॥ श्रीः ॥

तिलक-महाराष्ट्र-विद्यापीठशाखाभूत-
पुण्यपत्तनस्थ-वैदिक-संशोधन-मण्डलेन
प्रकाशिता

॥ ऋग्वेदसंहिता ॥

पदादिसूच्यात्मकः

पञ्चमो भागः

सोनटक्के इत्युपाह्वः श्रीपादसूनुः नारायणशर्मा
काशीकरोपाह्वो गणेशसूनुः चिन्तामणिशर्मा
इत्येताभ्यां संपादितः

शके १८७३

मूल्यं ५० रूप्यकाणि

Tilak Maharashtra Vidyapith
VAIDIKA SAṀŚODHANA MAṆḌALA
(*Vedic Research Institute*)
POONA

ṚGVEDA-SAṀHITĀ

VOL. V
INDICES

BY
N. S. Sontakke, B. A. (Tilak)
C. G. Kashikar, M. A. (Tilak)

1951

Price Rs. 50

PREFACE

We have great pleasure in bringing out the fifth volume of the Ṛgveda comprising the various indices. Really speaking the edition of Ṛgveda with Sāyaṇabhāṣya was completed by the fourth volume comprising Maṇḍalas IX and X with Sāyaṇabhāṣya which was published in 1946. Since, however, no edition can be said to be complete without the requisite indices so inevitable for a scientific study of the text concerned, the edition may aptly be said to be complete with this fifth volume. The publication of this volume was planned since the very beginning and it has been eagerly awaited by scholars. The demand was greater also on account of the fact that the indices were not available to scholars except those who possessed Prof. Max Müller's edition of Ṛgveda with Sāyaṇa's commentary. The Bombay edition of the Ṛgveda with Sāyaṇabhāṣya gave only the mantra-index. A Devanagari reprint of Max Müller's Word-index of the Ṛgveda was published by Swami Vishveshwarananda and Swami Nityananda. But it is also long out of print. The Vishveshwarananda Vedic Research Institute of Hoshiarpur, Punjab, has already planned the publication of a number of volumes giving word-indices of the entire Vedic literature and has even published a few volumes amongst which there is one (vol. I, part I) that gives a word-index of all the Saṁhitās. But it covers words beginning only with अ. Further volumes are still to be published. Under these circumstances the publication of this volume may, in our opinion, be considered as not only justified but essential.

The first volume of our edition was published in 1933, and now this fifth and last volume is being out in 1951, thus completing the edition in about a period of 18 years. The reasons for this length of period required for completing the edition in comparison with the other editions have already been discussed in the introduction to our fourth volume. On this occasion we feel it our pleasant duty to express our gratitude to the Almighty—the *Vedapuruṣa* for favouring us with the complete publication of the Ṛgveda—His *niśśvasita*, along with the materials necessary for its understanding.

As already said, the index-material is absolutely necessary for the scientific edition of any text and has to be collected and compiled before commencing the editing. For the purpose of our Ṛgveda edition, however, the indices prepared and published by Max Müller were already available. Hence the preparation of the word-index and other indices was not undertaken by us before editing the first volume, but was commenced after the fourth and last volume of the text and commentary was out. Naturally, for compiling the present volume, the indices published by Max Müller have been of immense help to us. We, therefore, gratefully express our indebtedness to him. The plan of this index-volume has been practically the same as that of Prof. Max Müller. His index-volume comprised the Sarvānukrama, index of Devatās, index of Ṛṣis, index of Pratīkas, word-index and *Uttarapadasūcī*. All these are included in the present volume also. We have commenced the volume with the word-

index only because it was prepared first of all. In addition to these, we have published the index of metres as is given at the end of the edition of Kātyāyana's Sarvānukrama edited by Prof. A. A. Macdonell. Besides, a word-index and a verse-index of the *Khilas* have also been incorporated here. The word-index of the *Khilas* is being published here for the first time. The verse-index of the same was first published by Dr. Scheftelowitz at the end of his *Apokryphen des Ṛgveda.*

It had been suggested to us to include some other indices also in this volume. For instance, some scholars proposed that we should publish an index of names of historical persons in the Ṛgveda and another of geographical names. But it was thought that the preparation of such indices would involve the interpretation of the Ṛgveda regarding which there is no unanimity amongst scholars. The last word with regard to the interpretation of the Ṛgveda has not yet been spoken. Until that any attempt to prepare such an index is bound to prove to be imperfect. It was reasonable, in our opinion, to publish only such indices regarding which there cannot be any point of dispute. Another suggestion made was to publish lists of passages or sūtras quoted from different works in Sāyaṇabhāṣya, such as Pāṇini's grammar, Yāska's Nirukta, Śaunaka's Bṛhaddevatā, Āśvalāyana Śrauta-sūtra and the various Brāhmaṇas. This, in our opinion, would involve much labour and additional expense without any material gain. In his commentary on the first Maṇḍala, Sāyaṇa has made a comprehensive attempt at explaining each and every word occurring in the Ṛgveda on the basis of Pāṇini's grammar and has, therefore, quoted the various sūtras often and often. Further he has left that practice considering that the elucidation made in the commentary on the first Maṇḍala covered practically everything. The same thing applies to other works also. Therefore, it did not matter much if a particular Sūtra of Pāṇini was found quoted in the commentary on a particular mantra.

With regard to the indices found in common with those in Max Müller it has to be noted at the outset that the indices printed in this volume are not a mere reprint of Max Müller. Each and every index has been independently worked out. The opportunity of comparing the index thus prepared with that of Max Müller has, of course, never been lost.

Of all the indices the word-index is the most extensive and also the most important. The *pada* as read in Padapāṭha has been taken as basis, just as Max Müller has done. A comparison of our word-index with that of Max Müller revealed that his index suffered from three types of imperfections: (1) Repetitions[1] in the Ṛgveda-padapāṭha are not recorded therein. The number of words omitted in this way is not small. This defect is probably due to the fact that his index was based either on some

1. On the repetitions cf. C. G. Kashikar, *The Problem of the Galantas in the Ṛgveda-padapāṭha*, Proceedings of the XIII th All-India Oriental Conference, Nagpur, 1946, pp. 39-46; *Repetitions in the Ṛgveda-Padapāṭha*, ABORI. XXVIII, parts iii-iv, pp. 301-5; Dr. C. K. Raja, *Ṛgveda Repetitions and the Padapāṭha*, Summaries of Papers, pp. 3-4. XIVth All-India Oriental Conference, Darbhanga, 1948.

MS of Ṛgveda-padapāṭha which invariably omits the repetitions or on a printed book of the same which also must have omitted the repetitions. There is evidently no reason in not recording a *pada* because it was omitted in traditional recitation of the Padapāṭha. (2) There are some omissions of words due to oversight. (3) In some cases either the reading or the accent is printed incorrectly. It is possible to collect all such irregularities in Max Müller's word-index, but it has not been thought expedient to do so here.

Regarding the place of ळ in the order of consonants an improvement over Max Müller was thought necessary. Max Müller has placed ळ after ल. Since, however, ळ is nothing but ड coming between two vowels (cf. ṚV-prāti. 1.52) we have treated it as ड itself. Maurice Bloomfield in his Vedic Concordance has also identified ळ with ड. In the Ṛgveda there are six mantras (7.59.12, 10.20.1, 121.10, 190. 1-3) which have no padapāṭha. The text and accent of *padas* in these verses have been adopted in consideration of similar *padas* occurring elsewhere in the Ṛgveda, e.g. the entire verse RV. 10.20.1 is repeated in 10.25.1. In case the *padas* were not found in the Ṛgveda, other Vedic texts and also grammar were consulted for the purpose. Max Müller has recorded *padas* from RV. 7.59.12 and 10.190.1-3, but not from 10.20.1, 121.10.

As regards the *Uttarapadasūcī* it may be pointed out that an attempt has been made to make it as comprehensive as possible. The principles underlying the compilation of the *Uttarapadasūcī* have been the same as those adopted by Max Müller. However, there is one more point. There are, in the Ṛgveda, a number of words consisting of more than two parts or *padas*. In such cases Max Müller has recorded that *uttarapada* which apparently was prominent. For example, अनुपऽक्षितं RV. 3.13.7; 10.101.5. Max Müller simply records क्षितं as an *uttarapada*. In fact there are three *padas* in that word, viz. अन्, उप and क्षितं; so both उप and क्षितं ought to be taken as *uttarapadas*, and we have recorded them accordingly. If it is necessary to record क्षितं, it is equally necessary to record उप also. Similarly, प्रतिऽआवर्तय RV. 6.47.31 where Max Müller records only आवर्तय while we have recorded वर्तय also. Sometimes a word comprises even four *padas*. In such case we have recorded all the three *uttarapadas*. e. g. अनिभृष्टऽतविषिः RV. 2.25.4; 5.7.7. This has been entered at three places, viz. at नि, भृष्ट and तविषिः. Words even with five *padas* are rarely met with. e. g. अदब्धव्रतऽप्रमतिः RV. 2.9.1.

After the *Uttarapadasūcī* the word-index for the *Khilas* has been printed. The *Khilas* had been printed in Vol. IV, pp. 891–1001. These were edited by Mr. C. G. Kashikar; so the work of compiling the *Khila* word-index was entrusted exclusively to him. The details about the same are given by him in an introductory note in Sanskrit to the index. As already said, the index is being printed here for the first time. As a result of the fresh study of the *Khilas* some modifications have been made in the text already printed. In such cases the readings in the printed text have

been recorded in foot-notes. However, there is still much scope for improving the text of the *Khilas*. The present index is only an attempt in that direction. It is hoped scholars will pay closer attention to the study of the *Khilas*.

A word by way of explanation is necessary as to why it was chosen to print a separate word-index for the *Khilas* instead of incorporating the same into the main word-index. There are certain reasons for doing so. The first is that just as the words from the main text are referred to by means of three figures denoting maṇḍala, sūkta and mantra respectively, similarly the *Khila*-words are referred to by three figures denoting the adhyāya, sūkta and mantra respectively. So it would have been necessary to attach some sign to them for distinguishing them from the ordinary words. Then there are certain hymns and verses which, being apocryphal, are kept outside the fold of the five adhyāyas of the *Khilas*. However, they have got some sort of tradition behind them and hence claim a place along with the others. It would have been necessary to distinguish words in them from those in the *Khilas* proper which means another complication. It would have been a disservice to the reader, had the words from the *Khilas* as well as from the apocryphal hymns and verses been allowed in the index without any sort of distinction. Such provisions would have made the matter rather clumsy. Another very important reason is that the system of accents adopted in printing the *Khilas* was different from the normal one. There the *udātta* was shown by a perpendicular stroke above the letter, just like the *svarita*. It was necessary to follow the same system in printing the *Khila* word-index. Had the *Khila* word-index with a different accent system been incorporated into the main index, the whole matter would have become useless. For these reasons it was thought convenient to print a separate word-index for the *Khilas*. It would be, we think, profitable to use the two indices separately.

After the verse-index of the Ṛgveda about which there is nothing worth special mention, there is the verse-index of the *Khilas*. The references are to chapter, hymn and verse. In the case of apocryphal or unauthorised hymns and verses the page-number is shown in brackets. In compiling the index of Ṛṣis the Sarvānukrama of Kātyāyana has always been consulted. For compiling the index of Devatās both the Sarvānukrama and Bṛhaddevatā have been consulted and the Devatās differently recorded in the Bṛhaddevatā have been noted in foot-notes. For this purpose the index of Devatās printed in Macdonell's well known edition of Bṛhaddevatā has also been used. One thing may be mentioned with regard to the entry of Devatās. There are certain hymns or verses which are treated in Sarvānukrama as *ātmastuti*[1]. In some of these cases (3.26.7–8;

1. Cf. Sarvā. 3.26 द्व्यृच आत्मस्तुतिर्वा ; 4.26 इन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानम् ; 4.42 षळाद्या आत्मस्तवः; 10.48–50 इन्द्रः...आत्मानमुत्तरैस्त्रिभिस्तुष्टाव ; 10.119 ऐन्द्रो लब आत्मानं तुष्टाव; 10.124.2–4 तिस्रश्चाग्नेरात्मस्तवः (according to Bṛhad. verses 1–4 are self-praise of Agni); 10.125 वागाम्भृणी तुष्टावात्मानम् ; 10.139.4–6 देवगन्धर्वो विश्वावसुरात्मानमस्तौत् ; 10.159 पौलोमी शच्यात्मानं तुष्टाव।

4.26. 1–3; 42. 1–6; 10.119) Max Müller has recorded *ātmā* or *paramātmā* as the deity of the hymn or verse. That he meant *soul* by the word *ātmā* is clear from his entry as "Brahma, *see* ātmā". In fact in such verses the Ṛṣi of the verse concerned praises *himself*, not *ātman* in the Vedantic sense. So we have given under the word *ātmā* cross-references to many of these Ṛṣis and have given the actual references under the respective names of the Ṛṣis themselves. After the Devatā-index comes the index of metres for which Macdonell's index added to the edition of Sarvānukrama has mostly been used. We acknowledge with thanks the help we received from the two monumental works of Prof. Macdonell, viz. Sarvānukrama and Bṛhaddevatā. Lastly comes the Sarvānukrama in which references according to the Maṇḍala enumeration and Aṣṭaka enumeration, *pratīka* of the hymn, number of verses in each hymn, Ṛṣi, Devatā, Cchandas and page-reference are given in tabular form.

Some explanation is necessary with regard to the figures placed both above the words as well as above the mantra-number in a reference, since they are used in different senses at different places. First of all, in the word-index it comes only at the top of the mantra-number and denotes the repetitions of the word concerned in that particular mantra. In the word-index of *Khilas* it occurs both above the word as well as the mantra-number. The figure above the word refers to the foot-note and the figure above the mantra-number denotes the repetitions of the word in that mantra as in the word-index. In the index of *Khila* verses it occurs above a word and refers to the foot-note. In the index of Devatās it comes both above a word as well as above a mantra-number. The number above a word refers to the foot-note and that on a mantra-number denotes the pāda of the mantra, sometimes even a half-verse. In the index of metres the number placed upon the mantra-number refers to the foot-note. In the Sarvānukrama given in tabular form a number is shown above the mantra-number in the column for deity and it denotes the pāda of that mantra, sometimes even a half-verse.

In spite of all possible care, a few mistakes have crept in the present volume. These are recorded below the contents. The reader is requested to refer to them and make corrections accordingly before using the book. There may be a few other minor mistakes, but they are easily comprehensible.

We have been compelled to enhance the price of this volume as compared to the previous volumes. When we published the fourth volume, the second world-war was just over; however, there was no improvement in the worse conditions already created. We then naturally expected that conditions will definitely ease by the time of the publication of the fifth volume. To our misfortune, however, the conditions not only did not ease but became still more difficult. In conformity with the very high prices in the market, the cost of printing rose considerably. An increase in the price, therefore, became inevitable for which we crave the indulgence of the reader. The extent of the volume is also partly responsible for the higher cost.

ACKNOWLEDGMENTS :—We have now to do the pleasant duty of acknowledging help that has been given to us in bringing out this volume. First of all, we have to express our deep sense of gratitude to the Government of Bombay for their deep sympathies for this work. Besides the annual recurring grant, the Government were pleased to sanction a non-recurring grant of Rs. 10,000 towards the publication of the present volume. The expenditure made on paper for this volume was fully met from this grant. We have also to express our gratitude to the Government of India, Government of Hyderabad, Government of Nepal, and the Governments of Uttar Pradesh, Bihar and Saurashtra for the liberal patronage given by them. Formerly we used to seek the patronage of Indian Princes who, we are proud to say, rose to the occasion and did whatever they could to help us financially. Since the attainment of Independence of India almost all the States have been merged with their neighbouring provinces. Naturally the moral responsibility to patronize such causes which ultimately lead to the cultural resuscitation of modern India, now lies with the Government of India and State Governments and we are glad to say that they are bearing it commendably. We are confident that efforts of this kind will be liberally patronized also in future. We have also to thank the Akhila Bharatiya Arya (Hindu) Dharma Seva Sangh, Delhi and its president Shriman Seth Jugal Kishore Birla under whose direction the Sangh has been liberally helping our Maṇḍala for the last few years. We are thankful to all our donors and sympathizers but for whose help it would not have been possible to undertake and continue the work on the various projects. To scholars and oriental journals we are thankful for their appreciation of the four volumes of our Ṛgveda edition already published. Our thanks are also due to the management of Messrs. Killick Nixon & Co. (The Indian Paper Sales Association), Bombay, for promptly procuring suitable paper for this volume. Last, but not the least, we must thank Mr. S. R. Sardesai, B.A., LL.B., Manager, Samarth Bharat Press, Poona, for the efficient and speedy printing of the present volume. It may be noted with pleasure that all the five volumes of our edition were printed at this press and we take this opportunity to express our appreciation for the hearty co-operation rendered by its staff all these years.

Now that the project of the publication of the Ṛgveda edition has fully materialized, we shall be free to devote our energies to the other projects already announced, viz. the edition of Kṛṣṇa Yajurveda Taittirīya Saṁhitā and the Śrautakośa. May the Almighty who graciously accredited us with the completion of the Ṛgveda edition also do us the favour of enabling us to go through these undertakings.

Lastly we beg to place this volume in the hands of students of the Veda and hope it will meet with their approval.

Vaidika Saṁśodhana Maṇḍala,
Poona, 15th August 1951.
Independence Day.

N. S. SONTAKKE
C. G. KASHIKAR

|| श्रीः ||

प्रास्ताविकम्

अथेममृग्वेदसंहितायाः पञ्चमं भागं विविधसूच्यात्मकं विदुषां करकमलेषु सादरं समर्पयितुं प्रमोदन्ते नश्चेतांसि। वस्तुतः सभाष्या ऋग्वेदसंहिता तु प्राङ्मुद्रितैश्चतुर्भिर्भागैरेव संपूर्णा। किंतु सूच्यादिसाधनैर्विना वेदाध्ययनस्य प्रायोऽशक्यत्वात् सूच्यात्मकेन पञ्चमभागेनैव सभाष्यस्यर्ग्वेदस्य मुद्रणं संपूर्णतां यातमिति वक्तुमुचितम्। अस्य भागस्य योजना प्रागेव सुनिश्चिताऽऽसीत् तदनुसारेण च चतुर्थभागप्रकाशनादनन्तरमस्य भागस्य प्रतीक्षा विद्वद्भिः क्रियते स्म। विशेषतश्च बहोः कालादारभ्य ऋग्वेदसूचीनामनुपलभ्यमानत्वादिमं भागं विद्वांसः शीघ्रमपेक्षितवन्तः। मॅक्समुल्लरमहोदयैः प्रकाशिते सभाष्यर्ग्वेदस्य पुस्तके पदादिसूच्यो मुद्रिता आसन्। मुम्बापुर्यां मुद्रिते सभाष्यर्ग्वेदपुस्तके केवलं मन्त्रसूच्येवासीत्। श्रीमद्भ्यां विश्वेश्वरानन्दनित्यानन्दस्वामिभ्यामृग्वेदसंहितायाः पदसूची प्रायो मॅक्समुल्लरसूच्यनुसारेण देवनागरीलिप्या मुद्रापिताऽऽसीत्। सापीदानीं नोपलभ्यते। होश्यारपूरनगरे विश्वेश्वरानन्द-वैदिकशोधसंस्थानेन सर्वस्य वैदिकसाहित्यस्य सूचीसंपादनं महतायासेनोपक्रान्तमस्ति। तत्र प्रथमे भागे वैदिकसंहितानां पदसूची मुद्रापिता परं सा केवलमकारादिपदानामेव। एवमस्य सूच्यात्मकस्य पञ्चमभागस्य प्रकाशनं न केवलमुचितं किंतु आवश्यकमिति सुस्पष्टम्।

ऋग्वेदसंहितायाः प्रथमो भागः १९३३ खिस्ताब्दे प्रकाशित आसीत्। अयं च पञ्चमो भाग इदानीं १९५१ खिस्ताब्दे प्रकाश्यते। एवं विंशतिवर्षाभ्यन्तर इदं पुस्तकं संपूर्णं प्रकाश्यतां गतम्। पूर्वं मुद्रितानां सभाष्यर्ग्वेदपुस्तकानामपेक्षयास्य पुस्तकस्य प्रकाशनकालावधिविषये चतुर्थभागप्रास्ताविके कारणादिविचिकित्सा कृतैवास्ति। अतो नात्र तद्विषये पुनरुच्यते। यस्य कृपाप्रसादलेशेनेदं तस्यैव निःश्वसितस्वरूपायाः सायणभाष्यसहिताया ऋग्वेदसंहितायाः प्रकाशनं निर्विघ्नं समाप्तिं गतं तं परमात्मानमभिवादयामहे।

सूच्यादीनां ग्रंथसंपादनार्थमत्यन्तमावश्यकत्वात् तासां विरचनं ग्रन्थस्य मुद्रणात् प्रागेव कार्यमिति सामान्यो नियमः। अस्माभिस्तु संपूर्णस्य ग्रन्थस्य मुद्रणानन्तरं तत्कृतम्। अत्रेदं समाधेयं यत् अस्मद्ग्रन्थसंपादनकार्यार्थमावश्यकानि सूच्यादिसाधनानि मॅक्समुल्लर-महोदयैः प्रकाशितान्यस्मभ्यमुपलब्धान्यासन्नेव। तेन संहिताभाष्यमुद्रणानन्तरं सूच्यादिसंपादनेन न कापि हानिः संजाता न वा भाष्यसंपादने न्यूनतावशिष्टा। अस्मिन् ग्रन्थे मुद्रितानां सूचीनां संपादनार्थं मॅक्समुल्लरसंपादितानां सूचीनां नितरामुपयोगः संजात इति तेषामुपकारा अवश्यं स्मर्तव्याः। मॅक्समुल्लरपुस्तके याः सूच्यो मुद्रिताः न केवलं तावत्य एवात्र प्रकाशिताः, किंतु काश्चन ततोऽप्यधिकाः। छन्दःसूची, खिलपदसूची, खिलमन्त्रसूची चेत्येता अत्र मुद्रिताः सूच्यो मॅक्समुल्लरपुस्तके न सन्ति। एतासु खिलपदसूची तु प्रथममेव संपाद्य मुद्यते।

अस्मिन् पुस्तके याः सूच्यो मुद्रितास्तदपेक्षयाधिकाः काश्चन सूच्योऽत्रान्तर्भावयितव्या इति कैश्चन सूचितमासीत्। ऋग्वेदोल्लिखितैतिहासिकपुरुषाणां तथा च नगरपर्वतनद्यादिकानां शब्दसूची देयेति केनचनोक्तम्। किंतु ऋग्वेदसंहिताया अर्थज्ञानविषये सर्वेषां विदुषामैकमत्य-राहित्यादेतादृशी शब्दसूची निर्दुष्टा पूर्णा च न भवेत्। यतः एकस्य मते कश्चन शब्द ऐतिहासिक-

पुरुषवाचकः स्यादन्यस्य मते तु न स्यात्। नदीपर्वतादिविषयेऽपि सैवापत्तिः। अस्माभिस्त्वेतत् सुनिश्चितमासीत् यत् केवलं विवादातीताः सर्वथा पूर्णाः सूच्य एवात्र समावेशनीया इति। अन्यः कश्चन सूचितवान् यत् पाणिनियास्कादीनां ग्रन्थेभ्यो यानि वचनानि सायणभाष्य उद्धृतानि तेषां सूची मुद्रणीयेति। एतत्स्वीकरणे महान् परिश्रमः द्रव्यव्ययश्चावश्यकः स्यात्, न च तावान् लाभः। सायणाचार्यैः प्रथममण्डले प्रतिपदं व्याकरणप्रक्रियादि प्रोच्य विस्तृतं भाष्यं व्यरचि, न तथाग्रिमेषु भागेषु, सर्वेषां पदानां प्रायः पूर्वमेव स्पष्टीकृतत्वात्। अतः अमुकमन्त्रस्य सायणभाष्ये अमुकं पाणिनिसूत्रमुद्धृतमिति ज्ञानेन न कोऽपि लाभः संजायेत। एतदवधार्य उपर्युक्तानां सूचीनां विरचनविषयेऽस्माभिर्मतिर्न कृता।

यद्यपि मॅक्समुल्लरपुस्तकस्थाः सर्वा अपि सूच्योऽत्र प्रतिदृश्यन्ते, तथापीदं सर्वथावधेयं यदत्र मुद्रिताः सूच्यो न मॅक्समुल्लरसूचीनां प्रतिकृतय इति। एताः सर्वा एव सूच्यो नूतनतया संपादिताः। मॅक्समुल्लरसूचीभिस्सह तासां तुलना कृता इति तु अकथयित्वैव स्पष्टम्।

सर्वासु सूचीषु पदसूची सर्वथा प्राथम्यमर्हति। अस्याः संपादने पदपाठगतं पदमेव प्रमाणत्वेन स्वीकृतम्। मॅक्समुल्लरपदसूच्यां काश्चन त्रुटय उपलभ्यन्ते ता दूरीकर्तुमत्र प्रयत्नः कृतः। पदपाठे यानि 'गलितानि' पदानि भवन्ति तेषां तत्राभावो दृश्यते। पदपाठस्य लिखित-पुस्तकानुसारेण पदपाठानुसारिमुद्रितपुस्तकसाहाय्येन वा सा पदसूची संपादिता स्यादित्यनु-मीयते। एवमनिर्दिष्टानां पदानां संख्या नाल्पा। 'गलितानाम्' अपि पदानां सूच्यां समावेश आवश्यक एव। कानिचित् पदानि दृष्टिदोषादनिर्दिष्टानि। केषुचित् पदेष्वक्षराणि स्वरो वाऽशुद्धं मुद्रितः। एतादृशानां सर्वेषां प्रमादानां परिगणनं संग्रहणं च कर्तुं शक्यं, परं न तदत्र कर्तु-मिष्यते। व्यञ्जनक्रमविषये मॅक्समुल्लरपुस्तकापेक्षया एकत्र परिवर्तनं कृतं तदवधारणीयम्। मॅक्समुल्लरपुस्तके 'ल'कारानंतरं 'ळ'कारं स्थापयित्वा सूच्यः संपादिताः। किंतु 'द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः' (१.५२) इति ऋक्प्रातिशाख्यसूत्रानुसारेण ळकारस्य डकाररूपत्वात् अस्माभिः ळकारस्य डकार एव परिगणना कृता। ब्लूमफील्ड्महोदयानां वैदिकपादसूचीग्रन्थेऽपि डकारळकारयोः समानरूपत्वमेवाङ्गीकृतम्। ऋग्वेदसंहितायां षण्णां मन्त्राणां (७.५९.१२; १०.२०.१; १२१.१०; १९०.१–३) पदपाठो नास्ति। अत्रस्थानि पदानि ऋग्वेदस्थानां समानपदानामनुसारेण स्वीकृतानि। ऋग्वेदेऽनुपलब्धानि चेत् वेदान्तरं व्याकरण-शास्त्रं वाऽनुसृत्य तेषां पाठः स्वरश्च स्वीकृतौ। मॅक्समुल्लरपुस्तके १०.२०.१; १२१.१० इत्येतयो-र्मन्त्रयोः पदानि नोपलब्धानि।

पदसूच्यनन्तरमुत्तरपदसूची प्रदत्तास्ति। तस्याः परिपूर्णत्वविषये यावच्छक्यं प्रयतितम्। उत्तरपदसूची इति संज्ञायां पदशब्दस्य यल्लक्षणं मॅक्समुल्लरमहोदयैः स्वीकृतं तदेवात्रापि। किंत्वेको विशेषः। ऋग्वेदे कानिचित्पदानि त्र्यवयवानि चतुरवयवानि पञ्चावयवानि वोपलभ्यन्ते। एतादृशेषु पदेषु यः प्रमुख उत्तरावयवः स एव उत्तरपदमिति कृत्वा मॅक्समुल्लरसूच्यां स्वीकृतः। यथा 'अनुपऽक्षितं' ऋ. सं. ३.१३.७; १०.१०१.५। अत्र 'क्षितं' इत्युत्तरपदं मॅक्समुल्लरपुस्तके स्वीकृतम्। 'क्षितं' पदस्योत्तरपदत्वं सिद्धमेव, किंतु 'अनुप' इत्यवशिष्टपदभागे 'अनू' इत्यस्य पूर्वपदत्वात् 'उप' इत्यप्युत्तरपदत्वेन स्वीकर्तव्यम्। अतोऽस्माभिः 'उप' 'क्षितं' इत्युभे अपि पदे उत्तरपदत्वेन प्रदत्ते। तथा च 'प्रतिऽआवर्तय' ऋ. सं. ४.४७.३१ अत्र 'आवर्तय' इत्युत्तरपदं विद्यते एव। तथापि 'वर्तय' इत्यप्यस्माभिरुत्तरपदत्वेन दर्शितम्। एवम् 'अनिभृष्टऽतविषिः' ऋ. सं. २.२५.४; ५.७.७, 'अदब्धव्रतऽप्रमतिः' ऋ. सं. २.९.१ इति क्रमेण चतुर-वयवस्य पञ्चावयवस्य चोदाहरणे।

उत्तरपदसूच्या अनुपदं खिलपदसूची विनिवेशितास्ति। अस्मत्प्रकाशिताया ऋग्वेदसंहितायाश्चतुर्थे भागे ८९१–१००१ पृष्ठेषु यानि खिलानि मुद्रितानि तेषामियं पदसूची भवति। तानि श्रीमद्भिः चिं. ग. काशीकरमहोदयैः संपादितान्यासन्। अतः खिलपदसूच्याः संपादनमपि तैरेव कृतमस्ति। खिलपदसूचीविषये यत् किंचिन्निवेदनीयं तैरेव सूच्या आरम्भे प्रास्ताविके निवेदयिष्यते। खिलानां पदसूच्यत्र प्रथममेव मुद्राप्यते। तस्या विरचनप्रसङ्गेन खिलानां मुद्रितपाठविषये केचन अभ्यूहाः कर्तव्या आसन्। एतादृशेषु स्थलेषु नूतनान् पाठान् सूच्यां दत्वा मुद्रितपाठाः टिप्पणीषु दर्शिताः। पाठशोधनार्थं बहु प्रयतितेऽपि किंचिन्न्यूनत्वमवशिष्टमेव। तस्य पूरणे विद्वांसः प्रयतेरन्नित्याशास्महे।

अत्रेदं शङ्क्येत यत् सत्यामेव पदसूच्यां किमर्थं खिलानां स्वतन्त्रा पदसूची विनिर्मितेति। तत्रेदमुच्यते। ऋग्वेदपदानि मण्डलसूक्तमन्त्रात्मिकाभिस्तिसृभिः संख्याभिः प्रदर्शितानि। खिलेष्वपि अध्यायसूक्तमन्त्रा इति संख्यानां त्रित्वं विद्यत एव। तेन सखिलस्य ऋग्वेदस्य पदसूच्यां विरचनीयायां खिलत्वप्रतीत्यर्थं खिलपदे किंचिच्चिह्नमावश्यकं भवेत्। अपरं च खिलेषु कानिचन सूक्तानि केचन मन्त्राश्च अध्यायपञ्चकाद्बाह्या अत एव प्रक्षिप्ता भवन्ति। तद्गतानामपि पदानां पदसूच्यां समावेश आवश्यक एव। एतेषां पदानामपि खिलपदेभ्यो भेदज्ञापनमपरिहार्यमेव। एवं खिलपदानां प्रक्षिप्तखिलपदानां च पृथक्त्वसंपादनार्थं कस्यामपि योजनायां कृतायां पदसूच्यवलोकनं दुष्करमभविष्यत्। अन्यच्च। मुद्रितखिलेषु स्वरविषयेऽन्या रीतिरवलम्बिताऽऽसीत्। तत्र उदात्तस्वरः प्रदर्शितः, सोऽपि स्वरितचिह्नवदुपरितनया रेखया। इयमेव स्वरप्रदर्शनपद्धतिः खिलपदसूच्यामप्यपरिहार्यासीत्। एवमेकस्यामेव पदसूच्यां स्वरविषये रीतिद्वयस्यावलम्बनेऽव्यवस्था प्रसज्येत। एतदर्थं खिलपदसूची स्वतन्त्रतयोपन्यस्ता। तच्च विदुषां लाभायैव स्यादित्याशास्महे।

खिलपदसूच्यनन्तरं मन्त्रसूची स्थापितास्ति। इयं बहुषु पुस्तकेषु पूर्वं मुद्रितापि अत्रास्याः समावेश आवश्यको मतः। समनन्तरमेव खिलमन्त्रसूची दीयते। तत्राध्यायसूक्तमन्त्राणां संख्या दर्शिताः। प्रक्षिप्तमन्त्राणां संख्यास्तु पृष्ठानि बोधयन्ति पृथक्त्वबोधनार्थं च ताः कोशेषु स्थापिताः। ऋषिसूच्यां देवतासूच्यां च प्रदत्तानि ऋषिनामानि देवतानामानि कात्यायनीयसर्वानुक्रममनुसरन्ति। शौनकीयबृहद्देवतायां देवतानां प्रकथनं क्वचित् सर्वानुक्रमात् विभिन्नमस्ति। अयं भेदो देवतासूच्यामधस्तनटिप्पणीषु प्रदर्शितः। देवतानिर्देशविषयेऽयं विशेषः। सर्वानुक्रमे क्वचनात्मस्तुतिवाचकानि सूत्राण्युपलभ्यन्ते यथा 'तृच आत्मस्तुतिर्वा' (ऋ. ३.२६), 'इन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानम्' (४.२६), 'षळाद्या आत्मस्तवः' (ऋ. ४.४२), 'इन्द्रः...आत्मानमुत्तरैस्त्रिभिस्तुष्टाव' (१०.४८–५०), 'ऐन्द्रो लव आत्मानं तुष्टाव' (ऋ. १०.११९), 'तिसृभिश्चाग्नेरात्मस्तवः' (१०.१२४.२–४), 'वागाम्भृणी तुष्टावात्मानं' (ऋ. १०.१२५), 'देवगन्धर्वो विश्वावसुरात्मानमस्तौत्' (ऋ. १०.१३९.४–६), 'पौलोमी शच्यात्मानं तुष्टाव' (ऋ. १०.१५९) इति। एषु मध्ये केषुचित् स्थलेषु मॅक्समुल्लरसूच्याम् 'आत्मा', 'परमात्मा' वेति देवता निर्दिष्टा। वस्तुतो नात्रात्मनो नाम जीवस्य ब्रह्मणोऽथवा स्वरूपस्य स्तुतिरभिप्रेता किंतु तत्तन्मन्त्रस्यर्षिः स्वयमात्मानमुद्दिश्य ब्रवीति स्तौति वा। अतोऽस्माभिः 'आत्मा' इति स्थले तत्तेषामृषीणां नामान्युल्लिखितानि, ऋषीणां निर्देशस्थलेषु च तेषां तेषां मन्त्राणां संख्याङ्का विनिवेशिताः। प्रो. मॅक्डोनल्महोदयैः संपादितस्य सर्वानुक्रमग्रन्थस्यान्ते या ऋग्वेदसंहितायाश्छन्दःसूची मुद्रिता तामनुसृत्यात्र छन्दःसूची दत्तास्ति। मॅक्डोनल्संपादितस्य सर्वानुक्रमस्य बृहद्देवतायाश्च थ उपयोगोऽस्माभिः कृतः तदर्थं तेषामुपकारं

स्मरामः । अन्ते च सर्वानुक्रमो मुद्रितोऽस्ति यत्र मण्डलगणनयाष्टकगणनया च सूक्तानां संख्या सूक्ते मन्त्रसंख्या ऋषिच्छन्दोदेवता इत्यादिकं सर्वं कोष्ठकेषु प्रदीयते ।

अस्मिन् ग्रन्थे क्वचन शब्दानामुपरि क्वचन मन्त्राङ्कानामुपरि येऽङ्काः स्थापितास्तेषां विषये किंचित् स्पष्टीकरणमावश्यकम्। तत्र तावत् पदसूच्यां मन्त्राङ्कस्योपरि योऽङ्को निवेशितः स तस्य पदस्य तस्मिन् मन्त्रे तावत्संख्याकामावृत्तिं द्योतयति । खिलपदसूच्यां शब्दस्योपरि वर्तमानोऽङ्कोऽधस्तनटिप्पण्याः संबन्धं दर्शयति, मन्त्राङ्कस्योपरि वर्तमानश्च पूर्ववत् तस्य पदस्य तस्मिन्मन्त्रे आवृत्तिं बोधयति । खिलमन्त्रसूच्यां शब्दस्योपरि दृश्यमानोऽङ्कोऽधष्टिप्पणीं ज्ञापयति । देवतासूच्यां शब्दस्योपरिदत्तेनाङ्केनाधस्तलटिप्पणी द्योत्यते, मन्त्राङ्कस्योर्ध्वं स्थापितेनाङ्केन च तस्य मन्त्रस्य पादः क्वचनार्धर्चोऽपि बोध्यते । छन्दसूच्यां मन्त्राङ्कस्योपरि निवेशितोऽङ्कोऽधष्टिप्पणीं दर्शयति । सर्वानुक्रमे मन्त्राङ्कस्योपरि दत्ता संख्या तस्य मन्त्रस्य पादं क्वचनार्धर्चमपि बोधयति ।

एवं महता श्रमेण संपादितेऽप्यस्मिन् ग्रन्थे बहवो दोषाः मानवसुलभप्रमादान्मुद्रणवशाद्वा जाताः स्युः । तत्र ये गुणास्ते पूर्वेषां विदुषां, ये दोषास्ते त्वस्माकमिति साञ्जलिबन्धं स्वीकुर्मः । अत्रोपलभ्यमाना दोषा विद्वद्भिः क्षन्तव्या निवेदनीयाश्च । अस्मद्दृष्टिपथमायाताः काश्चनाशुद्धयः विषयानुक्रमण्या अधस्तात् प्रदर्शिताः । तत्रस्थान् शुद्धान् पाठान् तत्तत्स्थलेषु विनिवेश्य पुस्तकमुपयोज्यमिति प्रार्थयामहे ।

पूर्वप्रकाशितपुस्तकापेक्षयास्य भागस्य मूल्यमधिकतरं निर्धारितं तत्र परिस्थितिरेव कारणम् । चतुर्थभागप्रकाशनसमये विश्वव्यापि महायुद्धमचिरादिव समाप्तमासीत् । परं युद्धजनितमहार्घता न लेशतोऽपि न्यूना अभवत् । तदास्माकमाशा आसीद्यत् पञ्चमभागप्रकाशनसमये एतादृशी परिस्थितिर्न भवेत् । किंतु दुर्भाग्यवशात् न तत्र किमपि सौलभ्यं संजातं प्रत्युत महार्घता परां कोटिं गता । तदनुसृत्य मुद्रणमपि महार्घं जातम् । तेनास्य ग्रन्थस्य मूल्याधिक्यमावश्यकमभूदिति सुधीभिः क्षन्तव्यम् ।

धन्यवादवितरणम्—अस्य ग्रन्थस्य संपादनार्थं प्रकाशनार्थं च यैः सज्जनैर्विविधं साहाय्यमाचरितं तेभ्यः सर्वेभ्य इदानीं सामोदं धन्यवादान् वितरामः । प्रथमतस्तावत् मुम्बापुरीराज्यशासनाधिकृतानां कृतज्ञतां प्रदर्शयामहे । एतैर्महाभागैर्वार्षिकं द्रव्यसाहाय्यं तु क्रियत एव, किंतु ततोऽप्यधिकमस्य ग्रन्थस्य प्रकाशनाय दशसहस्ररूप्यकाणि प्रदत्तानीत्यहो तेषामौदार्यम् । एतद्ग्रन्थस्य कृते आवश्यकानि पत्राण्यनेनैव द्रव्येण संपादितानि । भारतशासनाधिकारिभिरस्मिन्नेव संवत्सरे य आश्रयः प्रदत्तस्तदर्थं ते धन्यवादार्हाः । तेषामाश्रयः प्रतिसंवत्सरं नियतं प्राप्तो भवेदित्यस्माकं बलवती आशा । तथा च नेपाल–हैद्राबाद–उत्तरप्रदेश–बिहार–सौराष्ट्र–प्रशासकैरपि स्वकीयमौदार्यं प्रकटितं तदर्थं तेषामुपकारमरान् शिरसि वहामः । भारतीयस्वातन्त्र्यप्राप्तेः पूर्वमेतस्मिन्देशे ये संस्थानाधिपतयः प्राशासुः तेभ्यः कालेकाले पर्याप्तं साहाय्यं अस्माभिः प्राप्तं यदर्थं तेषामुपकारस्मरणमावश्यकम् । इदानीं स्वातन्त्र्यप्राप्तेरनन्तरं तेषां राज्यानि समीपवर्तिषु प्रदेशराज्येषु विलीनानि । तेन संस्थानाधिपतिभिः क्रियमाणं ग्रन्थप्रकाशनसाहाय्यात्मकं कार्यं तेषां तेषां प्रदेशराज्यप्रशासकानामुपरि क्रमेणैवापतति । इदं च परमं प्रमोदस्थानं यत् प्रदेशप्रशासकैः भारतप्रशासकैश्चायं भारः स्वीय इत्युररीक्रियत इति । दिल्ली नगरस्थ—अखिलभारतीयार्यधर्मसेवासंघेन एतावत्कालपर्यन्तं यत्साहाय्यमविरतं कृतं तदर्थं तस्य संघस्य, विशेषतस्तस्याध्यक्षमहोदयानां श्रीमतां जुगलकिशोर–बिडलामहोदयानां

कृतज्ञतां प्रकटीकुर्मः । अन्यैश्चोदारधीभिः समयेषु यत्साहाय्यं कृतं तदर्थं ते सर्वेऽपि धन्यवादार्हाः । सभाष्याया ऋग्वेदसंहितायाश्चतुर्षु भागेषु स्वकीयान् सदभिप्रायान् प्रकटीकृतवतां विदुषामुपकारा अप्युल्लेखनीयाः । श्रीमद्भिः किलिक्-निक्सन्-कंपनीप्रशासकैरस्य ग्रन्थस्य मुद्रणार्थमावश्यकानि पत्राणि संपाद्य दत्तानीति तेभ्यो धन्यवादान् वितरामः । अस्य ग्रन्थस्य शुद्धे शोभने च मुद्रणे कृतभूरिपरिश्रमाणां श्रीमतां स. रा. सरदेसाईमहोदयानां समर्थ-भारत-मुद्रणालयाधिकृतानां साहाय्यमविस्मरणीयमेव । ऋग्वेदसंहितायाः सर्वेऽपि भागा एतेषामेव मुद्रणालये मुद्रिता इत्यवश्यमुल्लेखनीयम् । मुद्रणालये कार्यं कुर्वद्भिः सेवकैः कृतस्य सहयोगस्य स्मरणमस्मिन्नवसरे धन्यवादपूर्वकं कुर्मः ।

एवमृग्वेदसंहितायाः सभाष्यायाः प्रकाशनकार्यं परमेशप्रसादात् समाप्तवतामस्माकमिदानीमन्येषु प्रागेवाङ्गीकृतेषु कार्येषु प्रवृत्तिः सुलभा । सायणाचार्याणां तथा च भट्टभास्करमिश्राणां भाष्यद्वयेन युतायास्तैत्तिरीयसंहितायाः कृष्णयजुर्वेदीयायाः संपादनं तथा च श्रौतकोशसंज्ञकस्य यज्ञधर्मविषयकस्य महतो ग्रन्थस्य विरचनमिति द्वे कार्ये पूर्वमेवारब्धे । यथेदमृग्वेदप्रकाशनकार्यं श्रीशकृपया विदुषामाशीर्भिश्च संपूर्णतां गतं तथैवास्य ग्रन्थद्वयस्यापि प्रकाशनमस्मन्मण्डलद्वारा समाप्तिं यायादिति तं भगवन्तं विद्यातीर्थमहेश्वरं पुनः पुनः प्रार्थयामहे ।

अन्ते चायं भागो विदुषां तोषाय स्यादित्याशास्महे ।

वैदिक-संशोधन-मण्डलम्
पुण्यपत्तनम्
भारतीयस्वातन्त्र्यदिनम्
शके १८७३

ना. श्री. सोनटक्के
चिं. ग. काशीकर

विषयानुक्रमणी

शुद्धिपत्रम्

[इदं शुद्धिपत्रमनुसृत्य अशुद्धं पदं तत्तत्स्थानान्निष्कास्य शुद्धं पदमावश्यकतानुसारमुचितस्थले स्थापनीयम् ।]

पृष्ठे	स्तम्भे	अशुद्धम्	शुद्धम्
८८	१	अस्मे	अस्मै
९५	१ (३४ पङ्क्तौ)	३२.४;	३२.४; ३३.३;
११२	१	आहुः (१०.१२१.४)	आहुः
१६६	१	एषे (५.४१.७)	आ । हुषे
१८२	१	कृष्णयामम्	कृष्णऽयामम्
२४६	२	तरुषसा	तरूषसा
२६३	२	त्रिधातुऽशृङ्ग	त्रिधातुऽशृङ्गः
२६६	१	त्वम् (१०.८५.२६)	त्वम्
३३८	१	निऽशिषत्	निऽशिषत्
३४३	२	पृक्षः	पृक्षः
३७६	१	पुष्यम्	पुष्पम्
४२४	२	मुश्रा	मुश्रा
५४५	१	विप्राः (७.४३.१)	विप्रा
६०६	१	सुम्राः	सुम्रा
८२७	२	परान्	पराक्
८५६	१	शिवासः	अशिवासः
१०३७	२	शसीयसी	शशीयसी

॥ श्रीः ॥

सादरं समर्पणम्

भासा यस्य विभाति विश्वमखिलं प्रोतं च यस्मिन्निदं
निःश्वासाः श्रुतयश्च यस्य तनुते यो भूर्भुवः स्वस्ततः ।
निष्प्रत्यूहमियं यदीयदयया प्राप्ता कृतिः पूर्णतां
विद्यातीर्थमहेश्वराय सततं तस्मै नमः सादरम् ॥ १ ॥

आर्षो यः खलु वेदमन्त्रनिवहः प्रायोऽप्यसौ दुर्गमः
शाकल्योऽत्र 'पद'-क्रमं रचितवाँल्लोकोपकृत्यै सुधीः ।
मन्त्रब्राह्मणविस्तरेण सुगमो यैरर्थमार्गः कृतो
वन्द्यास्ते खलु मन्त्रबोधनपराः शाङ्खायनाद्याः सदा ॥ २ ॥

दुर्बोधांश्च निसर्गतः श्रुतिगतानादाय मन्त्रान् पृथक्
तेषामर्थविबोधनं निगममाधैर्यत्नतः साधितम् ।
यास्काचार्यमुखा निरुक्तिनिरता वेदार्थसंदर्शिनो
धन्यास्तेऽपि निरुक्तकारविबुधास्तेभ्यो नमः सर्वदा ॥ ३ ॥

प्राचीनैरुपदर्शिते निजदृशं संस्थाप्य दीपेऽचलां
ये वेदाब्धिषु निर्भयं समचरन् भाष्योडुपैः पण्डिताः ।
प्रामुख्यं किल तेषु बिभ्रति च ये तान् सायणार्यान् मुदा
आम्नायार्णवकर्णधारधिषणान् दिक्षु श्रुतान् संस्तुमः ॥ ४ ॥

वेदाभ्यासपरंपरा नवयुगे शार्मण्यदेशागतै-
र्लोकेऽस्मिन् खलु मोक्षमुल्लरमहाभागैः स्वयं निर्मिता ।
श्रीमत्सायणसूरिभाष्यसहितम् ऋक्संहितामुद्रणं
लोकेऽभूद्यदुपज्ञमेव विमलं तेभ्यो महद्भ्यो नमः ॥ ५ ॥

* * *

पदसूच्यादिभिर्युक्तो वेदाभ्यासोपकारकः ।
अर्प्यते पञ्चमो भागस्तेष्वाचार्येषु सादरम् ॥ ६ ॥

॥ श्रीः ॥

अकारादिवर्णक्रमेण ऋग्वेदपदसूची

अ

अंशः २.१.४; २७.१; ५.४२.५; ७.३२.१२

अंशम् १.१०२.४; २.१९.५; ३.४५.४

अंशवः ८.९.१९; ५३.४

अंशवे १.४६.१०

अंशाऽइव ५.८६.५; १०.१०६.९

अंशाः १०.३१.३

अंशाय १.११२.१

अंशुः ३.३६.६; ४.२२.८; ५.४३.४; ९.६२.४; ६८.४; ७४.२; ५; ८९.६; ९१.३; ९२.१; १०.१७.१२; १३; ९४.१०

अंशुना ४.५८.१

अंशुऽभिः १.९१.१७; ९.१५.५; ६७.२८

अंशुम् १.१३७.३; ३.३६.७; ४.२६.६; ५.३६.१; ६.१७.११; २०.६; ७.९८.१; ८.५.२६; ७२.२; ९.६८.६; ७२.६; ८६.४६; ९५.४; ९७.१४; १०.९४.९; ११३.२; १४९.५

अंशुऽमतीम् ८.९६.१३

अंशुऽमत्याः ८.९६.१४; १५

अंशोः १.१२५.३; २.१३.१; ३.४८.२; ४.१.१९; २५.३; ९.९६.८; १०७.१२; १०.९४.८

अंसत्रऽकोशम् १०.१०१.७

अंसत्रम् ८.१७.१४

अंसत्रा ४.३४.९

अंसयोः ५.५७.६

अंसाभ्याम् १०.१६३.२

अंसेषु १.६४.४; १६६.९; १०; १६८.३; ५.५४.११; ७.५६.१३

अंसौ १.१५८.५

अंस्याः १.१९१.७

अंहः १.४२.१; २.२३.४; ५; २८.६; ३३.२; ३४.१५; ३.१५.३; ५९.२; ४.२.९; ३.१४; ११.६; १२.६; २०.९; ५.३१.१३; ४५.११; ६.२.४; ३.१; २; ४.८; ११.६; ३७.४; ४४.१६; ६७.८; ७.४०.४; ६०.६; ६६.५; ८२.७; ८.१९.६; ९.१०४.६; १०.३५.१४; ३९.११; ६३.६; १२६.१; ८

अंहःऽमुचम् १०.६३.९

अंहःऽयुवः ५.१५.३

अंहतिः १.९४.२; ८.७५.९

अंहतिऽभ्यः ५.५५.१०

अंहतिम् ८.६७.२; २१

अंहसः १.१८.५; ३६.१४; ५८.८; ९; ९१.१५; ९३.८; १०६.१–६; ११५.६; ११७.३; ११८.८; १३६.५[२]; १८०.५; २.२६.४; ३३.३; ३.३२.१४; ४.२.८; ५३.६; ५५.५; ५.५१.१३; ६.१६.३०; ३१; ४८.८; ७.१.१५; १५.३; १३; १५; १६.१०; ७१.५; १०४.२३; ८.१८.६; १०; २४.२७; ३१.२; ९.५६.४; १०.२४.३; २५.८; ३६.२; ३; ५३.५; ६५.१२; ६६.५; ९७.१५; १२६.२; १३२.७[२]; १६४.४

अंहसि १.५४.१

अंहांसि ६.२.११; १४.६; ७.२३.२

अंहुरः १०.५.६

अंहुरणा ६.४७.२०

अंहुरणात् १.१०५.१७

अंहोः १.६३.७; १०७.१; २.२६.४; ५.६५.४; ६७.४; ८.१८.५; ६७.७

अकः ५.८३.१०; ७.७७.१; ८.७३.१६

अकः १.२४.८; १२३.७; ४.१८.५; ७.७६.१; १०.५३.३[२]; ६७.४

अकनिष्ठासः ५.५९.६; ६०.५

अकरम् ८.८०.१; १०.४९.६

अकरम् १.११४.९; १०.४९.५; ८५.१७ १२४.४; १२७.८; १६७.४;

अकरित्यकः २.१२.४

अक्तम् २.३.४; ४.२७.५; ९.७४.८; १०.१७७.१
अक्तवः १०.३.४; ८९.१५
अक्तवे १०.४०.५
अक्ता १.६२.८
अक्तुः १.१४३.३; २.३०.१
अक्तुना २.१०.३; १९.३
अक्तुऽभिः १.३४.८; ३६.१६; ४६.१४; ५०.२; ७; ९४.५; ११२.२५; ३.१७.१; ३१.१६; ४.५३.१; ३; ५.४८.३; ८४.२; ६.६९.३; ९.५०.५; १०.१४.९; ३७.९
अक्तुऽभ्यः १०.८९.११
अक्तुम् ७.६६.११; १०.६४.३; ९२.२
अक्तुषु ८.९२.३१
अक्तून् १.६८.१; ५.५४.४; ६.४.५; ३९.३; ६५.१; ७.७९.२; ८.५.८; १०.१.२; १२.७
अक्तोः ३.७.६; ३०.१३; ४.१०.५; ५.३०.१३; ६.३.३; ५; २४.९; ३८.४; ७.११.३; ३९.२; १०.९२.१; १४
अक्तौ ६.४९.१०
अक्रः १.१४३.७; १८९.७; ३.१.१२; ४.६.३
अक्रत ८.६.३; २३.१८; १०.१.३; ३४.५; ७१.२
अक्रत १.२०.४; ६४.५; ९२.१; ५.२१.३; ७.१०३.८; ८.६५.१२; ९.२१.७; १०.६२.७; ६६.१४; ९४.५; १४; १५५.५
अक्रतुः १०.८३.५
अक्रतून् ७.६.३
अक्रन् १.९२.२; ४.३३.२
अक्रन् १.३३.१५; ६१.१६; २.३९.८; ३.३०.२०; ३५.८; ५०.४; ५.३०.१२; ५९.१; ६.२८.१; ४४.८; १०.१४.९; १२८.९
अक्रन्दः १.१६३.१
अक्रन्दत् १०.४५.४
अक्रन्दयः ९.५४.१
अक्रन्दयन् १०.१०२.५
अक्रपिष्ट ७.२०.९
अक्रमिषम् १०.९५.२
अक्रमीः १०.६०.६
अक्रमीत् ९.११४.१
अक्रमीत् ४.१५.३; ६.५९.६; ९.३६.१; ४०.१; ४५.४; ६४.२९; ६९.४; ७४.८; ८६.१४; १०८.२; १०.१८९.१
अक्रमीम् १०.१६६.५
अक्रमुः ८.९३.१४; ९.४१.१
अक्रमुः ९.१०.१; २३.२; ३१.१; ३२.१; ८६.१७; १०.९७.१०
अक्रविऽहस्ता ५.६२.६
अक्राः १०.७७.२
अक्रान् ९.६४.९; ९७.४०
अक्रान् २.११.८; ९.६९.३
अक्रामत् १०.९०.४; १३८.५
अक्रि १०.१५९.४; १७४.४
अक्रीळन् १०.७९.६
अक्रुक्षत् १०.१४६.४
अक्रौ १.१२०.२
अक्ष ३.५३.१९
अक्षः १.१६४.१३; १६६.९; ३.५३.१७; ६.२४.३; ८.५.२९; १०.८५.१२
अक्षः १०.३४.४
अक्षण्ऽवन्तः १०.७१.७
अक्षण्ऽवान् १.१६४.१६
अक्षत् १०.११.७
अक्षतः ५.७८.९; १०.१६६.२
अक्षन् १.८२.२
अक्षन् १.१९१.१२; १०.१५.१२; २७.८
अक्षऽनहः १०.५३.७
अक्षऽभिः १.८९.८; १२८.३; १३९.२[२]; २.२.४; ९.१०२.८; १०.२१.७; ७९.५; १२७.१
अक्षम् १.३०.१४; १५; ७.३३.४
अक्षरः ९.८५.५
अक्षरत् १.११२.११; ८.७.१; ९.३९.४
अक्षरत् ९.२८.२; ६३.३
अक्षरन् १.३३.११; ८४.४; १८८.५; ९.८.१; १७.२; २१.३; २९.१; ३०.१; ३३.२; ६३.१४; १५; ७८.३; ९८.११; १०१.४
अक्षरम् १.१६४.४२; ३.५५.१
अक्षरा ७.१५.९; ३६.७

अक्षरा ७.१.१४
अक्षराऽइव १.३४.४
अक्षराणाम् ३.३१.६
अक्षरे १.१६४.३९; ६.१६.३५
अक्षरेण १.१६४.२४; १०.१३.३
अक्षस्य १०.३४.२
अक्षाः ९.४३.५
अक्षाः १०.२७.१७
अक्षाणि ७.५५.६
अक्षारिति ९.१८.१; ६६.२८; ८७.४; ८९.१; ९७.४५; ९८.२; ३; १०७.९[२]; १०९.१६; १७; ११०.१०; १०.८९.६
अक्षासः १०.३४.६; ७
अक्षि ९.९.४
अक्षिणाः ४.१८.१२
अक्षितऽऊतयः ८.३.१५
अक्षितऽऊतिः १.५.९; ६.२४.१
अक्षितऽऊतिम् ४.१७.१६
अक्षितम् १.९.७; ५८.५; ६४.६; १३०.५; ५.५३.१३; ७.६५.१; ८.७.१६; ७२.१०; ९.२६.२; ३१.५; ६८.३; ७२.६; ७८.३; ११०.५; १०.१०१.६
अक्षितऽवसुम् ८.४९.६
अक्षिता ३.४०.७; ९.६८.३
अक्षिति १.४०.४; ८.१०३.५; ९.६६.७
अक्षिते ९.११३.७
अक्षिऽपत् ६.१६.१८; १०.११९.६
अक्षियन्तम् ४.१७.१३
अक्षी इति १.७२.१०; ११६.१६; ११७.१७; १२०.६; १०.७९.२
अक्षीइवेत्यक्षीऽइव २.३९.५
अक्षीभ्याम् १०.१६३.१
अक्षीयमाणम् ३.२६.९
अक्षीयमाणा १.१५४.४
अक्षुः १.१८०.५
अक्षे ८.४६.२७
अक्षेणऽइव १०.८९.४
अक्षेत्रऽवित् ५.४०.५; १०.३२.७
अक्षैः १०.३४.१३

अक्षोदयत् ४.११.४
अक्ष्णः ८.२५.९
अक्ष्णयाऽध्रुक् १.१२२.९
अक्ष्णऽयावानः ८.७.३५
अखनन्तः १०.१०१.११
अखर्वम् ७.३२.१३
अखिदत् ८.७७.३
अखिद्रयामऽभिः १.३८.११
अख्खलीकृत्य ७.१०३.३
अख्यः ७.१३.३
अख्यत् ४.१४.१; २४.८; ५.३०.९; १०.४५.४
अख्यत् १.३५.७; ८; ४६.१०; ११३.४; १२३.२; ४.२.१८; १३.१; १९.९; ५.८१.२; ९.१०१.७; १०.१२७.१; १८९.२
अख्यत १.१६१.१३; ९.६१.७
अख्यन् १.३५.५; ४.१.१८
अख्यम् १.१०९.१; ८.५५.१
अख्यम् ५.४८.४
अगच्छः ८.९८ ३; १०.१७०.४; १७१.२
अगच्छः १०.७३.६
अगच्छत् १.३२.१४; ३.३१.७
अगच्छत् १०.९८.२
अगच्छत १.११०.२
अगच्छत १.१६१.६
अगच्छतम् १.११९.८
अगच्छतम् १.११७.१९; ५.७८.४; ८.८.१०; ५७.१; १०.३९.७
अगदम् १०.१६.६; ९७.२
अगन् १.१६४.३७; ३.३७.१०; ९.३२.५; ९७.५
अगन् १.१२३.२; १७९.४; ४.३५.२; ५३.७; ७.२०.९; १०.१०.७; २९.४; ४०.१२; ८६.२२
अगन्म १.५०.१०; ११३.१६; ४.५.१२; ६.१६.३८; ७.१२.१; ८.४८.३; ११; ९२.१३; ९.६७.२९; १०.६०.१
अगन्म ३.३१.१४; ३३.३; ६.४७.२०; ८.१९.३२; ३९.८; ७४.४; १०.२.३
अगन्महि ६.५१.१६

१६२.१५; १६९.३; १८८.१०; ११; २.२.८; ३.१^{२}; १०; ४.२; ७; ९.१; १०.१–३; ५; ३.१.११; १२; १८; २.२; ८; ३.१; २; ४; ६; ९; ११; ४.२; ८; १०; ५.१–१०; १०.४; ११.१–३; ५; ६; १३.४; १४.१; १६.१; १७.१; २०.४; २२.१; २३.१; २५.२; ३; २६.३; ७; २७.४; ५; १३; १४; २९.२; ७; ९; ३१.३; ५३.४; ५४.१; ५६.१०; ५७.१; ४.१.१०; २०; २.१; ३.१०; ५.२–४; ६.२; ४; ५; ७; ७.७; ११; ९.४; १२.३^{२}; १३.१; १४.१; १५.१–३; २५.३; ४; २८.३; ५५.४; ८^{२}; ५.१.१–३; ५; ६; २.९; ३.१०; १२; ४.२; ६.२; ३^{२}; ९.२; ११.१; ४^{२}; १३.३; १४.४; १५.१; १६.२; १७.४; १८.१; २४.१; २५.४^{३}; ५; ६^{२}; २८.१; २९.७; ४१.४; १०; ४४.१५^{३}; ४९.३; ५१.१३; १४; ५८.३; ६०.७; ७५.९; ७६.१; ६.१.६; ४.२; ४; ६.२; ८.२; ९.१; १२.१; ४; १४.२^{२}; ४; ५; १५.१०; १३; १६.१९; २८^{२}; ३४; १८.१०; ४९.१; ९; ५१.१०; ५२.६; ६३.४; ७.१.१४-१६; २.८; १०; ४.२-६; ५.२; ६.३; ५–७; ७.३-५; ८.१; २; ४; १०.२; ११.४; १२.२; १५.३; ६; १०; १६.१२; ३०.३; ३४.१४; २५; ३५.४; ३६.१; ३९.१; ७; ४०.३; ७; ४२.४; ४४.५; ४९.४; ५०.२; ५१.३; ५६.२५; ६२.३; ६७.२; ७७.१; ७८.२; ८.७.३६; १२.९; १८.९; १९.८; ११; १९; २२; २३; २३.१३; २५.१९; २७.१; ३९.१; ४; ५; ६^{४}; ७-९; ४०.१; ४३.६–८; २२; ४४.१२; १६; २१; ५६.५^{२}; ५८.२; ६०.१३; ६९.११; ७१.१३; ७५.४; १४; १०२. ९; १०३.२; १२; ९.५.११; ६६.२०; ८८.५; १०.१.१; ६; २.२–५; ३.३; ७; ५.७; ६.२; ४; ८.१; १६.६; १०; ११; १७.३; १९.२; २१.५; ३१.९; ४५.१; ४; ७; ८; १२; ४६.८; ५१.४; ५२.४; ६१.१४; ६५.१; ६९.७; ११; १२; ७०.७; ७८.२; ७९.४; ८०.१^{४}; २^{३}; ३^{४}; ४^{३}; ५; ६; ८५.८; ३९–४१; ८७.१; ८८.४; ६; ९०.१३; ९५.१२; १००.६; १०९.२; ११०.१०; ११; ११३.८; ११५.२; ५^{४}; ७; ११८.३; ४; १२२.१; १२४.४; १२८.२; १५०.४; ५; १५१.१; १५८.१; १६२.१; २; १६४.३; १६५.२; १६९.२; १७३.५; १७६.४; १८७.५

अग्निःऽइव १०.८४.२; १०६.३

अग्निऽजिह्वाः १.४४.१४; ८९.७; ३.५४.१०; ६.२१.११; ५०.२; ५२.१३; ७.६६.१०; १०.६५.७

अग्नित् २.१.२; १०.९१.१०

अग्निऽतपः ५.६१.४

अग्नितपःऽभिः १०.६८.६

अग्निऽतप्तेभिः ७.१०४.५

अग्निऽदग्धाः १०.१५.१४

अग्निऽदूतः १०.१४.१३

अग्निधम् १०.४१.३

अग्निऽधाने १०.१६५.३

अग्निना १.१.३; १२.६; ३६.१८; १६२.११; ५.४३.७; ८.३५.१; ४३.१४

अग्निऽभिः १.२६.१०; ३.२४.४; ६.१०.२; ११.६; १२.६; ७.३.१; ८.१८.९; १९.७; ६०.१; १०.१४१.६

अग्निऽभ्यः ७.१.४

अग्निऽभ्राजसः ५.५४.११

अग्निम् १.१.१; १२.१; ७; ९; १४.३; २३.२०; २७.१; ३५.१; ३६.१; २; ७; ११^{२}; ३८.१३; ४४.३; ४; ८; ४५.४; ५८.७; ७१.७; ७२.४; ८४.१८; ९६.१–७; १०६.१; ११२.१; ११३.९; ११६.८; १२७.१; १२८.८; १३६.६; १३९.१; १४३.४; ७; १४६.१; १५७.५; १६१.३; १६४.४६^{२}; १७०.४; १७४.३; १८१.९; १८६.३; २.२.१; ३; ४.१; ३; ८.५; १०.४; ६; १२.३; २४.७; २५.१; ४१.१९; ३.१.२–४; ११; १४; २.३–५; १३; १४; ३.३; ५; ९.५; ९; १०.६; ११.४; १२.३; १३.३; ५; १७.४;

१९.१; २०.१; ५; २३.२; ३; २६.१; २; २७.२; ६; ११; १२; २९.१; ५; १५; ३१.१५; ४.१.१९; २.१७; १९; ३.१; ६.८; ११; ३९.२; ४; ५८.८; ५.१.४; ७; २.१२; ३.४; ४.३; ६.१; १०; ९.३; ११.२; ४[२]; १४.१; ३; ५; ६; १७.१; २१.४; २२.२; २५.१; ४; ९; २६.७; २८.६; ४३.७; ६०.१; ८५.२; ६.१.३; ८; ७.१; ८.४; १०.१; १४.२; १५.४; ७; १७; १६.४०; ४६; ४८; ३१.९; ४९.२; ५०.१; ६०.१२; ७.१.१; २; २.३; ३.१; ५; ६.४; ७.१; १०.३; ५; १६.१; ३; ३९.५; ४१.१; ४२.६; ४४.१; ३; ७८.३; ८०.२; ९९.४; ८.७.३२; ११.६; ९; १९.२; ४; १३; २३.२; ७; २०; २२; २५; ३१.१४; ३९.१[२]; ८; ४३.१९; २४; २५; ३१; ४४.१; ३; ६; ७; १३; १५; २६; ४५.१; ४८.६; ६०.२; १७; ७१.११; १२[५]; १३; १४[३]; १५[२]; ७३.८; ७४.१; ४; ६; ८४.१; १०२.४–७; १०; २२[२]; १०३.१; ३; १०; १०.१.५; ६.५; ७.३[३]; ५; ९.६; ११.३; ४; १६.९; १४; २०.२; ६–८; २१.१; ३५.३–१२; ४५.६; ४६.९; ५२.६; ६१.९; १६; ६३.९; ६४.३; ८; ६८.९; ७०.३; ८०.५[३]; ६[२]; ७; ८८.३; ८–१०; १२–१४; ९१.६; ८; ९२.२; १०१.१[२]; ११८.६; १२१.७; १२२.४; १२६.५; १३६.१; १४०.६; १४१.३; १५०.४[२]; ५; १५५.५; १५६.१

अग्निम्ऽअग्निम् १.१२.२; ६.१५.६; ८.६०.१७

अग्निम्ऽइन्धः १.१६२.५

अग्निऽरूपाः १०.८४.१

अग्निवान्ऽइव ७.१०४.२

अग्निऽश्रियः ३.२६.५

अग्निषु १.१०८.४; ५.६.६; ७.१.२२

अग्निऽस्वात्ताः १०.१५.११

अग्निऽहोतारः १०.६६.८

अग्नी इति ५.४५.४; ६.५९.३; ६०.१

अग्नीन् ७.१.१४

अग्नीनाम् १०.७८.३

अग्नीपर्जन्यौ ६.५२.१६

अग्नीषोमा १.९३.२–४; ६; ७; ९; १२; १०.१९.१

अग्नीषोमा १.९३.८; १०.६६.७

अग्नीषोमौ १.९३.१; ५; १०; ११

अग्ने १.१.४; ६; ९; १२.३; ५; १०; १२; १३.४; १४.७; १०; ११; १५.४; २२.९; २६.२; २७.४; ३६.५; १२; ४४.१; २; ५; ७; ९–११; ४५.६; ८; १०; ५८.८; ७३.४; ७५.२–५; ७६.५; ७९.४; ६; ९४.१–१४; ९७.१; १०५.१३; १२७.११; १४४.७; १४७.५; १६१.१; १८८.३; १८९.१–३; २.१.१५; १६; २.२; ६; १३; ७.१; ४; ५; ९.२; ४; ६; ३.१.१६; २२; २३; २.६; ३.७; १०; ५.११; ६.११; ७.११; १०.२; ७; ११.९; १३.६; १४.३; ४; १५.५; १६.६; १९.३; ४; २०.२; ३; २१.३; २२.२; ३; ५; २३.२; २४.१–५; २५.१; ४; ५; २७.३; १०; १५; २८.१; ३–६; २९.४; ८; १२; ५७.५; ४.१.३; ४.३; १२; ६.१; ७.२; ९.१; १०.१; ३–५; ७; ८; ५.१.११; ३.७; ९; ४.९; ७.९; ९.४; १०.१; १३.१; ६; १६.५; २०.३; २१.१; २; २२.४; २३.१; ४; २४.१; २५.३; २६.१; ३; ४; ६; २७.२; २८.३; ४; ४६.२; ५१.१; ५६.१; ६०.६; ८; ६.१.१३; २.१; ८–११; ३.१; ४.६; ८.५; १०.२; ५; ११.१; २; ४; १३.१–३; ५; ६; १४.६; १५.१४–१६; १९; १६.३; ९; १०; १६; २१; ३३; ३६–३९; ४३; ४८.१०; ५१.५; ६०.३; ७.३.३; ९.५; १४.३; १५.१३; १६.९; १७.१; ३; ४३.३; ८.११.२; ७; १९.९; २९[२]; २३.६; ११; २६; २८; ३०; ३९.३; ४३.२; १२; १५; १६; १८; २३; २६; २७; ४४.२; ४; ५; ८; ११; १४; २२; २५; २९; ६०.१; ३; ५; ७; १६; १८–२०; ७१.५; ६; ८; ७४.७; ७५.११; १३; १६; ८४.९; १०२.१६; १८; १०३.१३; ९.६६.१९; २१; ६७.२३; २४; २६;

१०.१.२; १२.६; २१.६; ८; ७९.५; ६; ८०.७[२]; ८७.५; ७; २१; २३; ९१.३; ९८.१२; ११८.१; ७; १२२.६; १२८.६; १४०.१; १४१.१; १५०.३; १५६.४; ५; १९१.१

<u>अग्ने</u> **१**.१.७; १२.४; ८; १३.१; १४.१; २; ८; १९.१–९; २२.१०; २३.२३; २४; २६.१०; २७.७; ३१.१–१८; ३६.४;६; ९; १५; १९; ४४.१३; ४५.१; २; ७; ५८.४; ६; ९; ५९.१; ६०.५; ६७.३; ७१.६; १०; ७२.३; ७; १०; ७३.५; ७–१०; ७४.७–९; ७६.१–३; ७९.७–९; ११; ९४.१६; ९५.९; ११; ९६.९; ९७.४; १२७.९; १३९.७; १४०.१०–१३; १४१.९; १०; १४२.१; ४; १४३.८; १४४.६; १४७.१-४; १५०.१; ३; १६४.११; १८९.४–७; **२**.१.१–१४; २.७; ९-१२; ३.३; ४.८; ९; ५.८; ६.१; २; ७; ९.३; ५; ३५.१५; ३७.६; **३**.१.१[२]; १७; २०; २३; ४.१; ११; ५.११; ६.२; ५; ७–९; ११; ७.१०; ११; ९.२; ७; १०.१; ३; १३.७; १४.५–७; १५.२–४; ७; १६.३; ५; १७.२; ३; ५; १८.१–५; १९.२; ५; २१.१; ४; २२.५; २३.४; २८.२; २९.१०; ५४.३; २१; २२; ५५.२; ५७.६; ६१.६; **४**.१.१; २; ४; ५; २.२; ४–६; ९; १०; १२–१४; १६; २०; ३.४; ५; ६[२]; ७; ९; १२–१६; ४.२; ४; ५; ७; १०; १३; १५; ५.६; १४; ६.६; ९; १०; १०.२; ११.१–६; १२.१; २; ४–६; **५**.१.८; ९, १०[२]; २.७; ८; ११; ३.१; ५; ६; ८; ११; ४.१; ४-८; १०; ११; ५.३; ६.४; ५; ७; ८; ७.१०; ८.१–७; ९.१; ६; ७; १०.२–७; ११.३; ५; ६; १२.३; ४[२]; ५; ६; १३.४; ५; १६.४; १८.५; २०.१; २; २३.२; २६.५; २७.१; ३; २८.२; ५; ३०.१२; १३; १५; ३४.९; ४३.६; १५; ४७.७; ५१.८–१०; **६**.१.१; ७[२]; ९–११; १३; २.५; ४.१; ७; ८; ५.४; ६; ७; ६.३; ७.३; ५; ८.६[२]; ७; ९.७; १०.६; ११.६; १२.६; १३.४; १४.३; १५.८; ९; ११; १२; १६.१; ७; १२; १३; २५; २७; ३१; ४५; ४७; २७.८; ४८.३; ४; ७-९; ५०.९; ५१.१३; ५२.१२; ६०.२[२]; ३; ६६.९; **७**.१.३; ५; ७-९; ११; १३; १७-२५; २.१; ११; ३.३; ७; १०; ४.७; ९; १०; ५.३–६; ८; ९[२]; ७.२; ७; ८.३; ५; ७; ९.६; १०.४; ११.१–३; ५; १२.३; १३.२; ३; १४.२; १५.७; १२; १६.५; ७; १७.६; १८.२२; ३४.८; ३९.४; ५; ४२.२; ५; ४३.५; ५९.१; ९३.७; ८; १०४.१०; १४; **८**.१.३३; ११.१; ३; १०; १९.१५; १७; २५; २६; २८; ३०; ३३; २३.१४; २९; ३९.२; १०; ४३.३; ९; १०; १३; १४; १७; २०; २८; ३०; ३२; ३३; ४४.१७-१९; २३; २४; २८; ३०; ६०.९; ११; १४; १६; ७१.१; ४; ७४.८; ११; ७५.१; १०; ८४.४; १०२.१; २; २०; १०३.४; १४; **१०**.१.७; २.१; ७; ४.१; ४;६; ७; ६.६; ७; ७.१; २; ४; ७; ८.६; ९.९; ११.५; ७–९; १२.९; १५.९; १०; १२; १६.१; ५; ८; १३; १९.३; २०.१०; २१.२; ४; ७; ३२.६; ४५.२; ३; ९–११; ४६.१०; ५१.१; ३; ५; ७; ९; ६९.३; ४; ६; ८; १०; ७०.१; ११; ८५.३८; ८७.४; ६; ८–१४; १६; १७; १९; २०; २२; २४; २५; ८८.५; ९१.४; ७; ९–११; १५; ९८.८; १०; ११; ११०.३; ११५.९; ११८.८; १२२.२; ३; ७; ८; १२४.१; १२६.८; १२८.१; १४०.४; १४१.६; १४२.१–३; ५; ६; १५६.२; ३

<u>अग्नेः</u> **१**.२४.२; ३६.२०; ४४.१२; ७२.२; ९७.५; ११५.१; १२२.५; १२८.५; १४३.३; **२**.८.१; ६; ३८.५; **३**.२.९; ११.८; १५.१; २६.६; ३५.९; १०; **४**.१.७; १५.५; ४०.१; ५५.७; **५**.२.१०; १३.२; ५१.२; **६**.६.५; ६६.१०; **७**.६.२; ८८.२; **८**.६.७; ४३.१; ४४.२०; ७३.९; ७५.७; **९**.९६.५; **१०**.३.४; ६.१; ७.३; १६.७; ३४.११; ३६.१२; ५१.२; ६; ८; ६२.५; ६; ६९.१;

अघऽशंसाय ७.१०४.४; ८.६०.८; १०.१८२.१

अघऽशंसे ५.३.७

अघस्य १.१२३.५; ८.७९.४; ८३.५; १०.८९.१४

अघा ८.४७.५; १०.१०२.१०

अघाः ६.४८.१६; ५९.८

अघात् १.१२८.५; १६६.८

अघानाम् ८.४७.२

अघानि २.२९.५; ७.८३.५

अघाय १.१८९.५; ७.१९.७

अघासु १०.८५.१३

अघुक्षत् ५.४०.८

अघोरऽचक्षुः १०.८५.४४

अघ्नतः ७.२०.८

अघ्नता ५.५१.१५

अघ्नते ८.२५.१२

अघ्न्यम् १.३७.५

अघ्न्यस्य १.३०.१९

अघ्न्या ७.८७.४; ८.१०२.१९

अघ्न्या १.१६४.२७; ७.६८.९; १०.६०.११

अघ्न्याः ८.७५.८; ९.१.९

अघ्न्याः ९.८०.२

अघ्न्यानाम् ८.६९.२; १०.१०२.७

अघ्न्याभ्यः ५.८३.८

अघ्न्याम् ७.६८.८

अघ्न्यायाः ४.१.६; ९.९३.३; १०.४६.३

अघ्न्यायाः १०.८७.१६

अघ्न्ये १.१६४.४०

अघ्न्यौ ३.३३.१३

अङ्कुसम् ४.४०.३

अङ्क्षि ४.४०.४

अङ्काः १.१६२.१३

अङ्कीऽइव ३.४५.४

अङ्कुऽयन्तम् ६.१५.१७

अङ्कुशः ८.१७.१०

अङ्कुशम् १०.४४.९; १३४.६

अङ्कुशिनः १०.३४.७

अङ्क्ते १.१२४.८; ५.१.३; ८.२९.१

अङ्ग १.१.६; ८४.७–९; १९; ११८.३; १६४.७; २.४१.१०; ३.३३.११; ५८.३; ५.३.११; ६.४४.१०; ५०.१०; ५२.३^{3}; ७२.५; ७.२०.९; ५६.२; ९१.१; ८.६.२६; ७.२; २४.१२; १५; ८०.३; ९६.१०–१२; ९.१०८.३; १०.४.४; ४२.३; ५४.४; ६४.१३; ७९.४; ८६.७; १२९.७; १३१.२; १४६.४^{2}; १४९.३

अङ्गम् १०.८५.३०; १०९.५

अङ्गम्ऽअङ्गम् १०.९७.१२

अङ्गात्ऽअङ्गात् १०.१६३.६

अङ्गानि १०.१०३.१२

अङ्गाराः १०.३४.९

अङ्गिरः १.१.६; ३१.१७; ७४.५; ११२.१८; २.२३.१८; ४.३.१५; ९.७; ५.८.४; १०.७; ११.६; २१.१; ६.२.१०; १६.११; ८.६०.२; ७४.११; ७५.५; ८४.४; १०२.१७

अङ्गिरःऽतम १.७५.२; ८.४३.१८; २७; ४४.८

अङ्गिरःऽतमः १.३१.२; १००.४; १३०.३; ९.१०७.६; १०.६२.६

अङ्गिरःऽतमम् ८.२३.१०

अङ्गिरःऽतमा ७.७५.१; ७९.३

अङ्गिरःऽभिः १.६२.५; १००.४; २.१५.८; ४.१६.८; ६.१८.५; ७.४४.४; १०.१४.३–५; १११.४

अङ्गिरःऽभ्यः १.५१.३; १३२.४; १३९.७; ८.१४.८; ६३.३; ९.६२.९; ८६.२३

अङ्गिरसः १.६२.२; ७१.२; ३.५३.७; ४.२.१५; ३.११; ५.११.६; ४५.८; ६.६५.५; ७.४२.१; ५२.३; १०.१४.६; ६२.५; ६७.२; ७८.५; १०८.८; १०; १६९.२

अङ्गिरसः १०.६२.१–४

अङ्गिरसाम् १.६२.३; १०७.२; १२१.१; ३; १२७.२; २.२०.५; ६.११.३; १०.७०.९

अङ्गिरस्वत् १.३१.१७; ४५.३; ६२.१; ७८.३; २.१७.१; ३.३१.१९; ६.४९.११; ८.४०.१२; ४३.१३

अङ्गिरस्वन्तौ ८.३५.१४
अङ्गिरस्वान् २.११.२०; ६.१७.६
अङ्गिराः १.३१.१; ८३.४; १३९.९; ३.३१.७; ५.४५.७; १०.९२.१५
अङ्गिरे ४.५१.४
अङ्गेभिः १.१४१.८; ३.७.४
अङ्गैः १.८९.८; २.३३.९; ३.१.५; १०.४.६
अङ्घ्रि ९.५.१०
अङ्ग्याः १.१९१.७
अङ्धि १०.१५६.३
अङ्ध्वे १०.१००.१०
अच ५.८३.८; ९.९७.५४
अचक्रत् ४.१८.१२
अचक्रम् १०.१३५.३
अचक्रया ४.२६.४; १०.२७.१९
अचक्रिरन् ८.६.२०
अचक्रे इति १.१२१.११
अचक्रेभिः ५.४२.१०
अचक्षत १०.१२३.६
अचक्षयत् २.२४.३
अचचक्षम् ५.३०.२
अचथः ५.७८.६
अचरः १०.५४.२
अचरत् १.१०३.३; ३.४८.३; ४.३.१०; २४.९; १०.१०२.८
अचरन् ३.५६.२
अचरन्ती इति १.१८५.२
अचरम् १०.९५.१६
अचरमाः ५.५८.५
अचष्ट २.१५.७; ३.५४.६; ४.१८.३
अचाकशम् १०.८६.१९; १३५.२
अचामि १०.११९.५
अचारिषम् १.२३.२३; १०.९.९
अचिकितत् ७.८०.२
अचिकित्वान् १.१६४.६
अचिकेत् १०.५१.३
अचिक्रदः ९.२२.७
अचिक्रदत् ४.२४.८; ७.३६.३; ८.४६.३१; ९.२.६; ९६.२४
अचिक्रदत् १.५८.२; ७.२०.९; ९.१८.७; २७.४; ६७.४; ६८.२; ७५.३; ७७.१; ८२.१; ८६.९; २०; १०.९६.१०
अचिक्रदन् ८.१००.५
अचितः ७.८६.७; १०४.१; ९.९७.५४
अचितम् १०.८७.१२
अचिते ७.६१.५
अचित्तम् १.१५२.५; ६.४६.१२
अचित्तात् ४.३.१
अचित्तान् ३.१८.२
अचित्तिः ७.८६.६
अचित्तिऽभिः ४.१२.४
अचित्तिम् ४.२.११
अचित्ती ४.५४.३; ७.८९.५
अचित्रम् ६.४९.११
अचित्रे ४.५१.३
अचिध्वम् १.८७.२; ५.५५.७; ८.७.२; १४
अचीकृषम् १०.११९.११
अचुक्रुधत् ५.३४.७
अचुच्यवीत् ८.७२.८
अचुच्यवीतन १.३७.१२[2]
अचुच्यवुः १.१६६.५; ५.५३.६
अचुच्यवुः १.४५.८; १६८.४; ५.५९.७; ८; ८.४२.४; ९५.२; १०.९७.१०
अचेत् ४.२४.८
अचेत् १०.१०२.२
अचेतत् ७.९५.२
अचेतयत् ३.३४.५; ७.८६.७
अचेतसः ७.१८.८
अचेतसम् ७.६०.६; ७
अचेताः १.१२०.२
अचेतानस्य ७.४.७
अचेति १.११३.४; १३९.४; ७.६७.२; ७८.४; ८.५६.५; १०.७४.६
अचेति १.८८.५; ६.२७.४
अचैत् ६.४४.७
अचोदते ५.४४.२
अचोदयः १.४२.५
अचोदयत् ५.३१.३

अचोदसः ९.७९.१

अच्छ १.२.२; ६.६; ३१.१७; ३८.१३; ४०.३; ४१.६; ४४.४; ७१.३; १०१.८; १०४.५; १०५.१४; १२२.५; १२३.४; १२९.५; १३०.१; ५; १३२.५; १३९.१; १४१.१२; १४२.४; १५१.७; १६३.१३; १६५.४; १३; १४; १६७.२; १७३.११; १८६.६; १०; २.१८.७; १९.२; ३; २४.१२; ३६.६; ३९.१; ५; ३.१.१; ४.३; १४.३; १५.५; १९.२; २२.३[२]; २९.९; ३१.६; ३३.२; ३; ५; ३५.१; ३९.१; ४२.३; ५३.४; ५४.५; ५५.३; ५७.३; ४; ६१.५; ४.१.२; १०; १९; ५.१३; १४.१; १५.७; १६.९; २०.२; ५; २१.४; २४.८; २९.४; ३४.१; ३; ३८.५; ४४.५; ४५.७; ५.१.१; ४; २४.१; २५.१; ४१.१४; ४२.१५; ४३.८; ४५.५; ९; ४७.६; ५२.१४; १५; ५५.१०; ५९.६; ७४.३; ७६.१; ८३.१; ६.२.११; ६.१; १४.६; १६.१२; ४४; २२.५; ३०.४; ३२.४; ३७.३; ४१.१; ४४.१५; ४७.७; ४९.४; ५१.३. ६७.२; ७.१.१८; ३.३; ९.५; १०.३; १८.४; २३.४; २४.३; ३४.२०; ३६.९[२]; ५७.७; ६७.१; ७२.३; ९०.१; ९२.३; ९३.७; ८.२.२८; ५.३३; १६.१०; १२; २१.६; २२.४; २३.१०; ३३.१३; ४८.६; ५१.३; ६०.२; ७१.६; १०[२]; ७५.२; ९३.२३; १०२.७; १०३.२; ९; ९.१.५; ५७.१; ६४.१६; ६६.११; १२; ६८.१; ६९.९[२]; ८१.२; ८७.१; ९१.१; ९२.२; ९५.३; ९६.२; ९७.६; ८; २५; १०६.१; १०७.१२; १०८.२; ११०.४; १०.१.७; ६.४; २६.१; ३०.१; २; ५; ६; ३२.५; ४३.१; ४५.९; ४७.६; ८८.१४; ११२.४; १४१.१; १४३.५

अच्छऽउक्तौ ५.४१.१६[२]

अच्छद्यन् १०.१०८.१०

अच्छान् ६.२८.५; १०.३४.१

अच्छान्त १.१६५.१२

अच्छान्त्सुः १०. ११९.६

अच्छायः १०.२७.१४

अच्छिद्यमानया २.३२.४

अच्छिद्रऽऊतिः १.१४५. ३

अच्छिद्रऽऊध्नी १०.१३३.७

अच्छिद्रम् २.३.८; ५.६२.९; ६.४९.७; ८.२७.९

अच्छिद्रस्य ६.४८.१८

अच्छिद्रा १.५८.८; १६२.१८; २.२५.५; ३.१५.५

अच्छिद्राः १.१५२.१

अच्छिन्नऽपत्राः १.२२.११

अच्छैदि १.११६.१५

अच्छोक्तिऽभिः १.६१.३; १८४.२; ८.१०३.१३

अच्यन्त ५.५४.१२

अच्यवयत् २.२४.२

अच्युतः १.५२.२; १०.१११.३

अच्युतऽच्युत् २.१२.९; ६.१८.५

अच्युतम् १.५६.५; २.३.३; ६.१५.१; १७.५; १०.१७०.३

अच्युता १.८५.४; १६७.८; २.२४.२; ६.२.९; २२.६; ३१.२; ८.२०.५; १०.६१.१०

अच्युताः १०.११५.४

अच्युतानाम् ८.९६.४

अच्युतानि ३.३०.४

अजं १.१७४.३; ६.४९.१२

अज १.२३.१३; ४२.३; ६.२५.९; ४७.३१

अजऽअश्व १.१३८.४[२]; ६.५५.३

अजऽअश्वः ६.५८.२; ९.६७.१०

अजऽअश्वम् ६.५५.४

अजः १.६७.३; १६२.२; ४; १६३.१२; २.३१.६; ३.४५.२; ६.५०.१४; ७.३५.१३; ८.४१.१०; १०.१६.४; ६४.४; ६५.१३; ६६.११; १३४.६

अजकाऽवम् ७.५०.१

अजगन् १.१३०.९; १६१.४; १८७.७; ३.९.२

अजगन् १.१६१.१; ५.३१.१०; ७.१८.७

अजगन्त १०.१५५.४

अजगन्तन १०.८६.२२

अजग्मिरन् १०.२७.१५
अजघ्नुषी ८.६७.१५
अजतम् २.३९.७
अजति ५.३७.४; ६.६६.७
अजति १.३३.३; १६१.१०; ५.३४.७; ८.४५.३
अजतु ६.५४.१०
अजते १.९५.७
अजथ ५.५४.४
अजध्वम् ६.४८.११
अजनः २.१३.७
अजनत् २.२३.१७
अजनत् ३.३१.१५; १०.८२.१
अजनत ४.५.५
अजनन् २.१३.५
अजनन्त ८.१०२.१७; १०.७.५
अजनयः १.१३४.४; १०.५५.४
अजनयः १.९१.२२
अजनयत् २.१९.३; २०.७; ९.९७.४१
अजनयत् १.९६.२; २.३५.१३; १०.१३५.५
अजनयथाः १०.५४.३
अजनयन् ८.८९.१
अजनयन् २.१०.३; ७.७६.४; १०.६१.७; ८८.१३; १२२.२
अजनयन्त १०.८८.९
अजनयन्त १.५९.२; १६८.९; ४.१.१२; ८.१००.११; १०.८८.८
अजनयम् १०.४८.२; १८३.३
अजनि २.५.४; ३४.२
अजनि १.७४.३; ८३.५; १४४.४; ७.९४.१; ८.६.१०
अजनिष्ट ५.२.४; ३१.३; ७.४.२; १०.७२.५
अजनिष्ट १.११३.१; १२३.९; २.५.१; ३.२९.३; ५९.४; ५.११.१; ३२.३; ७.७६.१; १०.१७.६
अजन्ति ९.९१.१
अजभर्तन १०.७२.७
अजऽमायुः ७.१०३.६; १०
अजयः १.३२.१२[२]; ८.१४.१३
अजयः ८.९६.१८; १०.६९.९; १६७.१
अजयत् १०.१०२.२
अजयत् २.३०.३; ४.१७.११; ५.३०.५; ६.७३.३; १०.१०३.१
अजयन्त ४.४२.८
अजर १.५८.४; १२७.९[२]; ६.२.९; ५.७; ८.५; १६.४५; ८.२३.११; १०.११५.४
अजरः १.५८.२; १४४.४; १४६.२; ३.२.२; २३.१; ४.४५.७; ५.४.२; ७.४; ४४.३; ६.४.३; १५.५; २२.३; ४८.३; ६८.९; ७.१५.१३; १०.५०.५; ८७.२१
अजरम् १.१२६.२; १६४.२; १४; ३.८.२; ३२.७; ५.६.४; २७.६; ६.५.७; ८.६; १९.२; २१.१; ३८.३; ४९.१०; १५; ७.१८.२५; ८.६.३५; २३.४; २०; ९९.७; १०.५१.७; ८८.१; ३; १०६.६; १५६.४
अजरयू इति १. ११६.२०
अजरा १. ११३. १३; ५.३४.१
अजराः १.६४.३; १२७.५[२]; १४३.३[२]; ३.१८.२; ७.३.३; १०.९४.११
अजराणि १०.९१.७
अजरासः ७.५४.२; १०.४६.७; ८७.२०
अजरे इति ३.६.४; ६.७०.१; १०.३९.७
अजरेभिः १.१६०.४; ६.५.४; ६.२; ७.१०४.५
अजरेभ्यः १०.९४.७
अजरैः २.८.४
अजरौ १.११२.९
अजवसः २.१५.६
अजस्य १.१६४.६; १०.८२.६
अजस्र ८.६०.४
अजस्रः २.३५.८; ३.१.२१; २६.७; ५४.१; ७.१.१८; १०.६.२
अजस्रम् १.१००.१४; ९.११३.७; १०.४५.१; १३९.१; १८५.३
अजस्रया ७.१.३
अजस्रा १०.१२.७
अजस्राः ४.५५.२
अजस्रेण ६.१६.४५; ४८.३; ७.५.४
अजस्रैः १.१८९.४

अजहात् १०.१७.२; १३८.५
अजहात् ४.२६.७; २७.२
अजहातन ८.७.३१
अजहुः ८.९६.७
अजाऽइव २.३९.२
अजाः ६.५७.३; १०.२६.८
अजागः १०.१०४.९
अजातऽशत्रुः ८.९३.१५
अजातऽशत्रुम् ५.३४.१
अजातान् ५.१५.२
अजाति ५.२.५; १२
अजानन् १.७२.८; १०; ३.३१.४; १०.८५.१४
अजानाम् १.१६३.६
अजाम् ८.७०.१५
अजामयः ६.२५.३
अजामि ५.१९.४; १०.१०.९; १०
अजामिऽभिः १.१००.११
अजामिम् १.१११.३; १२४.६; ४.४.५; ६.४४.१७; ७.८२.६
अजामीन् ६.१९.८; १०.६९.१२
अजायत १.१२८.४[२]; ३.२९.१४; १०.१८७.५
अजायत १.११.४; ३.३.११; ६.४८.२२[२]; ८.६.२८; ८९.६; १०.११.४; ७२.२–४; ९०.५; ९; १२; १३[२]; १२९.३; १३५.६; १९०.१[२]; २
अजायथाः १.१४१.९; १०.१८०.३
अजायथाः १.५.६; ६.३
अजायन्त १.३१.१; ३७.२
अजायन्त १०.७२.३–५; ९०.१०
अजाव १.१७९.३
अजावयः १०.९०.१०
अजासः ६.५५.६; ७.१८.१९
अजिगात् १.३३.१३
अजिघांसत् ४.१८.१२
अजिन्वत् १.१५६.५; ९.९.४
अजिन्वतम् १.११२.९; १०
अजिन्वतम् १०.६५.१२
अजिरः ६.६४.३; ८.१०१.३; १०.९८.३
अजिरम् १.१३८.२; ३.९.८; ४.४३.६; ७.११.२; १०.१०२.४
अजिरऽयते ८.१४.१०
अजिरऽशोचिषः ९.६६.२५
अजिरऽशोचिषम् ८.१९.१३
अजिरा ३.३५.२; ५.५६.६
अजिराः १.१३४.३
अजिरासः १.१४०.४; ५.४७.२; ८.४९.८
अजिह्वत १०.८९.१३
अजिहीत १०.४९.५
अजिहीत २.२३.१८
अजीगः ७.६७.१
अजीगः १.११३.४–६
अजीगरिति १.११३.९; ५.१.३
अजीगरिति १.९२.६; १६३.७; ३.५८.१; ६.४७.३; ६५.१; ७.१०.१; ७५.१; १०.२९.१; १०६.१
अजीजनः ५.८३.१०; ९.११०.३; ४
अजीजनत् ४.५३.२; ७.७९.३; ८.९५.५
अजीजनत् ९.४२.४; ६१.१६; ६६.२४; १०.१३४.१[२]; २[२]; ३[२]; ४[२]; ५[२]; ६[२]
अजीजनन् ३.२९.१३; ४.३६.५; ७.७८.३; ८.८८.४; ९.७१.५; १०२.६; १०.८८.१०
अजीजनन् ३.२३.३; १०.२३.६
अजीतये ९.९६.४
अजीतिम् ९.९७.३०
अजुरम् ८.१.२
अजुर्य ६.२२.९
अजुर्यः २.८.२; ६.३०.१
अजुर्यम् १.६७.१; १४६.४; २.१६.१; ३.७.४; ५३.१५; ५.६९.१; ६.१७.१३; १०.८८.१३
अजुर्यमुः ५.६.१०
अजुर्यस्य ८.१३.२३
अजुर्या २.३९.५
अजुर्याः २.३.५; ३.७.७; ४.५१.६
अजुर्यासः १०.९४.१२
अजुषत् ८.७५.१४
अजुषत २.३७.४; ९.९२.१
अजुषध्वम् १०.९४.१०

अञ्जावाः ४.५८.९
अञ्जि १.१२४.८; ४.५८.९; ७.५७.३; ८.२०.११; २९.१
अञ्जिऽभिः १.३६.१३; ३७.२; ६४.४; ८५.३; ८७.१; ११३.१४; २.३४.१३; ५.५२.१५; ५६.१; १०.७८.७
अञ्जिऽमन्तः ५.५७.५
अञ्जिषु २.३६.२; ५.५३.४
अञ्जीन् १०.७७.२
अञ्जे १.६१.५; ६४.१
अञ्ज्मः ९.४५.३
अण्वम् ९.१०.५; ९१.३
अण्वानि ९.८६.४७; १०७.११
अण्वीः ९.१.७
अण्वीभिः १.३.४
अण्वेषु ९.१६.२
अण्व्या ९.१४.६; १५.१; २६.१
अतः १.६.९; २२.१६; १८; २३.१२; २५.११; ४७.७; ५३.३; १०१.८; १०८.७–१२; १४७.५; १६५.५; २.२४.७; ३.३६.६; ४.२.१२; १६.५; १८.१; २; २६.५; २७.३; ५०.३; ५.३०.५; ३४.४; ५०.३^{2}; ६०.६; ६२.८; ६.५.३; ४०.५; ७.१०४.३; ८.५.२७; ६.२९; ८.११; १४; ९.१०; १०.१; ६; २०.१८; ४९.७; ९२.१०; ९७.४; ९.४८.३; ८६.१५; ९५.१; १०.१.४; १२.३; १४.९; ४१.३; ४६.६; ८५.२१; २२; ९०.३; १०८.१०; १२०.७; १४९.२^{3}
अतक्त १०.२८.४
अतक्षत् १.६२.१३
अतक्षत् १०.४८.३
अतक्षत १.८६.३
अतक्षत १.१६१.७
अतक्षन् २.३१.७; ७.७.६
अतक्षन् १०.६१.७
अतक्षम् १.१०९.१; ५.२.११; २९.१५
अतक्षाम १०.३९.१४
अतक्षिषुः १.१३०.६^{2}
अतक्ष्म ८.६.३३
अतथाःऽइव १.८२.१
अतन् ६.६१.९
अतनुत् ८.५.१; ७२.१८
अतनोत् २.१७.४; १०.१११.५
अतन्द्रः १.७२.७; ७.१०.५; ८.६०.१५
अतन्द्राः ८.२.१८
अतन्द्रासः १.९५.२; ४.४.१२
अतन्वत १०.९०.६
अतपत् ३.३१.१०; १०.८८.९
अतप्तऽतनूः ९.८३.१
अतप्यमाने इति १.१८५.४
अतमानम् २.३८.३
अतमानाः ६.९.२
अतरः १.३२.१४; १०.१०४.८
अतरः १०. १०८.१
अतरत् ४.२७.२; ७.१८.६; ८.१००.८
अतरन् ५.४५.११
अतरन् १.३६.८
अतरम् १०.१०८.२
अतर्पयः ४.१९.५
अतर्पयत् ९.९.६
अतव्यान् ५.३३.१; ७.१००.५
अतष्ट १.१६३.२; ३.५४.१२; ४.३५.५
अतसम् ४.४.४; ८.६०.७
अतसस्य ३.७.३
अतसा १०.८९.५
अतसानि २.४.७
अतसाय्यः २.१९.४
अतसाय्या १.६३.६
अतसि १.३०.४
अतसीनाम् ८.३.१३
अतसे १.१६९.३
अतसेषु १.५८.२; ४; ४.७.१०
अतान् ६.६७.६
अतापि ७.७०.२
अतारिम ८.१३.२१
अतारिषुः ३.३३.१२
अतारिष्म १.९२.६; १८३.६; १८४.६; ७.७३.१

अतारीत् ७.४.५

अतारीत् १.३२.६

अति १.४.३; ३२.८; ३६.७; १६; ४२.७; ५५.३; ६४.१३; ८१.५; ९४.७^{२}; ९७.७; ८; ९९.१^{२}; १०२.८; १०५.६; १०९.६; १३५.६^{२}; ७; १४१.१३; १४३.३; १७०.३; १७३.२; १७४.९; १८२.३; १८३.४; १८९.२; २.२.१०; ७.३; ११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; २३.१५; २५.१; २७.७; १६; २८.१; ३४.१५; ३.९.३; ४^{२}; १०.७; १५.३; २०.४; २७.३; ४३.२; ४५.१; ४.८.८; ३६.९; ३९.१; ५.१.९; ३.११; ४.९; २५.९; ४४.७; ४५.११; ५२.३; ५३.१४; ६६.५; ७३.८; ६.४.५; १०.५; ११.६; १२.५; १६.२०; १८.७; २०.१२; २१.२; २२.७; ४५.६; ५२.२; ६१.९; ६२.२; ७.१.१४; २३.२; ३२.२७; ३३.२; ४०.४; ८२.१; ९७.४; ८.१.३३; २.३४; १३.२१; १६.११; १८.१७; १९.१४;२२.१४; २४.२; २६.३; ५; ३२.२१; २२; ४२.३; ४६.१६; ५६.३; ५८.३; ६०.१६; ६२.२; ६५.९; ६७.२; ६९.१४^{२}; ७३.१५; ८३.३; ९२.१४; २२; ९७.१५; ९.२.१; ३.२; ८.५; १४.६; १५.६; १७.५; ३०.४; ३६.२; ४१.२; ४३.५; ४५.४; ६०.२; ३; ६३.४; १५; ६६.२२; २८; ६७.२०; ६९.४; ९; ७०.९; १०; ७२.३; ८५.९; ८६.७; २६; २९; ३१; ४४^{२}; ४७; ८८.६; ९६.६; १७; ९७.४; ५६; १००.९; १०६.१३; १०७.१७; १९; २०;२५; १०.११.७; १२.५; १४.१०; ३१.९; ३३.९; ३५.१४; ४४.१; ५६.७; ६३.६; १३; ७५.१; ७७.२; ८५.३२; ८६.२; ९०.१; ५; ९१.२; ९३.६; ९६.८; ९७.१०; १२६.१–४; ५^{२}; ६^{२}; ७; १३३.६; १८७.१–५

अतिऽअविः ९.१३.१

अतिऽअविम् ९.६.५; ४५.५; १०६.११

अतिऽआर्थम् ८.१०१.१४

अतिऽआयातम् ५.७५.२

अतिऽआथाहि ३.३५.५

अतिऽऊर्मिः ९.१७.३

अतिऽएतुवै ५.८३.१०

अतिऽएषि ९.९७.३१

अतिऽक्रमे १.१०५.१६

अतिऽतस्थौ १०.६०.३

अतित्विषन्त ५.५४.१२

अतिथिः १.७३.१; १२८.४; २.२.८; ३.२.२; ४.१.२०; ४०.५; ५.१.८; ९; ३.५; ४.५; १८.१; ६.२.७; ४.२; ७.८.४; ९.३; ४२.४; ८.१९.८; १०३.१२; १०.९१.२

अतिथिऽग्वम् १.५३.१०; ११२.१४; ४.२६.३; ६.१८.१३; ८.५३.२; १० ४८.८

अतिथिऽग्वस्य १.५३.८; २.१४.७; ६.४७.२२

अतिथिऽग्वाय १.५१.६; १३०.७; ६.२६.३; ७.१९.८

अतिथिनीः १०.६८.३

अतिथिम् १.४४.४; ५८.६; १२७ ८, १८६.३; २.४.१; ३.३.८; २६.२; ४.२.७; ५.८.२; ६.७.१; १५.१; ४; ६; १६.४२; ७.३.५; ८.२३.२५; ४४.१; ७४.१; ८४.१; १०३.१०; १०.१.५; ९२.१; १२२.१; १२४.३

अतिथीन् ५.५०.३

अतिथे ८.७४.७

अतिऽदिव्य १०.४२.९

अतिऽध्वसन् ८.५५.५

अतिऽनेनीयमानः ६.४७.१६

अतिऽपारयः ६.४७.७

अतिऽपिप्रति ७.६६.५

अतिऽप्रशर्धयत् ८.१३.६

अतिऽमतिम् १.१२९.५

अतिऽमन्ये १.१३८.४

अतिऽयाजस्य ६.५२.१

अतिऽयाथः ५.७७.३

अतिरः ४.३०.३

अतिरः १.११.७; ४.३०.७; ८.९६.१७; १०.५४.१; १५३.२

अतृऽभ्यः १.३४.६; ८०.२; ११२.५; २.१.१; ३८.११; ५.३१.९; ७६.४; ६.६२.६; ९.५९.२; १०.३९.४; ६३.२; ८०.३

अत्यः १.५६.१; ५८.२; ६५.३; १४९.३; १९०.४; २.४.४; ३.२.७; ३८.१; ५.३०.१४; ६.२.८; ४.५; ७.२४.५; ८.५०.५; ९.३२.३; ४३.५; ६६.२३; ७६.१; ७७.५; ८०.३; ८१.२; ८२.२; ८५.५; ८६.३; २६; ४४; ९३.१; ९६.१५; २०; ९७.१८; ४५; १०.६.२; ७६.२; ९६.१०; १४४.१

अत्यःऽइव ९.४३.१

अत्यम् १.५२.१; ६४.६; १२९.२; १३५.५; ३.२.३; २२.१; ५.२५.६; ४४.३; ७.३.५; ९.८५.७

अत्यम्ऽइव १.१३०.६; ९.६.५

अत्यस्य १.१८०.२

अत्या ४.२.३

अत्याः १.१६३.१०; १७७.२; १८१.२; ३.५६.२; ५.३१.९; ६.४४.१९; ९.१३.६; ८७.५

अत्याःऽइव ५.५९.३

अत्यान् १.१२६.४; ३.३४.९

अत्यान्ऽइव २.३४.३; ३.३२.६

अत्याय ३.७.९

अत्यासः ७.५६.१६; ९.४६.१; ९७.२०

अत्येन २.३४.१३

अत्यैः ६.३२.५

अत्र १.३३.१५; ४१.४; ४८.४; ५२.११; १५; ६७.२; ८४.१५; ११८.५; ११९.७; १२३.३; १२४.१; १३५.८; १५१.५; १५४.६; १६२.४; १६३.५; ७; १६४.१; ६; ११; २१; ३३[२]; १६५.११; १३; १७३.१२; १७९.३; १८२.३; १८७.७; २.१.१५; १५.९; १८.३; ३०.२; ३५.६; ३.१.६; ७; २३.१; ३८.३; ६; ३९.३; ५५.२; ५७.२; ४.१.१३; १९.१; २२.७; २६.५; ७; ३०.७; ४१.६; ४२.८; ५४.१; ३; ५.२९.९; ३०.७; १०; ३१.७; १०; ४१.६; १७; ४४.९; ४५.७; ६१.११; ६३.१; ६.१७.८; २०.४; २४.५; ६३.५; ७.४.४; १८.३; १२; १९; ३०.३; ३९.३; ४०.६; ५७.५; ६५.४; ८५.२; १०३.२; ८.१५.१२; ३१.१८; ३४.३; ४५.२६; ९.१४.४; ७३.९; ९७.५२; १०.१.३; ११.८; १२.४; ६; ८; १६.१३; १७.९; १८.९; १२; १३; २७.६; ९; १०[२]; ३१.११; ४२.४; ५१.४; ५३.८; ६४.१६; ७१.२; ८; ७२.६; ७; ७३.१; ३; ९१.९; ९२.१५; ९३.१५; १०२.७; १११.६; ११३.३; ६; १३४.७; १३५.१; १६६.३

अत्रम् ५.३२.८

अत्रयः ५.२२.४[२]; ३९.५[२]; ४०.९

अत्रये १.५१.३; ११२.७; १६; ११८.७; ११९.६; १८०.४; ७.६८.५; ८.७३.३; ७; ८; १०.३९.९; १४३.३

अत्रसन् ८.४८.११; १०.९५.८

अत्राणि १०.७९.२

अत्रिः १.१३९.९; १८३.५; ५.७.१०; ४०.६; ८; ७३.६; ७; ७४.१; ७८.४; ८.४२.५

अत्रिणः १.२१.५; ९४.९; ७.१०४.१; ५; ९.८६.४८

अत्रिणम् १.३६.१४; २०; ८६.१०; ६.१६.२८; ५१.१४; ८.१२.१; १९.१५; ९.१०४.६; १०५.६; १०.३६.४; ११८.१

अत्रिऽभ्यः ५.६७.५

अत्रिम् १.११६.८; ११७.३; २.८.५; ५.१५.५; ६.५०.१०; ७.७१.५; ८.५.२५; १०.८०.३; १४३.१; २; १५०.५

अत्रिऽवत् १.४५.३; ५.४.९; ७.८; २२.१; ५१.८–१०; ७२.१

अत्रीणाम् ८.३६.६; ३८.८

अत्रे ५.४०.७

अत्रेः ५.२.६; ८.३६.७; ३७.७

अत्रेःऽइव ८.३५.१९

अत्रैः १.१२९.८

अत्विषन्त ८.९४.७

अत्विषुः १०.५६.४

अत्सारिति १०.२८.४

अत्सि १०.२८.३

अथ १.४.३; १०.३; १६.७; २४.१५; २६.९; ४७.३; ५४.९; ५९.२; ७५.२; ७६.३; ८१.८; ८७.४; ९२.१५; ९३.७; ९४.९; १०२.६; १०; १०८.१; ६–१२; १०९.२; ११४.९; ११७.१९; ११९.९; १३६.१; २; १६३.१३; १६४.१२; २.३.९; ३६.३; ३७.५; ३८.१; ३.३.१; ६.६; ९.३; १३.३; १७.३; ५; २८.५; २९.१०; ३१.७; ३२.१०; ३४.१०; ४७.२; ५३.३; ११; ४.१८.५; ११; २०.९; २४.१०; ३५.३; ४; ३६.४; ४२.९; ५.३०.९; ६.१६.१८; ४०.१; ४; ५३.५–७; ५४.७; ७.११.४; ९८.५; ८.९.१४; १०.५; ४०.२; ४६.१५; १६; ४८.६; ८९.२; ९६.७; १०२.१९; ९.४.१–१०; ८१.२; ८६.२८; ८७.६; १०.१.७; १४.१०; १५.४; ११; १६.१; २[२]; २३.३; २७.२२; ५१.७; ५२.३; ५; ८५.१६; ३३; १०७.३; १०८.३; ८; १११.६; १२७.६; १२९.६; १४३.३; १४५.३; ५; १८२.१–३

अथर्यः ४.६.८

अथर्युम् ७.१.१

अथर्वणः ६.१६.१४; १०.४८.२

अथर्वणा १०.२१.५

अथर्वणि ८.९.७

अथर्वऽभ्यः ६.४७.२४

अथर्वऽवत् ६.१५.१७; १०.८७.१२

अथर्वा १.८०.१६; ८३.५; ६.१६.१३; १०.९२.१०; १२०.९

अथर्वाणः ९.११.२; १०.१४.६

अथर्व्यम् १.११२.१०

अथो इति १.२८.६; ५०.१२; ११३.१३[२]; १५७.६[२]; १६४.४०; ४६; १९१.१; २[३]; ३.३७.११; ६०.४; ६.७५.१५; ८.९१.६; ९.३९.५; ६०.२; १०.२७.९; ३९.५; ६०.८–१०; ८५.२; ३५; ४१; ९०.५; ९२.४; ९६.१३; ९७.९; १६[२]; १३६.५; १३७.४; १५९.३; १७३.६; १९०.३

अदः १.१०५.३; १८७.७; ६.५६.३; ८.१०.१; २६.१७; ९.६५.२२; १०.७२.६; १२०.३; १५५.३; १८६.३

अदक्षिणासः १०.६१.१०

अदत् १०.३७.११

अदत्ते १.१८९.५

अदत्त १.३२.३; १४५.३; ५.२९.२; १०.३१.११

अदत्तन १.१३९.७

अदत्तम् १.११६.१३; ११७.७; ८; २४; ११८.९; ८.५९.६

अदत्रऽया ५.४९.३

अददन्त ७.३३.११

अददाः १.५१.१३

अददात् १०.८५.९

अददात् ५.३०.११; ६.६१.१

अददात १०.६४.१२

अददाम् ४.२६.२

अददुः ६.५८.४

अददुः ५.२९.५; १०.१७.२; १०९.६

अदृंहन्त १०.८२.१

अदधाः ३.३०.७; १०.७३.९

अदधाः १.८३.३; १०.१३८.६

अदधात् ३.३०.१४; ९.९७.४१; १०.५४.६

अदधात् १.३३.८; ५.८५.२; ६.४४.२३; १०.५६.७

अदधात ७.३३.४

अदधाम् १०.१८३.३

अदधावत् ९.८७.७

अदधुः ३.२.९; २९.७; ३१.१०; ४७.३; ६.६७.५; १०.१२.७; ५३.११; ६८.११; ८८.११; ९०.११

अदधुः २.४.२; ६.३९.३; ९.११३.३; १०.५६.४; ६; ७१.३; १२५.३

अदन् १०.४.४; ७९.६

अदन्ति १.९३.३; १०५.८; २.१.१३; १४; १०.२८.११; ३३.३; १४६.३

अदन्तु १०.८७.७; ११०.११
अदब्धः १.२४.१३; ७६.२; ८९.५; १२८.१; २.९.६; २७.१३; ४.४.३; ५.१९.४; ६.७.७; ७.३६.२; ८.५९.३; ७८.६; ९.७७.५; ८५.३; ९७.१९; १०७.२; १०.१२८.६
अदब्धऽधीतीन् ६.५१.३
अदब्धम् ४.५०.२; ६.५१.१; १०.८७.२४
अदब्धव्रतऽप्रमतिः २.९.१
अदब्धस्य ७.६६.६; ८.४४.२०; १०.७५.९
अदब्धा ३.५४.१६; १०.७५.७
अदब्धाः १.१७३.१; २.२७.९; ३.१.६; ४.२.१२; ७.६०.५; ८.१८.२; १०१.६; ९.९७.५७
अदब्धाः २.२८.३
अदब्धान् ६.५१.४; ९
अदब्धानि १.२४.१०; ३.५४.१८
अदब्धासः १.८९.१; २.२७.३; ६.६७.५; ८.६७.१३
अदब्धे इति ४.५५.३
अदब्धेभिः १.९५.९; १४३.८; ६.८.७; ७१.३
अदब्धैः ६.४८.१०
अदभा ५.८६.५
अदभ्रम् ८.४७.६
अदमयः ६.१८.३
अदयः १०.१०३.७
अदरित्यदः १.१२१.१०
अदर्दः ५.३२.१
अदर्दः २.२४.२
अदर्दरित्यदर्दः १०.६७.७
अदर्दिरुः १०.१३८.१
अदर्दृतम् ४.२८.५
अदर्धः २.३८.४
अदर्शि १.४६.११; १०४.५; १३६.२; ८.१०३.१
अदर्शि १.९२.५; ११३.७; १२४.३; ४; ४.५२.१; ५.१.२; ७.७७.३; ८१.१; ८.५६.१; १०१.१३; १०.३.१; १०७.१
अदहः ७.१.७
अदहः १.३३.७; १०.६९.११
अदहत् ४.२८.३
अदहत् १०.८०.३
अदाः १०.१५.१२
अदात् ८.३.२२; १९.३६
अदात् १.३०.१६; ६.२७.७; ४७.२२; २४; ७.१०३.१०[३]; १०.८५.३९; ४१; ९९.९
अदानम् ४.१९.९
अदाभ्य १.३१.१०; ७.१५.१५
अदाभ्यः १.२२.१८; ३.११.५; ४.५३.४; ५.५.२; ९.३.२; २८.६; ३७.५; ५९.२; ७५.२; ८५.६; १०३.४; १०.११.१; २५.७; २६.७
अदाभ्यम् ३.६२.६; ७.१०४.२०; ८.५.१२; ६१.१२; ८५.५; १०१.१२. ९.२६.४; १०.११८.६
अदाभ्यस्य ८.७.१५
अदाभ्या १.१५५.१
अदाभ्या ५.७५.७; ८; ७.६६.१७
अदाभ्याः ३.२६.४
अदाभ्याः २.३४.१०
अदाभ्यानि १०.५४.४
अदाभ्यासः ९.७०.३
अदाभ्येन १०.११८.७
अदामानः ६.२४.४; ४४.१२
अदाशत् ४.४२.९
अदाशन् ७.१९.९
अदाशुरिः ८.४५.१५
अदाशुषः ७.१९.१; ९.२३.३
अदाशुषाम् १.८१.९
अदाशूःऽतरस्य ८.८१.७
अदाशून् १.१७४.६
अदिक्षि ५.४३.९
अदितयः ७.५२.१
अदितये १.२४.१; २; १५; ४.३.८; ५.८२.६; १०.८७.१८; ११०.४
अदितिः १.४३.२; ७२.९; ८९.१०[६]; ९४.१६; ९५.११; ९६.९; ९८.३; १००.१९; १०१.११; १०२.११; १०३.८; १०५.१९;

अदेवऽन्नात् ५.६१.६
अदेवम् २.२२.४; ३.३२.६; ९.१०४.६; १०५.६
अदेवऽयन्तम् २.२६.१
अदेवऽयुः ८.९७.३
अदेवऽयुम् ७.९३.५; ८.७०.११; ९.६३.२४
अदेवऽयून् १०.२७.२; ३
अदेवऽयोः १.१५०.२
अदेवस्य १.१७४.८; २.१९.७; १०.१११.६
अदेवाः ८.९६.९
अदेवात् १०.१२४.२
अदेवान् ३.१.१६; १०.१३८.४
अदेवानि ६.४८.१०
अदेवीः १.१७४.८; ३.३१.१९; ५.२.९; १०; ६.२५.९; ४९.१५; ७.१.१०; ९८.५: ८.११.३; ६१.१६; ९६.१५
अदेवेन २.२३.१२
अद्धा १.५२.१३; ३.५४.५; ८.१९.९; १०१.११; १०.१११.७; १२९.६
अद्धातयः १०.८५.१६
अद्धि १.१६४.४०; १०.१५.१२; ११६.७; ८
अद्धि ३.३५.३; ५२.७
अद्भुत ५.१०.२; ६.१५.२; ८.२६.२१; ९.२०.५
अद्भुतऽएनसः ८.६७.७
अद्भुतऽएनसाम् ५.८७.७
अद्भुतः १.९४.१२; १३; १४२.३; २.७.६; २६.४; ५.२३.२; ६.८.३; ८.१३.१९; ९.२४.६; ८३.४; ८५.४; १०.१५२.१
अद्भुतऽक्रतुम् ८.२३.८
अद्भुतक्रतू इत्यद्भुतऽक्रतू ५.७०.४
अद्भुतम् १.१८.६; १४२.१०; १७०.१; ८.४३.२४; १०.१०५.७
अद्भुतस्य १.७७.३
अद्भुतस्य १.१२०.४
अद्भुता १.२५.११
अद्भुता ५.६६.४
अद्भुतान् ४.२.१२
अद्म १.५८.२
अद्मऽसत् १.१२४.४; ८.४४.२९
अद्मऽसदः ६.३०.३
अद्मऽसदाम् ७.८३.७
अद्मऽसद्याय ८.४३.१९
अद्मऽसद्वा ६.४.४
अद्रि १०.८६.१४
अद्य १.१३.२; ६; २३.२३; २५.१९; २८.८; ३४.१; ३; ३५.११; ३६.२; ६; ४४.१; ३; ९; ४५.९; ४७.३; ४८.१५; ४९.२; ५०.११; ५४.५; ५८.८; ७६.५; ८४.१६; ९२.१४; १५; ९३.२; १००.१०; ११३.७; १२; १३; १७; ११५.६; १२०.३; १२३.३; ८; १३; १२५.३; १३६.४; १४२.१; ८; १५९.५; १६१.११; १३; १६३.१३; १६७.१०; १८०.१०; १८२.८; १८४.१; १८८.१; २.३.३; १३.८; २७.२; २९.२; ६; ३२.५; ३७.५; ४१.३; २०; २१; ३.१४.५; १७.२; १९.४; २९.१६; ३६.३; ५३.२१; ४.२.२; १०.१; ४; १६.२; २४.७; २५.१; ३; ३०.२३; ३७.२; ४४.१; ३; ५१.३; ४; ५.१.११; १३.२; २२.२; २६.८; ४५.५; ४९.१; ५१.१३; ५३.१२; ५६.१; ५८.३; ७३.१; ७४.१; ७; ७९.१; ३; ८२.४; ७; ६.४.१; १५.१४^{२}; १६.२६; १८.१३; २१.९; २४.५; ३०.३; ३७.१; ५०.४; ९; ५२.१७; ५६.४; ६; ६३.१; ६५.३; ६८.१; ७१.३; ६; ७.२.१; १७.५; ३५.१५; ४०.१; ४३.४; ४७.१; २; ५१.२; ५७.२; ५९.३; ६०.१; ६६.४; १२; ६९.६; ७५.२; ७८.५; ९३.१; १००.५; १०४.१५; ८.१.१०; १६; २.२०; ३.८; ५.१८; ९.९; १३; १०.५; १५.६; २०.२; २२.१; ६; २६.३; ८; २७.५; १४; १९; २१; ३३.१५; ४७.१८; ६४.१२; ६६.७; ७३.५; ९३.४; ९४.८; १०१.४; ९.४४.६; ६५.२८; ६७.२२; ८४.१; १०.९.९; १४.१२; १५.२; १८.३; २२.१; २; ३०.२; ३; ३२.८; ३५.१–३; ५; ७; ९; १३; ३६.२–१०; ११^{२}; १२; ३७.५; ३८.४; ४०.१४; ४५.९; ५३.३^{२}; ४; ५४.२; ५५.५; ६३.८; ६५.१५;

६६.१५; ८१.७; ८७.१३; १५; ९२.९; ९५.१४; ११०.१; ९; ११३.१०; १२७.४; १३५.५; १४२.६; १६०.२; १६४.५; १६७.३

अद्यऽअद्य ८.६१.१७

अद्यः २.१३.९

अद्युः १०.९५.१४

अद्युतः ६.३९.३

अद्युम् ७.३४.१२

अद्यूत्ये १.११२.२४

अद्यौत् १.१२३.७; १०.१११.२

अद्यौत् १.११३.१४; १२२.१५; १२४.२; ३.१.८; १८; ५.२; ९; ४.५.१५; ६.३.८; १२.३; ५१.१; ९.८५.१२; १०.४५.८

अद्रयः १.१४९.१; २.१६.५; ३.३२.१६; ४१.२; ४.१९.५; ५.८७.२; ६.४८.५; ६३.३; ८.४.१३; ५३.३; ६३.२; ७२.११; ८८.३; ९.७९.४; १०.७६.७; ७८.६; ८९.६; ९४.८; ११; १३; १४; १००.८; १०४.२

अद्रयः १०.७६.४; ८; ९४.१

अद्रवः १०.७५.२

अद्रवत् ८.१०१.३

अद्रवत् ९.९३.१

अद्रवन् १०.९८.६

अद्रिः १.१६५.४; ३.३१.७; ५.४५.७; ६.४०.२; ७.२२.१; ३५.३; ६८.४; १०.७६.२

अद्रिऽजाः ४.४०.५

अद्रिऽजूतः ३.५८.८

अद्रिणा १.१६८.६; १०.२८.३

अद्रिऽदुग्धः ९.९७.११

अद्रिऽदुग्धाः १.५४.९; ४.५०.३

अद्रिऽबर्हाः १०.६३.३

अद्रिऽबुध्नः १०.१०८.७

अद्रिऽभिः १.१२१.८; १३०.२; १३५.२; ५; १३७.१; ३[2]; २.३६.१; ३.४४.५; ५३.१०; ४.४५.५; ५.४०.१; ८६.६; ८.१.१७; २२.८; ३५.२; ३८.३; ६५.८; ८२.५; ९.११.५; २४.५; २६.५; ३०.५ ३२.२; ३४.३; ३८.२; ३९.६; ५०.३; ५१.१; ६३.१३; ६५.८; १५; ६६.२९; ६७.३; ६८.९; ७१.३; ७५.४; ८०.५; ८६.२३; ३४; १०१.३; ११; १०७.१; १०; १०९.१८

अद्रिऽभित् ६.७३.१

अद्रिम् १.७.३; ५१.३; ६१.७; ६२.३; ४; ७१.२; ७३.६; ८५.५; ८८.३; २.१.१; ४.१.१४; १५; २.१५; ३.११; १६.८; १८.६; २१.६; ५.४३.४; ४५.१; ५२.९; ६.१७.५; ३२.२; ३९.२; ६२.७; ८.६०.१६; ९.९७.३९; १०.२८.९; ४५.६; ६८.११; ११२.८; ११३.४

अद्रिऽमातरम् ९.८६.३

अद्रिऽवः १.१०.७; ११.५; ८०.७; १४; १२१.१०; १२९.१०[2]; १३३.२; ६[2]; ३.३७.११; ४१.१; ४.३२.५; ५.३५.५; ३६.३; ३८.३; ३९.१; ३; ६.४५.९; ४६.२; ७.२०.८; ८९.२; ८.१.५; १३; २.४०; ६.२२; १२.४; १३.२६; १५.४; २१.७; २४.६; ११; ३६.६; ४५.११; ४६.२; ११; ५०.१०; ६१.४; ६२.११; ६४.१; ६८.११; ७६.८; ८०.४; ९२.१८; २७; ९७.९; ९८.८; ९.५३.१; १०.१४७.१

अद्रिऽसंहतम् ९.९८.६

अद्रिसानो इत्यद्रिऽसानो ६.६५.५

अद्रिऽसुतः ९.७२.४

अद्रिऽसुतासः १.१३९.६

अद्री इति १.१०९.३; ७.३९.१; ४२.१

अद्रुहः १.३.९; १९.३; १५९.२; २.१.१४; ३.९.४; २२.४; ८.४६.४; ६७.१३; ९७.१२; ९.९.४; ७३.७; १००.१; ७; १०२.५; १०.६६.८

अद्रुहः ८.१९.३४; २७.९; १५

अद्रुहम् ६.१५.७; ८.४४.१०

अद्रुहा ३.५६.१; ४.५६.२; ५.६८.४; ७.६६.१८

अद्रुहा २.४१.२१

अद्रुहे ९.९.२

अद्रुह्वाणा ५.७०.२

अद्रेः १. ९३.६; ११७.१६; ११८.३; १३९.१०; ३.३१.६; ५८.३; ५.४१.१२; ७.६.२; २२.४; ७९.४; ९.८७.८; १०.२०.७
अद्रोघ ३.३२.९
अद्रोघः ६.१२.३
अद्रोघम् ८.६०.४
अद्रोघम् ५.५२.१
अद्रोघऽवाचम् ६.५.१; २२.२
अद्रोघेण ३.१४.६
अद्रौ १.७०.२; ५.८५.२; ९.९६. १०
अद्वयन्तम् ३.२९.५
अद्वयाः १.१८७.३; ८.१८.६
अद्वयाविनः १.१५९.३
अद्वयाविनम् ३.२.१५; ५.७५.५
अद्वयावी ७.५६.१८
अद्वयुम् ८.१८.१५
अद्विषेण्यः १.१८७.३
अद्विषेण्यम् १०.१२२.१
अद्वेषः १.२४.४; १८६.१०; ५.८७.८; १०.३५.९
अद्वेषे इति ९.६८.१०; १०.४५.१२
अध १.१५.१०; ३८.१०; ४२.६; ५५.५; ५७.२; ७२.१०; ९४.११; १०१.९; १०२.७; १०४.५; ७; ११४.१०; १२०.१२; १२१.६; १२२.११; १२७.६; ९; १२९.११; १३२.३; १३९.१; १०; १४०.१०; १४४.२; १५१.२; १५३.१; १५६.१; १६७.२; १६९.६; १७०.५; १८०.७; १८६.९; २.१३.५; १७.३; ४; २२.२; २८.९; ३०.३; ३१.२; ४; ३.४.९; ६.२; ३२.११; ३८.२; ४२.६; ५५.१; ६; ४.२.१४–१६; ५.१०; १४; ६.७; ७.२; १०.२; १६.१७; १७.७; १०; १८.९; १३; २२.६; २७.१; ३–५; ३१.६^{2}; ५.९.५; १६.४; १७.४; २९.५; ३८.१; ४०.६; ४६.२; ५२.३; ११^{3}; १६; ५४.६; ६६.२; ४; ८५.८; ६.१.२; २.७; ६.४; ५; १०.४; १२.५; १५.९; १६.४; १७.८–१०; १८.१४; १९.२२; २५.७; ३०.२; ३१.३; ३६.१; ४६.१०–१२; ६६.६; ८; ७.२.९; ३.२; ४.८; १५.१४; १८.१२; २१; २०.३; ५; २१.६; २९.३; ४; ३४.२; ३८.६; ४५.३; ५६.१; ७; २२; २४; ७४.५; ८२.९; ८३.५; ८८.२; ९०.३; ९१.५; १०४.१५; ८.१.१६; १८^{2}; २८; ३३^{2}; १२.१९; १३.२४; ४६.२९; ३१^{2}; ३३; ६२.९; ६९.१६; ७५.१६; ८३.८; ९; ८४.२; ६; ९२.२९; ९३.१२; १४; ९६.१५; ९८.७; ११; १००.२; १०१.१०; ९.४८.५; ६१.२; ७४.८; ९७.११; ९९.२; १०२.१; २; ११०.९; १०.१.६; ६.७^{2}; १०.१४; ११.४^{2}; २२.६; २५.१–३; ३०.१०; ३३.१; ३; ५४.६, ५९.१; ६१.२०–२४; ८३.७; ८५.२७; ९२.१४; ९५.१२, १४^{2}; ९७.२; १११.९; ११३.८; ११५.१; १३२.३; १३३.५
अधः ७.१०४.११; ८.३३.१९; १०.११९.११; १२९.५; १६६.२
अधःऽअक्षाः ३.३३.९
अधःऽपदम् १०.१३३.४; १३४.२
अधःऽपदाः ८.५.३८
अधःऽपदात् १०.१६६.५
अधत्त २.२२.२
अधत्त १.९६.१; ६.८.३; ८.९६.१३; १०.१०२.८
अधत्तम् १.९३.५; ११६.८; १५; १६; ११७.१७; ११८.७^{2}; ८; १८०.३
अधत्थाः ५.३२.२
अधन्विषुः ९.२४.१; २
अधऽप्रिया ८.८.४
अधमः ७.१०४.१६
अधमः १.३३.५; ९; ५१.५; ८.३.२०
अधमत् ४.५०.४; ८.८९.२, १०.५५.८; ७२.२
अधमम् १.२४.१५; ५.३२.७
अधमान् ४.२८.४
अधमानि १.२५.२१
अधयत् १.१४४.२; ३.१.१०; ५.१.३, १०.३२.८
अधरः १.३२.९; ३.५३.२१

अधरम् २.१२.४; १०.९८.५; १५२.४; १६६.३
अधरा १.३३.१५; १०.१४५.३
अधराचः १०.१३१.१; १३३.२
अधराचीनम् २.१७.५
अधरात् १०.४२.११; ४३.११; ४४.११
अधरात् ६.१९.९; ७.७२.५; ७३.५; १०४.१९; ८.६१.१६; १०.२७.१५; ८७.२०; २१
अधरात्तात् १०.३६.१४
अधरान् १.१०१.५
अधराभ्यः १०.१४५.३
अधवन्त ७.१८.१५
अधस्तात् ३.३०.१६
अधाक् २.१५.४
अधात् ४.३४.१
अधात् १.१६४.३३; २.३८.४; ५; ५.४०.८; ६.६६.३; ७.८८.४
अधाम् १०.१४५.६^{2}
अधायि १.११९.२; ३.५.३; ८.४८.१०; ७४.७; १०.३१.३
अधायि १.६०.४; १०४.७; १६२.७; १८३.६; १८४.६; ५.७५.९; ७.७.४; २४.५; ३४.१४; १०.२९.१
अधारयः १.५१.४; ५२.८; २.१३.७; ६.१७.७; ८.१२.३०
अधारयः ८.७७.९; ९३.१३
अधारयत् १.६२.७; १३९.१०; २.१७.५; ३.४४.३; ८.४१.१०; ९६.१५; १०.४९.१०
अधारयत् १०.४४.८
अधारयतम् ५.६२.३
अधारयन् ३.२.७; ८.३६.१–६
अधारयन्त १.२०.८; १०३.१
अधाविष्ट ९.७०.८
अधि १.६.९; १०; १६.६; १९.६; २१.६; २५.१८; २८.९; २९.६; ३२.७; ३३.३; ४; ३५.६; ११; ३६.११; ३९.४; ४२.३; ४३.७; ४६.३; ४७.७; ४८.७; ४९.१; ५१.५; ११; ५४.११; ५६.२; ६४.४; ७१.१०; ७२.१०; ७३.४; १०; ८०.४; ६; ८२.४; ८३.३; ८४.१७; ८५.२^{2}; ७; १२; ८८.३; ९२.४; ११४.१०; १२३.४; १२५.५; १२६.१; १३२.१; १३९.२^{2}; ३; ४; ११; १४०.६. ११; १४४.५; १४६.३; १५५.३; १५७.६; १६३.२; १६४.२; ३; ५; १८; २२; २३; २९; ३९; ४२; १६६.१०; १८८.६; २.२.१०; ३.७; ८.५; १३.७; १६.२; २७.६; २९.५; ३०.३; ४०.४; ३.३.३; ५.९; ८.३; ७; १९.५; २१.५; २९.४; ५३.१६; ५४.९; ४.४.५; ५.७; ९; १७.१२; २०; १८.१२; २७.४; २८.२; ३०.१२; १४; १५; ३५.८. ३६.७; ३८.७; ४५.१; ५८.११; ५.३.७; ३३.३; ३६.३; ४४.१३; ५२.१७; ५५.९; ५६.१; ५७.६^{2}; ६०.७; ६१.१२; ६२.५; ६३.१, ७८.९^{2}; ८३.९; ८७.४; ६.६.४; ७.६; १६.१३; २०.९; ३४.१; ३५.२; ४; ३८.३; ४५.३१; ४८.५; ५९.८; ६३.५; ६५.६; ७५.३; १२; ७.१८.१४; २४.५; २५.३; २७.३; ३३.११; ३६.१; ६८.६; ७६.२, ५; ८३.२; ८८.३; १०३.५; ८.१.१८; २.८; ४.१३; ७.७; ८.७; १४; ९.१४; १०.१; ३; ४; १२.१७; १७.११; १९.३७; २०.११; १२; २२; २६; २३.२६; २४.७; २५.५; ७; २८.५; ३०.३^{2}; ३२.४; ३४.१३; ४१.४; ४२.३; ४५.३२; ४७.३; ११; ४८.१४; ४९.७; ६४.११; ६५.११; ६७.६; ६८.१९; ६९.५; १५; ७२.२; ७; ७५.१५; ८३.७; ९१.३; ९२.२०; ९७.५; ९.८.८; १२.३; ६; १४.१; १९.३; ४; २५.३; २६.१; ३; ५; २७.१; ५; २८.३; ३१.२; ५; ३७.४; ५७.४; ६३.८; २७; ६५.१६; २५; ६६.९; २९; ७१.९; ७२.९ ७३.२; ५; ६; ७५.१^{2}; २; ३; ७९.४; ८२.४; ८३.२; ८५.९; १२; ८६.३; ६; ८; २५; २७; ९१.१; २; ९२.४; ९४.१; ९६.१३; ९७.१६; ४०; ५३; १०१.११; १६; १०५.४; १०७.८; १४; १०.१.२; ४.३; १०.१; १३.३; १५.५; २१.३; २७.६; ३३.७; ४१.२; ४३.२; ४८.२; ४९.९; ६३.१;

११; ६४.२; १२; ६५.११; ७१.२; ७३.५; ७५.२; ८; ७८.८; ७९.२; ८२.६; ८५.१; ४६; ९०.५; ९३.१५; ९४.३; ९; १४; ९६.४; ९८.६; १००.४; १०४.९; १०५.५; ११०.६; १२१.६; ८; १२३.२–४; ७; १२७.१; १२८. ४; १२९.४; १३०.२; १३३.१–६; १३५.३; १३८.६; १५३.२; १६३.१; ३; १७३.१; ३; १९०.१; २

अधिऽअक्षः १०.१२९.७

अधिऽअक्षम् ८.४३.२४; १०.८८.१३

अधिऽअक्षेण १०.१२८.१

अधिऽअतिष्ठत् १.१६३.९; १०.८१.४

अधिऽअधत्तम् १.११७.८

अधिऽअस्थाः १.४९.२

अधिऽअस्थात् ५.३१.१

अधिऽआसते १.२५.९

अधिऽइतौ २.४.८

अधिऽइथ ७.५६.१५

अधिऽइमसि १.८०.१५

अधिऽइयर्ति १०.३२.३

अधिऽइव ८.७.१४

अधिऽएति ९.६७.३१; ३२

अधिऽक्षितः ८.४०.३; ४१.९

अधिऽक्षितम् १०.९२.१४

अधिऽक्षियन्ति १.१५४.२; ७.९६.२

अधिऽगार्त्यस्य ५.६२.७

अधिऽजज्ञे ८.५८.३

अधित १.१४४.५; ९.७१.९; १०.१२७.१

अधिऽतिष्ठथः ८.१०.६

अधिऽतिष्ठन् ३.३५.४

अधिश्राः ४.१७.६; ७; ६.३१.१

अधिऽनिर्निजः ८.४१.१०

अधिऽनीयमानः १०.८९.६

अधिऽपत्यम् १०.१२४.५

अधिऽपाः ७.८८.२; १०.८४.५

अधिऽभोजना ६.४७.२३

अधिऽमन्थनम् ३.२९.१

अधिऽरथम् १०.९८.४; १०२.२

अधिऽरथा १०.९८.१०

अधिऽरथानि १०.९८.९

अधिऽराजम् १०.१२८.९

अधिऽरुक्मा ८.४६.३३

अधिऽवक्ता १.१००.१९; १०२.११; ८.९६.२०

अधिऽवक्तारम् २.२३.८

अधिऽवस्त्रा ८.२६.१३

अधिऽवाकाय ८.१६.५

अधिऽविकर्तनम् १०.८५.३५

अधिऽसवन्या १.२८.२

अधिऽस्कन् १०.६१.७

अधिऽस्थानम् १०.८१.२

अधीताम् १०.४.६

अधीमहि ४.३२.१९

अधीरा १.१७९.४

अधीवासम् १.१४०.९; १६२.१६; १०.५.४

अधुः ४.१३.४

अधुक्षत् ८.७२.१६

अधुक्षत् १.३३.१०; १०.१४९.१

अधुक्षत ९.२.३

अधुक्षत ९.११०.८

अधुक्षन् २.३६.१; ८.३८.३; ६५.८

अधूनुत ८.५२.१०

अधूनुतम् ३.१२.६

अधूनुथाः ८.१४.१४

अधूनोत् १.५९.६

अधूर्षत ५.१२.५

अधूषत १.८२.२

अधृष्टः १०.१०८.६

अधृष्टम् ६.६७.२; ८.६१.३; ७०.३

अधृष्टाः ६.५०.४; १५; ६६.१०; ७.३.८; ८.६६.१०; १०.१००.१२; १०१.८

अधृष्टासः ५.८७.२

अधेनुम् १.११७.२०

अधेन्वा १०.७१.५

अधोक् ४.१९.७

अध्रजन् १.१६६.४

अध्रिऽगवे १.६१.१

अध्रिऽगावः १.६४.३; ८.२२.११

अध्रिंऽगुः ६.४५.२०; ८.७०.१; ९३.११
अध्रिंऽगुम् १.११२.२०; ८.१२.२; २२.१०; ६०.१७
अध्रिंगू इत्यध्रिंऽगू ५.७३.२; ८.२२.११
अध्रिगो इत्यध्रिऽगो ३.२१.४; ५.१०.१; ९.९८.५
अध्रिजः ५.७.१०
अध्रुक् ६.५१.५
अध्रुक् ६.५.१; ११.२; ६२.४; १०.६१.१४
अध्वगौऽइव ८.३५.८
अध्वन् १.३७.१३; ६.१२.३; २९.२; ५१.१५; ८.८३.६; १०.३७.१०
अध्वनः १.४२.१; ७१.९; ७२.७; १०४.२; १४६.३; ३.३०.१२; ४.५.१२; १६.२; ५.५३.७; ५४.१०; ६.१६.३; ७.६०.४; ८.२७.१७; ५९.२; १०.२२.४; ११५.३; १७९.२
अध्वनयत् ६.१८.१०
अध्वनि ६.४६.१३; ५०.५
अध्वनीत् ८.६.१३
अध्वने १.४२.८
अध्वऽभिः १.२३.१६; ९.५२.२
अध्वरः ८.१९.१९; २७.३; ९.७.३
अध्वरम् १.१.४; १४.११; १८.८; १९.१; २३.१७; २६.१; ४४.१३; ७४.१; ४; ९३.१२; १०१.८; १३५.३; ७[२]; १५१.३; ७; २.२.५; ३.१७.५; २०.१; २४.२; २८.५; ५४.१२; ४.२.१०; ९.६; ७; १५.२; ३७.१; ५.४.८; ५१.२; ७१.१; ६.५२.१२; ६८.१०; ७.२.७; ४२.५; ५६.१२; ८२.७; ९२.५; ८.३५.६; ४३.२०; ६३.६; ७२.९; ९.४४.४; ८३.५; १०.३०.११; ६३.६; ८५.१८; ९२.१५; ९४.१०; ११०.२
अध्वरऽश्रियः १.४७.८; ८.४.१४; १०.७८.७
अध्वरऽश्रियम् १.४४.३; १०.३६.८
अध्वरस्य १.१२८.४; ३.८.८; ११.१; २३.१; ६०.७; ४.३.१; ७.८; ५.४९.४; ७.७.१; ११.१; ४; १६.१२; ४२.१; ८.१०.४; १०.१.५; ७.५; ६६.१; १०४.६; १४०.५
अध्वरस्य ४.६.१; ६.१५.१४; ७.१४.२

अध्वरस्यऽइव ६.६६.१०
अध्वराऽइव ३.६.१०
अध्वराणाम् १.१.८; २७.१; ४४.२, ९; ४५.४; ३.३.८; १०.४; ४.७.३; ६.७.२; ८.८.१८; ११.२; ४४.७; १०२.७; १०.२.६; ४६.४; ६६.८
अध्वरान् १.४८.११; १३५.५; ८.३५.२१; १०.२.३; ३२.२; ७६.३
अध्वराय ३.२.७; ४.७.७; ७.२.३; ४१.६; ४३.२; ८२.१; ८.१९.२, १०
अध्वरिऽयताम् १.२३.१६; ४.९.५; ६.२.१०
अध्वरिऽयसि १०.९१.११
अध्वरिऽयसि २.१.२; १०.९१.१०
अध्वरे १.१२.७; १५.७; १६.३; ४७.२; ५७.३; ९४.१३; १२१.१; ७; १४२.१३; १६५.२; ३.४.४; ८.१; १०.१; ७; १४.७; १६.६; २७.४; १२; २८.३; ५३.१०; ५७.४; ४.९.४; १५.१; ५५.१; ५.२६.३; २८.६; ४४.५; ६.२.३; १०.१; १५.७; १६.२; ४६; ५०.९; ७.३.१; ७.४; १६.५; ३९.४; ८४.१; १०४.१८; ८.३.५; ७.६; १२.३१–३३; १३.३०; २७.१; ३५.२३; ४६.१८; ५०.१०; ६०.२; ६६.१; ७१.१२; ९३.२३; ९.६७.१; ७२.५; ८२.३; ९८.३; १०२.६; ८; १०.८.३; ११.४; १७.७; २१.६; ३०.१५; ४०.१०; ७७.८; ९४.१४; १२२.७
अध्वरेषु १.५८.७; ७७.२; १६२.१७; २.१.१३; ३.२७.८; २९.७; ५३.१; ६२.५; ४.७.१; ५१.२; ५.१.७; ४.१; १४.२; २२.१; २८.४; ६.४९.२; ६३.४; ७.१.१६; १०.५; ९२.२; ८.११.१०; ६०.३; १०.३०.४; ८; ७६.३; ९८.९; ११४.५
अध्वरेऽस्थाः १०.७७.७
अध्वयन्ता १.१८१.१
अध्वर्यवः २.१४.१–११; ३७.१; ५.४३.३; ७.२.४; ९८.१; १०.३०.२; ३; १४; १५
अध्वर्यवः १.१५३.१; ३.४६.५; ५.३१.१२; ७.९२.२; १०३.८; ९.९७.३७; १०.३०.६

अनमयत् ७.६.५
अनमस्यन् ६.९.७
अनमस्युः १०.४८.६
अनमीवः ७.४६.२; ५४.१
अनमीवम् १०.१४.११
अनमीवस्य ३.१६.३
अनमीवाः ३.२२.४; ६२.१४; १०.१७.८; १८.७; ३५.६; ३७.७
अनमीवाम् १०.९८.३
अनमीवासः ३.५९.३
अनम्नत १.१३१.१
अनयः २.१३.१२; ६.१.७
अनयत् ६.४५.१; ५७.४; ७.१८.७; ८.३३.१६
अनयत् ३.३३.६; ८.७०.१५, १०.९९.९
अनयत १०.६१.२७
अनयन् ६.१५.१७; १०.५३.७
अनयन् १.३१.४; ७.३३.२; १०.१५७.५
अनयन्त ४.३३.७
अनयन्त १.१४१.१; ३.७.६; ५.४५.१०; ६.२४.६
अनयम् ४.२६.२
अनर्या ९.६५.१२; २७.
अनर्तिषु: १०.९४.४; ५
अनर्वणः ५.५१.११; ८.३१.१२
अनर्वणम् १०.९२.१४
अनर्वणाम् १०.३६.११; ६५.३
अनर्वन् १.११६.१६
अनर्वम् १.१६४.२; १८५.३
अनर्वा १.९४.२; २.४०.६; ४.१७.२०; ५.४९.४; ७.२०.३; ४०.४; १०.६१.५; १३; ९९.३
अनर्वाणः १.१९०.६; ८.१८.२
अनर्वाणम् १.३७.१; ५१.१२; १३६.५; १९०.१, २.६.५; ६.४८.१५; ७.९७.५; ८.९२.८
अनर्विशे १.१२१.७
अनर्शनिम् ८.३२.२
अनर्शऽरातिम् ८.९९.४
अनवः ५.३१.४; ७.१८.१४
अनवद्य १.३१.९; १२९.१[२]; १७४.२; १०.१४७.२
अनवद्यः ९.६९.१०
अनवद्यम् १.७१.८
अनवद्यऽरूपाः १०.६८.३
अनवद्यस्य १.३३.६
अनवद्या १.७३.३
अनवद्याः १.१२३.८; २.२७.२, ३.३१.१३; ६.१९.४
अनवद्याभिः ४.३२.५
अनवद्यासः ७.५७.५; ९१.१
अनवद्यैः १.६.८.
अनवन्त ८.९६.५
अनवन्त ५.३०.१०; १०.९५.६
अनवऽपृग्णा १.१५२.४
अनवऽब्रवः १०.८४.५
अनवभ्रऽराधसः १.१६६.७; २.३४.४; ३.२६.६; ५.५७.५
अनवसः ६.६६.७
अनवऽस्यन्तः ४.१३.३
अनवऽह्वरम् २.४१.६
अनवायम् ७.१०४.२
अनवि ८.१०.५
अनविष्ट ९.७१.७
अनशामहै ८.२७.२२.
अनश्नन् १.१६४.२०
अनश्रवः १०.१८.७
अनश्वः १.१५२.५, ४.३६.१; ६.६६.७
अनश्वऽदाम् ५.५४.५.
अनश्वम् १.११२.१२; १२०.१०
अनश्वासः ५.३१.५
अनष्टऽपशुः १०.१७.३
अनष्टऽवेदसम् ६.५४.८.
अनष्टाम् ७.४५.२
अनसः ४.३०.१०; ८.९१.७
अनसा ३.३३.९; १०; १०.१०२.६
अनस्थः ८.१.३४
अनस्था १.१६४.४

अनिंऽमिषन्तः १०.६३.४
अनिंऽमिषम् ५.१९.२; ७.६१.३
अनिऽमिषम् १.२४.६
अनिंऽमिषा ३.५९.१; ७.६०.७
अनिऽमिषाः २.२७.९
अनिऽमिषेण १०.१०३.२
अनिंऽमेषम् १.३१.१२; १६४.२१
अनिंराः ८.४८.११
अनिंराम् ७.७१.२; ८.६०.२०; १०.३७.४
अनिरेण ४.५.१४
अनिंऽविशमानाः ७.४९.१
अनिंऽवृतः ३.२९.६
अनिऽवेशनानाम् १.३२.१०
अनिंऽशितम् २.३८.८; ९.९६.२
अनिंशितऽसर्गाः १०.८९.४
अनिषङ्गाय १.३१.१३
अनिषव्याः १०.१०८.६
अनिंःऽस्तृतः ८.३३.९
अनीकम् १.११३.१९; ११५.१; १२१.४; १२४.११; १६८.९; २.३५.११; ३.३०.१३; ४.५.९; १५; ११.१; १२.२; ५.२.१; ४८.४; ७६.१; ६.४७.२८; ५१.१; ७.१.८; ९; ८८.२; ८.९६.९; १०.२.६; ७.३; ४३.४; ४८.३; ६९.३
अनीका ३.१९.४; ४.२३.७
अनीके ४.५८.११; ६.४७.५; ७.४.३; ८.७४.४; १०२.१३; ९.९७.२२
अनीकेन २.९.६
अनीकेषु ८.२०.१२
अनीकैः ३.१.१५; ५४.१, ४.१०.३; ७.८.५
अनीळः १०.५५.६
अनीताम् १.१२१.५
अनीनशात् १०.१६२.२
अनीयत ८.५६.४
अनु १.६.४; ५; १०.१२; १५,५; २३.२३; २५.१६; ३०.९; ३२.१; ३३.११; ३४.२; ३७.९; ३८.११; ४४.१०; ४६.१४, ४९.३; ५०.३; ६; ५२.४; ९; ११; १४; १५; ५७.२; ५; ६१.१५; ६५.१; २; ७१.६; ८०.१–७; ८[२]; ९[२]; १०–१६; ८२.३; ८४.६; १०–१२; ८५.३; ८६.३; ८८.६; ९१.१; २१; ९५.३; १०२.१; १०३.७[२]; ११३.८; १०; १३; ११६.१७; १२०.११; १२१.२; ३; ७; ११; १२४.३; १२६.३; ५; १२७.१;४; १२८.१[२]; १३२.३; १३४.१; १३६.५; १३८.३; १४०.९; १४१.३; ५; ९; १४७.२; ४; १४८.४[२]; १६१.३; ११; १६२.७; १६३.७; ८[६]; १२; १६४.९; २८; १६५.५; १६६.१०; १६७.१०[२]; १७३.८; १७५.६; १७६.२; ६; १८०.८; १८१.५; १८२.८; १८३.२; ३; १८४.४; १८५.४; १८७.४; १९०.५; १९१.१५; २.१.१०; १५.२; ४; ५; ८; ५.३; ४; ८.५; १३.३; १०; १३; १४.१२; १६.३; २०.८; २१.३; २४.१३[२]; २८.२; ६; ३०.२; ३१.३; ३६.६; ३७.१; ३८.३; ५–७; ४२.२; ४३.१; ३.१.१७; ४.७; ६.७; ७.६[२]; ७; ८; ९.४; १२.७; १५.३; १७.१; ५; २३.२; २६.८; ३०.४; ३१.१७; ३२.११; ३३.३; ४; ३४.८; ३५.८; ३९.८; ४३.१; ४७.३; ५०.२; ५१.९–११; ५५.४; ७; ६१.१; ४.४.१; २; ८; ९;११; १३.२; १६.१८; १७.१; ५; १८.३[३]; ११; २०.२; २२.७[२]; २६.२; २७.१; २९.३; ३०.२; १९; ३२.२२; ३३.६; ३५.१; ३७.४; ३८.३; ५; ४०.३; ४[२]; ४५.६; ४८.३; ५२.६; ५७.३; ७; ५८.४; ५.२.८; ११.६; १२.२; २९.२; ५; ३०.२; ३२.१०; ३३.२; ३४.१; ३६.२; ४०.९; ४४.१; ३; ४६.४; ४९.४; ५१.१५; ५२.६; ५३.२; ५; ६; १०; ११; १६; ५४.६; ५५.१–९; ५९.१; ६१.१९; ६२.२, ४; ५; ६९.१; ७३.४; ७८.२; ८०.४; ८१.२; ३; ८६.५; ६.१.२; ३; १५.९; १७.१२; १८.१४; १९; २०.२; २१.६; २३.८; २५.८[५]; २८.४; ३६.२[२]; ४६.१४; ४७.८; ४८.२२; ५२.१; ५४.५; ६; ६३.६–८; ६४.५; ६६.४[२]; ६७.६; ११; ७२.३; ७५.६, १८[२]; ७.३.२; ७.२; १८.१२[२]; २५; २१.७, ३१.७; ९;

३३.७; ३४.२४^{२}; ३८.६; ४५.२; ५६.१३; ६३.५; ७०.४; ७६.४; ७७.३; ८२.३; ८७.७; ९०.४; ९९.१; १०३.४; ८.१.१४; २८; ३४; २.३३; ३.८; ४.८; १०; २०; ६.३८^{२}; ७.१६; २४^{२}; ९.२; १०.६; ११.८; १३.६; १५.६; ९; १७.५; १९.३५; २०.७; २१.१८; २५.१६; १७; ३२.१९^{२}; ४०.८; ४१.३; ७; १०; ४३.९; २१; ४७.११; ४८.२; १३; ४९.३; ५८.२; ६१.५; ६२.७; ११; ६३.५; ६९.१८^{२}; ७०.५, ७६.११; ८८.५; ९६.१६; ९९.६; १०३.२; ९.२.४; ६.४; ८.४; १७.८; २२.६; २३.२; २९.१; ५४.१, ६३.६; ७०.३; ४; ७२.३; ८२.५; ८६.२४; ४२; ९२.३; ९६.१८; ९७.५; ३२; ५५; १०३.५; १०९.७; ११०.२; १११.३; ११२.३; ११४.१; १०.२.३; ६; ७; ६.७; ७.२; ९.९; ११.३; १२.३; १३.३^{२}; १४.१; २; १२; १७.५; ११^{४}; १८.१; १९.१; २७.५; १३; १७; २८.८; २९.२; ३२.६; ३७.३; ५^{२}; ४०.९; १०; ४३.५; ४५.११; ४६.२; ५१.६; ५३.६; ५६.३^{२}; ५; ६१.२१; ६३.३; ६६.८; १३; ६७.९; ६८.१२; ७१.३; ७२.३; ५; ७३.८; ८५.१४; ३१; ८७.१९; ८९.१३^{६}; ९१.७; ९५.५; ९७.१९; १०३.६^{२}; १०५.२; १०६.९; १०९.५; ११३.१; ११५.६; ११७.५; १२०.१; १२२.२; १२४.९; १२५.७; १३५.१; ४; १३६.२; १४२.७; १४५.६; १४७.१; १४९.३; १५९.२; १६८.२

अनुऽअर्तिता १०.१०९.२

अनुऽअविन्दत् २.१२.११

अनुऽअवैत् १०.१३९.४

अनुऽआलेभिरे १०.१३०.५

अनुऽऊहिरे १०.१५.८

अनुऽएतवे ७.३३.८

अनुऽएतवै १.२४.८; ७.४४.५

अनुऽएषि १०.१४२.५

अनुकामऽकृत् ९.११.७

अनुऽकामम् १.१७.३; ८.४८.८; ९.११३.९

अनुऽकामा ८.९२.१३

अनुवथाः ५.२.३

अनुऽक्षरन्ति ८.६९.१२

अनुऽगायसम् ८.५.३४

अनुऽग्मन् ३.३९.५

अनुग्रः ७.३८.६

अनुग्रासः ८.१.१४

अनुऽघुष्य १.१६२.१८

अनुऽचक्रदे ८.३.१०

अनुत्तम् १.८०.७; १६५.९; ७.३४.११

अनुत्तऽमन्युः ८.९६.१९.

अनुत्तऽमन्युम् ७.३१.१२; ८.६.३५

अनुत्ता ८.९०.५

अनुत्ताः ३.३१.१३

अनुदः १०.१८०.३

अनुदकाः ७.५०.४

अनुऽददाति २.१२.१०

अनुदितासः १०.९५.१

अनुऽदृश्य १०.१३०.७

अनुदेथाम् १.११६.९

अनुऽदेयम् ६.२०.११

अनुऽदेयी १०.८५.६; १३५.५; ६

अनुद्रे १०.११५.६

अनुऽधूपितासः २.३०.१०

अनुऽनोनुवतः ८.९२.३३

अनुपऽक्षितम् ३.१३.७; १०.१०१.५

अनुऽपथाः ५.५२.१०

अनुऽपस्पशानम् १०.१४.१

अनुऽपूर्वम् १.११७.३; १०.१८.५; ६; १३१.२

अनुऽब्रुवाणः ५.४४.१३

अनुऽभर्त्री १.८८.६

अनुऽभूतम् १०.६१.५

अनुऽमते १०.५९.६

अनुऽमत्याः १०.१६७.३

अनुऽमदन्ति १.१७३.७; ३.४७.४; १०.१२०.४

अनुऽमदाम १.१०२.३

अनुऽमद्यमानः ७.६३.३; १०.९८.८

अन्तरम् १.१०.९; ६.७५.१९; ७.१०१.५; १०.८२.७
अन्तरस्य ६.१५.३; १०.११५.५
अन्तरा १०.९१.१३
अन्तरा ३.४०.९; ९.८६.१३; १०.८६.१६; १७; ८८.१५; १३९.२; १६२.४
अन्तरान् ३.१८.२
अन्तराम् १.१०४.६
अन्तरिक्षऽप्राः ७.४५.१; ९.८६.१४.
अन्तरिक्षऽप्राम् १.५१.२; १०.९५.१७
अन्तरिक्षप्रुत्ऽभिः १.११६.३
अन्तरिक्षम् १.५२.१३; ७३.८; ८९.१०; ९१.२२; ११५.१; २.१२.२; १५.२; ३.८.८; २२.२; ३०.९; ३४.१०; ५४.१९; ४.१४.२; ५२.७; ५३.५; ५७.३; ५.१.११; ४२.१६; ५४.४; ५५.२; ८५.२; ३; ६.८.२; ४७.४; ६१.११; ६९.५; ७.३५.५; ९८.३; १०४.२३; ८.१४.७; ९.८१.५; १०.५३.५; ५९.७; ६५.२; ६६.९; ११; ८८.३; ८९.६; ९०.१४; १२४.६; १२८.२; १३९.२; १४९.१; १५३.३; १९०.३
अन्तरिक्षऽसत् ४.४०.५
अन्तरिक्षस्य १.११०.६
अन्तरिक्षा ६.२२.८; ७.७५.३
अन्तरिक्षाणि १.३५.७; ८.६.१५; १२.२४; १०.४४.८; ६५.४
अन्तरिक्षात् १.४८.१२; ६१.९; ३.३०.११; ४६.३; ५.५३.८; ८.३.२०; ८.३; ४; ९.६३.२७; १०.६८.५; ७०.११; ८९.११; १५८.१
अन्तरिक्षे १.३५.११; १६५.२; २.१४.३; ३०.३; ४०.४; ३.६.७; ५.५२.७; ७३.१; ८५.५; ६.४६.११; ५२.१३; ५८.३; ७.३९.३; ८.९.२; १०.६; ९७.५; ९.२७.६; १०.५.५; ६०.५; ८७.३; ६; १२१.५; १६८.३.
अन्तरिक्षेण १.२५.७; १६१.१४; ८.७.३५; ९.५.२; ६३.८; ६५.१६; १०.१३६.४
अन्तरिक्ष्या ९.३६.५; ६४.६
अन्तरिक्ष्याः ५.५४.९
अन्तरिति १.६२.९; ६७.५; ११६.२४; १३२.३; १५७.५; १५९.४; १६३.४; १६४.९; १७; ३१; २.२७.३; ४०.२; ३.३१.२१; ५४.९; ५५.५; १५; ५८.१; ४.१.७; ७.८; १३.४; २७.४; ५१.३; ५८.११; ५.६२.५; ६; ६.४.४; ९.५; ४४.२३; २४; ५८.३; ६६.४; ७२.४; ७.७१.५; ८.३९.१; ४८.२; १००.९; १०१.९; १४; ९.१२.५; ७; १५.३; ७०.५; ९६.७; १०.२७.९; १७; ४५.४; ४६.६; ४८.१०; ५७.१; ७९.३; १२५.७; १७७.१–३; १८३.३; १८९.२
अन्तरेण १०.३३.१
अन्तरैः ६.६२.१०
अन्ता ४.१.११
अन्ताः ७.६७.२; ८३.३; १०.८२.१
अन्तात् १.३०.२१; ३.६१.४; १०.८९.११
अन्तान् १.९२.११; ४.५०.१; ५.४७.४; ५९.७; ६.६२.१; ७.४५.२; ६९.३; ८.२५.१८; १०.८.१; २०.४; ८९.१; १०८.५
अन्ति १.७९.११; ८४.१७; ८९.९; ९४.९; १६७.९; १७६.१; २.२७.३; ४.२.१८; ४.३; ५.१०; ५.४४.११; ७६.२; ८.११.४; ७३.१–१८; ९.१९.७; ६७.२१; ९१.४
अन्तिऽऊतिम् १.१३८.१
अन्तिकम् १०. १६१.२
अन्तिके ९.७८.५
अन्तिऽगृहात् १०.९५.४
अन्तितः १.१७९.५; २.२७.१३; ३.५९.२; ५.१.१०; ८.२७.९; १०.११४.४
अन्तिऽदेवम् १.१८०.७
अन्तिऽवामा ७.७७.४
अन्ते ४.१६.२; १०.३४.११
अन्तेभ्यः १.४९.३; ८.८८.५
अन्तेषु ७.७९.२
अन्तौ ५.४७.३
अन्धः १.६२.५; ९४.७; १२२.१; १५३.४; २.१४.१; ३.३५.१; ४.१.१९; १६.१;

२३.१; २७.५; ५.३०.६; ४५.९; ६.६३.२; ६८.११; ७.२१.१; ८८.२; ९२.१; ८.२.१; ९.६२.५; ६८.६; ८६.४४; १०.११६.४
अन्धः १.११४. १६; ४.१९.९; ८.७९.२
अन्धम् १.११२.८; ११६.१६; १४७.३; २.१३.१२; ४.४.१३; ३०.१९; १०.२५.११
अन्धसः १.९.१; ५२.३; ८०.६; ८२.५; ८५.६; १३५.४; १५५.१; २.१४.५; १९.१; ३६.३; ३७.१; ३.४०.१; ४१.६; ४८.१; ४.३१.२; ३२.१४; ५.३४.२; ५१.५; ६.४२.४; ४३.४; ४५.२७; ६३.३; ७.२१.१; ९०.१; ८.१.२५; १३.१५; २१; १७.४; ८; २४.१६; ३२.२८; ३३.४; ७; ३५.२४; ४६.१४; ६१.३; ६५.२; ६६.२; ७८.१; ८८.१; ९२.१; ४; ९५.२; ९.१८.२; ५१.३; ५५.२; ५८.१; ६१.१०; १०१.१; १३; १०.२५.१; ३२.१; ५०.१; ७; ७६.६; ९४.८; ९६.९; ११५.३; १४४.५; १६७.२
अन्धसा १.५२.२; ५; ४.२०.४; ५.५४.८; ७.२०.४; ९.१.४; १६.२; ५२.१; ५५.१; ३; ६१.१९; ६७.२; १०७.२
अन्धसी इति ७.९६.२
अन्धस्य १०.३९.३
अन्धा ४.१६.४
अन्धांसि १.२८.७; ६.६९.७; ७.५९.५; ६८.२; ७३.४
अन्धांसिऽइव ५.४१.३
अन्धाः १.१४८.५
अन्धाम् १०.२७.११.
अन्धाय १.११७.१७; १८
अन्धे १.१००.८
अन्धेन १०.८९.१५; १०३.१२
अन्नऽकामाय १०.११७.३
अन्नम् १.१४०.२; २.२४.१२; ३५.५; ७; १०; ११; १४; ३.४८.३; ४.२.७; ११.१; १२.१; ६.४.४; ५; ४१.३; ७.९८.२; ८.४.१२; १०.५९.२; ६१.४; ६९.२; ७९.५; ९१.५; ९९.५; १०७.७; ११२.४; ११३.८; ११७.६; १२५.४
अन्नऽवान् १०.११७.२
अन्नऽवृधम् १०.१.४
अन्ना १.६१.७; १२२.१३; १२७.४; ३.३९.८; ४.७.१०; ११; ५.८.५; ७.३.४; ४.९; १०.९१.७
अन्निऽयते ४.२.७
अन्ने १०.२९.४
अन्नेन १०.९०.२
अन्नेषु २.२३.१६
अन्नैः २.१०.४; ३५.१२; ३.५०.१; १०.१.४; ५.४; २८.११, २९.३; ५
अन्यऽउदर्यः ७.४.८
अन्यः १.५२.१३; ५७.४; ८४.१९; १२५.७; १६१.९; १६४.२०[२]; १८१.४[२]; २.४०.४[२]; ५[२]; ३.३१.२[२]; ५.३२.३; ७७.२; ६.२१.१०; ३०.४; ४८.२२; ५२.१६[२]; ५७.२[२]; ६८.३[२]; ७.३२.२३; ३६.२; ५६.१५; ८२.२[२]; ५; ६[२]; ८३.९[२]; ८५.३[२]; १०३.३–५; ८.५.३९; १५.११; ६६.१३; ७८.४; १०.१०.१४; २८.१; ३४.१४; ४३.५; ६४.२; ८५.१८[२]; ११९.११; १३२.४; १३७.२[२]; १४६.५
अन्यऽकृतम् ६.५१.७
अन्यऽकृतेन २.२८.९
अन्यऽकृतेभ्यः ८.७९.३
अन्यके ८.२१.१८; ३९.१–१०; ४०.१–११; ४१.१–१०; ४२.४–६
अन्यकेषाम् १०.१३३.१–६
अन्यऽजातम् ७.४.७; ५२.२
अन्यत् १.३०.१९; ५२.१४; १०३.१[२]; ११५.५[२]; १२३.७[२]; १४०.७; ३.५५.११[२]; १५[२]; ५.२९.१०[२]; ३१.२; ७३.३; ६.२४.५[२]; ५८.१[२]; ६६.१; ७.३२.१९; ८.१.१; २.१७; २२.४; १०.२७.२१; ३१.८; ३७.२; ३; ८२.७; १२९.२; १४२.१; १४९.३
अन्यतः १.४.५
अन्यत्ऽअन्यत् २.२४.५; ३.३८.७
अन्यत्र ७.५९.५; ८.२४.११; १०.८६.२

अपऽश्रितः ५.६१.१९; ८.२४.३०
अपऽश्रितम् १.८४.१४
अपसः ३.१२.७; ६.६९.१
अपसः १.७१.३; ९२.३; २.२८.५; ३.२.७; ८.५; ६०.३; ४.३३.१; ५.४२.१२; ६.१७.१२; ८.२.१७; ९.७२.६; १०७.१३
अपसम् १.२.९
अपसा १.५४.८; ४.२.१४
अपसा १.३१.८
अपसाऽइव ६.६७.३; १०.१०६.१
अपसाम् १.९५.४; १६०.४; ३.२.५; ६.६१.१३; १०.५३.९; ७५.७
अपसि ३.१.३; ११
अपऽसु ८.४.१४
अपऽसेधन् १.३५.१०; ९.८२.२
अपऽस्पृण्वते ८.२.५
अपस्पृधेथाम् ६.६९.८
अपऽस्फुरम् ८.६९.१०
अपस्यम् १०.८९.२
अपस्यया ५.४४.८
अपस्यवः ९.१४.२
अपस्यात् १.१२१.७
अपस्याम् ७.४५.२
अपस्युऽभिः ९.७६.२
अपस्युवः १.७९.१; ९.२.७; ३८.३; ५६.२; १०.१५३.१
अपऽह्नुवे १.१३८.४
अपा ८.४.३
अपांसि १.६८.३; ७०.४; ८५.९; १७४.३; २.३.६; १७.८; ३.३.३; ४.१९.१०; ५.४७.६; ७.२१.४; ६३.४; ८.९६.१९; २१
अपाः ३.५३.६; ५.२९.८; ६.३९.१; १०.९६.१३
अपाक् ३.५३.११; ८.४.१; १०.५; ६५.१; १०.४४.७
अपाकः ६.११.४
अपाकऽचक्षसः ८.७५.७
अपाका १.१२९.१
अपाकाः १.११०.२
अपाकात् ८.२.३५
अपाके ६.१२.२
अपाक्तात् ७.१०४.१९
अपाङ् १.१६४.३८
अपाचः १०.१३१.१
अपाचीः ५.४८.२
अपाचीनम् ७.७८.३
अपाचीने ७.६.४
अपाचीम् १०.६७.५
अपाच्याः ८.२८.३
अपात् २.३७.४; ६.३८.१; ८.६९.११[२]; ९२.४
अपात् १.३२.७; १५२.३; ४.१.११; ६.५९.६
अपादः १०.९९.४
अपादम् ३.३०.८; ५.३२.८
अपादयत् २.११.१०.
अपाम् १०.३०.४; ११९.१–१३; १४९.२
अपाम् १.२२.६; २३.१९; ३२.११; ४६.४; ५१.४; ५४.१०; ५६.५; ६१.१२; ६७.५; ७०.२; ८५.९; १००.११; १२२.३; ४; १३४.५; १४३.१; १४४.२; १४९.४; १५८.६; १६४.५२; १६८.२; १८१.१; १८६.५; १८७.८; २.४.२; १२.७; १७.५; १९.३; २३.१८; ३०.१; ३१.६; ३५.१–३; ७; ९–११; १३; ३.१.५; १२; १३; ५.३; ९.१; २५.५; ४५.२; ४.२१.८; ४०.१; ५८.११; ५.४१.१०; ४६.७; ६.८.४; १३.१; ३; १७.१२; ४४.१८; ४७.२७; ५०.१३; ५२.१४; १५; ६४.१; ७.९.३; ३४.१५; ३५.१३; ४७.२; ८२.३; ८८.३; ८९.४; १०१.२; १०३.४; ८.१४.१०; १३; १६.२; १८.१६; १९.४; २५.१४; ४४.१६; ९३.२२; ९.३३.१; ४९.१; ७२.७; ७४.३; ७६.५; ८६.८; २५; ३६; ९६.१९; ९७.४१; ५७; १०८.१०; १०९.१३; १०.८.१; ५; १७.१४; ३०.३; १४; ३६.८; ४५.३; ४६.१; २; ४९.२; ५१.८; ७७.४; ८९.१०; ९२.१३; ९३.५; ९८.१२; १२३.१; १२४.९; १४२.७; १६८.३

अपाम ८.४८.३
अपाम्ऽईव १.५७.१; ९.९५.३; १०८.५
अपायि १.१७५.१; २.१९.१
अपायि ६.४४.८; १६
अपारः ५.८७.६; ८.६.२६
अपारम् ४.१७.८
अपारयत् २.१५.५; ४.३०.१७
अपाराम् ३.३०.९
अपारे ३.१.१४
अपारे इति ३.३०.५; ४.४२.६; ९.६८.३
अपारेण १०.४४.१
अपालाम् ८.९१.७
अपाविषुः ९.६०.२
अपाष्ठऽवत् १०.८५.३४
अपि १.१२१.१३; १२८.२; १४०.७; १५८.५; १६२.२; ८; ९; १४; १६४.६; १७९.१; १८६.१; २.३.९; ५.८; ११.१२; ३४.१०; ३.१.२१; ८.९; ३३.२; ८; ३८.६; ५९.४; ५.३१.९; ३३.१०; ४६.७; ६.३६.२; ४७.१३; ५१.१६; ५४.४; ५९.९; ६२.१०; ६८.६; ७.३.१०; ४.१०; १६.८; २१.५; २२.५; ३१.५; ३८.३; ४७.३; ५७.४; ६०.६; ८.१८.१९; १९.८; ३१.७; ३२.७; ४०.६; ४३.७; ४४.२४; २८; ४५.१९; ४७.८; ५६.४; ६६.१३; ९१.१; ९७.१२; ९.६९.१; ७१.६; १०.२.३; १२.५; १३.५; १४.६; १९.४; ५; २०.१; २५.१; ४४.४; ४८.३; ५२.३; ५६.४; ७१.५; ६; ७७.७; ८६.४; ८७.२; १६; ९५.१८; ९८.११; १०४.१०; १२०.३; १३१.७; १४२.१; १५४.१–५; १६६.३; १६७.४
अपिऽइतेः १.१२१.१०
अपिऽइत्यै २.४३.२
अपिऽइव ३.३८.८; ७.१८.६
अपिऽऊहे ७.१०४. १४.
अपिऽएति १०.११५.१
अपिंशत् १०.११०.९
अपिंशत ३.६०.२
अपिंशत १.११०.८; १६१.९
अपिंशन् ४.३३.४
अपिंशन् १०.६८.११
अपिऽकक्षे ४.४०.४
अपिऽकक्षेभिः १०.१३४.७
अपिऽकक्ष्यम् १.११७.२२
अपिऽकर्णे ६.४८.१६
अपिऽजुवा २.३१.५
अपितः ७.८२.३
अपिधानऽवन्तम् ५.२९.१२
अपिऽधाना १.५१.४; १६२.१३
अपिऽधीन् १.१२७.७
अपिऽनद्धम् १०.६८.८
अपिन्वः २.११.२
अपिन्वः ९.९७.३१
अपिन्वत् १.६२.६; १०.९९.१
अपिन्वत् ४.१९.७
अपिन्वत १०.७२.७
अपिन्वत ३.५५.१३; १०.३१.११
अपिन्वतम् १.११७.२०; ११८.८; ७.६८.८; ८२.३; १०.३९.१३
अपिन्वम् ४.४२.४
अपिप्रत ५.३४.२
अपिऽप्राणी १.१८६.११
अपिबः ३.३२.९; ३६.३; ५१.७; ५.२९.११; ६.४०.२; ८.५१.१; ५२.१; १०.१३१.५; १३८.२
अपिबः ३.३२.१०; ४८.२; ४.३५.७; ८.४.४
अपिबत् ८.४५.२६; ५२.३; १०.१३६.७
अपिबत् १.३२.३; २.१५.१; २२.१; ३.४८.४; ४.१८.३; ८.७७.४; १०.१०२.४
अपिऽयन्तम् १.१६२.२०
अपिऽरिप्राय १.११८.७; ८.५.२३
अपिऽवातयन्तः १.१६५.१३
अपिऽवृतः १०.३२.८
अपिऽवृतम् १.१२१.४; २.११.५
अपिऽवृताः १.१९०.६
अपिऽशर्वरे ३.९.७; ८.१.२९
अपिऽस्थितम् १.१४५.४
अपिऽहितम् १.३२.११; ५.६२.१; १०.१२९.३

अपिहिताऽइव ४.२८.१
अपिऽहितानि ४.२८.५
अपीच्यः ८.४१.८
अपीच्यम् १.८४.१५; २.३५.११; ८.३९.६; ४७.१३; ९.७१.५; ७५.३; ८६.१०; ८७.३
अपीच्या ८.४१.५
अपीच्ये १०.१२.८
अपीच्येन ७.६०.१०; १०.५३.११
अपीपतत् ८.१००.७
अपीपयत् १०.६४.१६
अपीपयन्त ७.३६.३
अपीपरन् ९.७३.१
अपीपेत् १०.३१.११
अपीपेम ८.६६.७
अपीप्यन् ८.९९.१
अपुः १.१६४.७
अपुनन् ३.२.९
अपुनरिति १०.६८.१०
अपुपोत् ३.२६.८
अपुरुषऽघ्नः १.१३३.६
अपुरुषम् १०.१५५.३
अपुष्पाः १०.९७.१५
अपुष्पाम् १०.७१.५
अपूपम् ३.५२.७; १०.४५.९
अपूपऽवन्तम् ३.५२.१; ८.९१.२
अपूर्व्यं ८.२१.१; ८९.५
अपूर्व्यः १.१३४.६
अपूर्व्यम् ३.१३.५; ५.५६.५; ८.१८.१; १०.२३.६
अपूर्व्या १.४६.१; ६.३२.१; ८.६६.११
अपृक्त ९.९७.१
अपृच्छत् १.१६१.४; १३
अपृच्छम् ५.३०.२
अपृच्छ्यन्त १.११०.४
अपृणः ३.३.१०
अपृणक् ४.१९.७
अपृणत् २.१५.२; २२.२; ३.२.७; ३४.१
अपृणतः ५.७.१०; ६.४४.११
अपृणन् १०.११७.१
अपृणन्तः ५.४२.९
अपृणन्तम् १.१२५.७; १०.११७.७
अपृणाः ३.६.२; ७.१३.२
अपृणात् ४.१८.५; १०.४५.६; ५५.३
अपृतन्यत् १.३२.७
अपेशसे १.६.३
अपो इति २.२८.६; ५.४८.२; ७.८१.१; ८.६७.१५; १०.८८.१२
अप्ऽजाः ४.४०.५
अप्ऽजाम् ७.३४.१६
अप्ऽजित् ९.७८.४
अप्ऽजिते २.२१.१
अप्ऽतुरः १.३.८; ११८.४; २.२१.५; ९.६३.५
अप्ऽतुरम् ३.२७.११; ५१.२; ९.६१.१३; ६३.२१; १०८.७
अप्ऽतूर्यम् ३.१२.८
अप्ऽतूर्ये ३.५१.९
अप्त्यस्य १.१२४.५
अप्नः १.११३.९; २०; १०.३६.१३; १०६.९
अप्नःऽस्थः ६.६७.३
अप्नऽराजौ १०.१३२.७
अप्नवानः ४.७.१
अप्नवानऽवत् ८.१०२.४
अप्नसः १०.८०.२
अप्नस्वती १०.४२.३
अप्नस्वतीम् १.११२.२४
अप्नस्वतीषु १.१२७.६
अप्यः १.१४५.५; ६.६७.९; ९.८६.४५
अप्यम् २.३८.७; ८; १०.८६.१२
अप्या १०.१०.४; ११.२; ९५.१०
अप्याः ३.५६.५; ६.५०.११; ७.३५.११; ९.१०८.६
अप्यानि ६.४९.६
अप्येभिः ४.५५.६
अप्रऽआयु ५.८०.३
अप्रऽआयुवः १.८९.१
अप्रऽआयुषे १.१२७.५

अभयम् २.२७.११; १४; ४१.१२; ३.४७.२; ४.२९.३; ६.२८.४; ४७.८; १२; ७.७७.४; ८.६१.१३; ९.७८.५; १०.६३.७; १३१.६

अभयम्ऽकरः १०.१५२.२

अभयानाम् १०.९२.१४

अभयानि ९.९०.४

अभये ३.३०.५

अभरः ८.९७.१

अभरत् ८.८२.९; ९.६८.६; १०.१४४.४; ५

अभरत् १.१३०.७; १६१.१०; ३.५३.१६; ४.२६.७; ६.८.४; ८.७७.१०; १००.८; ९.७२.३; ८६.२४; ११३.३; १०.११.४; १७.२; ७२.९; १०२.४; ११३.५

अभरन् ४.३३.४

अभरन् १०.१८१.३

अभरन्त १०.९२.१०

अभरम् १०.६०.१०

अभरिष्यत् २.३०.२

अभवः ३.३.१०; ९.२; ६.१.१; ८.७६.११; ९३.१७; १०.७०.९

अभवः १.४.८; ३१.१; ३२.१२; ५१.१३; ७२.७; ९१.२; २.१३.९; १०; ३.१.१७; ६.५; ३२.१०; ४.१७.६; ६.५.३; ३०.५; ३६.१; ८.९६.१६; ९.५९.४; ८६.२३; १०७.६; ७; १०.८.४; ८८.५; १११.६; १५३.५

अभवत् १.५८.१; ११२.४; १४६.५; १९०.२; ७.१०.५; ३३.६; १०.३१.६; ६१.६; ९२.१५; १३५.५; ६; १५९.४; १७४.४

अभवत् १.३२.९; ५९.२; १४१.४; १४३.२; १४६.४; २.५.३; १३.१; २२.२; २४.१४; ३.२.२; ८; २९.११; ३१.४; ७; ३४.१०; ४.३.११; ३३.९; ३६.३; ५.११.३; ४; ६.१८.२; ६; २०.३; ४४.७; ५७.४; ६५.५; ७.८३.४; ९८.५; १०४.२१; ८.७७.३; ८९.२; ९.८६.२१; १०.४५.८; ८५.९; ८८.२; ८; ९०.४; ९६.४; ११०.११; ११३.२; १३०.४; १४९.३; १५०.४

अभवत ४.३५.८[२]

अभवतम् १.११७.१४

अभवन् ३.३५.९

अभवन् १.११९.८; ४.१७.६; ७.८३.७

अभवम् ४.२६.१

अभागः १०.८३.५

अभारित्थभाः १०.२०.१०; ९९.१२

अभार्षम् १०.१३७.४

अभि १.५.१; १०; १०.४[२]; ११.२; ८; १५.३; १९.९; २२.११; २४.३; २५.११; ३१.१८; ३३.९; ११; १३; ३५.९; ३७.१; ४२.४; ८; १०; ४५.८; ४८.७; १४; ५१.१[२]; २; १०; ५२.५; ५४.२; १०; ६१.१०; ७१.७; १०; ७४.८; ७८.१[२]; २–५; ८०.३; १२; ८४.४; ८६.५; ८९.२; ९१.२३; ९२.१०; ९४.८; ९५.१०; १००.१७; १०१.६; ७; १०५.१९; १०८.१; ६; ११०.७; ११५.२; ११७.२१; ११८.४; ११९.१; १२०.८; १२१.६; ८; १२३.७; १२४.९; १२५.७; १३४.१; १३५.४; ६; १३६.५; १३९.३; ८; १४०.२; ३; ५; ६; १३; १४४.१; २; १४५.४; १४६.२; ३; १४९.४; १५४.५; १५६.२; १६०.२; ५; १६२.११; १५; १६४.३; २०; २७; २८; ४४; १६६.१४; १७०.१; १७४.५; १७८.४; ५; १७९.३[२]; १८३.२; १८९.३; १९०.४; ६; २.२.२; ४.२; ७; ९; ८.४; ६; ९.४; १४.९; १५.५; १६.८; १७.४[२]; २०.२; २२.२; ४; २३.६; ९; १६; २४.४; ६; २५.३; २६.१; २७.१४; २८.१; ३; २९.२; ३१.२; ३३.१; ७; ३४.९; ३९.७; ४१.१०; ४३.१; ३.१.४; १६; ४.५; ६.१०; ११.७; १४.४; १५.५; १६.२; ४; २३.२; २९.१३; ३०.८; ११; ३१.४; ५; १०; ३२.१५; ३८.१[२]; ४०.७; ४४.२; ४६.४; ४८.३; ५१.१; ४; ५३.१७; १९; ५४.६; ५५.९; ५९.१; ७[२]; ६०.१; ६२.९; ४.१.३; ८; १३; १४; १६; ४.६; ९; ५.७; ६.१; ७.४; १२.१; १६.५; १९; १९.५; २०.५; २१.२; २३.१; ४[२]; २४.८; २७.२; ३०.१३; ३१.३; ४;

३२.४; ९; ३३.९; ३८.८; ४३.५; ४४.२;
४६.३; ५०.२; ७; ५३.४; ५; ५६.५; ५७.८;
५८.५; ८; ९^{२}; १०; ५.३.७; ९; ४.१^{२};
५.४; ७.५; ८.७; ९.७; १५.२; १९.१;
२३.१; २७.३; २८.३; २९.२; १२; ३१.२;
५; ३३.२; ३; ३७.५; ४१.८; १९; ४२.३;
४४.५; ५१.५—७; ५४.१५; ६०.४; ६५.३;
७९.४; ८३.७; ८६.२; ६.५.७; ७.२;
४; ९.५; १०.५; १३.६; १५.१२; १५;
१६.४४; १७.१—३; ८; ९; १८.९; १३;
१९.३; ९; २०.१; २१.७^{२}; १०; १२;
२२.१; २; २५.५; २८.४; ३१.३; ३४.३;
४; ३६.५; ३७.३; ३८.३; ३९.२; ४४.१७;
४५.१८; २५; ४७.२५; ४८.१९; ४९.८;
१४; १५^{२}; ५०.६; १५; ५१.२; ५२.२;
५३.२; ६०.२; ७; ६१.१४; ६३.७; ७१.१;
७.१.१०; १३; ४.९; ५.२; ७; ८.४; १५.२;
१८.२; १०; १६; २१.६; २३.६; २५.२;
३१.४; ३२.२२; २४; ३३.१; ९; ३४.५;
९; ३५.४; ३६.६; ३७.१; ७; ३८.४^{३};
५; ३९.४; ४८.२; ३; ५६.३; २४; ५९.४;
८; ६०.२; ६१.१; ६७.३; ६९.२; ७०.५;
७१.४; ७२.१; ८३.५; ९; ८६.२; ८८.२;
९०.५; ९३.८; १०३.२; ३; १०४.२;
१९; २१^{२}; २३; ८.१.२७; ३२; २.१९;
४०. ३.३; ७; ५.३४; ६.७; २५; ३४;
४२; ८.१२; १२.१५; २३; १३.२७; २८^{२};
१५.१; १७.७; १५; २०.१६; १९; २१.५;
१२; १६; २३.२६^{२}; २४.१९; २१; २५.७;
२१; २७.६; ३१.१५—१८; ३२.१३; २८;
२९; ३७.२; ४०.४; ४५.२२; ४६.१४;
४७.१; ७; ४८.१; ४९.१; ५०.३; ५१.८;
५५.१; ५९.३; ६; ६०.४; ६६.१०; ६७.५;
९; ६९.४; ५; ११; ७२.२; ७४.१४;
७५.१५; ७७.५; ७९.२; ८१.५; ६; ८८.१;
४; ८९.४; ९२.१; ५; ६; ३१; ९३.१;
४; १९; २१; २४; ९५.१; ९६.१५; ९८.५;
९९.५; १००.१; ३; ४; १०१.६; १०२.३;
९; १०३.५; ९.१.२; ४^{२}; ९; ३.१; ४.७;

८; ६.२^{२}; ३^{२}; ७.३; ५; ८.१; ९.५; ६;
१०.९; ११.१; २; ६; १२.२; ८; १३.२;
७; १४.७; १६.६; १७.२; ६; २०.१;
४; २१.३; २३.१; ४^{२}; २४.२; २५.२;
२६.२; २८.४; ३०.४; ३२.५; ३३.२;
५; ३४.५; ३५.३^{२}; ३६.२; ३७.२; ६;
३८.६; ४०.१; ४२.५^{२}; ४४.१; ४५.२;
४७.१; ४८.३; ५१.५^{२}; ५६.३; ५७.२;
५९.४; ६०.३; ६२.१; ३; १९; २३; २५;
२८; ६३.६; १२^{२}; २५; २९; ६४.८; १३;
२१; ६५.१९; ६६.१; ४; २२; ६७.३;
९; १४; ६८.२; ८; ७०.१०; ७१.७;
७२.३; ७३.३; ८; ७४.७; ७५.१; ३;
५; ७७.१; ४; ७८.१; ३; ७९.३; ८०.२;
३; ८२.१—३; ८४.५; ८५.२—४; ७; ८;
८६.२; ३; १४; १५; १७^{२}; २५; ३५; ३६;
४३; ८७.१; ५—७; ८८.६; ८९.७; ९०.२;
९३.२; ३; ९४.२; ५; ९६.८; १६^{४}; २२;
९७.३; ४; ७; १२; २१; २५; ३९^{२}; ४३;
४५; ४९^{४}; ५०^{४}; ५१^{४}; ९८.१; २; ९९.२;
४; १००.१; १०१.३; ९; १६; १०२.७;
१०३.३; १०४.२; ४^{२}; १०५.१; १०६.११;
१२; १०७.१४; २१; २३; २५; १०८.२;
६; ९; १०९.४; ११०.२; ६; ८; ९; ११४.३;
४; १०.१.३^{२}; ३.२; ३^{२}; ४.२; ६;
५.६; ७.२; ८.८; ९.४; १५.६; १६.१;
१७.६; १८.८^{२}; ११; २२.८; २३.४;
२५.३; २६.३; २७.११; २८.८; २९.३;
७; ३१.३; ३२.१; ४^{२}; ३४.१४; ३७.१२;
४३.७; ४५.९; ४७.८; ४८.७^{२}; ४९.११;
५०.२; ५३.२; ४; ७; ८; ११; ५९.३;
६०.६; ६३.१६; ६४.१; ३; ६५.१५;
६६.९; १५; ६८.१; ११; ६९.६; १२;
७१.३; ७४.४; ७५.२; ४; ८३.३; ६; ७;
८४.१; ८६.८; ९; १९; ८७.३; ९; १४;
८९.१५^{२}; ९०.४; ९२.१३; १५; ९४.२;
९६.२; ९८.२; ५; ९९.३; ११; १०३.७;
१२; १०७.४; ११३.४; ११५.७; ११७.७;
८; ११९.८^{२}; १२०.३; १२१.६; १२३.२;

अभिऽव्लग्य १.१३३.१; २
अभिऽव्लङ्गैः १.१३३.४
अभिऽशसा १०.१६४.३
अभिऽशस्तये ५.३.१२; ७.९४.३; ८.१९.२६
अभिशस्तिऽचातनः ३.३.६
अभिशस्तिऽपाः ९.२३.५; ९६.१०
अभिशस्तिऽपाम् ६.५२.३
अभिशस्तिऽपावा १.७६.३; ७.११.३
अभिऽशस्तिम् ३. ३०.१; ५.३.७
अभिऽशस्तीः ८.८९.२
अभिऽशस्तेः १.७१.१०; ९१.१५; ९३.५; ६.४२.४; ७.१३.२; ८.६६.१४; १०.३०.७; ३९.६; १०४.९
अभिऽशासति ६.५४.२
अभिऽश्नथः १०.१३८.५
अभिऽश्रावाय १.१८५.१०
अभिऽश्रावे १०.१२.१
अभिऽश्रियः ९.७९.५; ८६.२७; १०.६६.८
अभिऽश्रियम् ८.४४.७; ७२.१३
अभिऽश्रिया १.१४४.६; ६.७०.१
अभिऽश्रिषः ८.१.१२
अभिऽश्रीः १.९८.१; ७.९१.३; १०.१३०.५
अभिऽश्रीणन् ९.९७.४३
अभिऽश्वसः १०.९२.८
अभिऽश्वसन् १.१४०.५
अभिष्टयः १.५२.४; ११९.८; ४.३१.१०; १०.२२.१२
अभिष्टये १.१२९.१; २.३४.१४; ५.१७.५; ३८.३; ८.८.१७; १२.४; २७.१३; ५०.१; ६७.१; १०; ६८.५; १०१.१; ९.८४.२; १०.९.४; ४९.४; ९३.११²
अभिष्टिः १.९.१; ३.३४.४; १०.१००.१२; १०४.१०
अभिष्टिऽकृत् ४.११.४; २०.१; ९.४८.५
अभिष्टिऽद्युम्नाः ४.५१.७
अभिष्टिऽपा २.२०.२
अभिष्टिऽभिः १.४७.५; १२९.९²; ४.४६.२; ५.३८.५; ८.३.२; १९.२०; ५३.५
अभिष्टिऽमत् १.११६.११
अभिष्टिऽशवसे ३.५९.८
अभिष्टौ १.१५८.१; ४.१६.४; ९; ५.४१.९; ६.३३.५; ६७.११; ७.१९.८; ९; १०.६.१; ६१.२२
अभिष्णक् १०.१३१.५
अभिऽसत्वा १०.१०३.५
अभिऽसाचः ६.६३.९; ७.३५.११; १०.६५.१४
अभिऽसाचम् ३.५१.२
अभिऽसाताः ५.४१.१४
अभिऽसृष्टः ३.३५.१; १०.९१.५
अभिऽसेनान् ६.४४.१७
अभिऽस्तने १.८०.१४
अभिऽस्तुतः ९.३.६; २७.१; ६७.१९; २०
अभिस्तुते इत्यभिऽस्तुते ७.३९.७; ४०.७
अभिऽस्थिताः १०.१६६.२
अभिऽस्वरन्ति १.१६४.२१
अभिऽस्वरा २.२१.५; ८.९७.१२
अभिऽस्वरे ३.४५.२; १०.११७.८
अभिऽस्वर्तारः १०.७८.४
अभिऽह्वयन्ति १०.११२.६
अभिऽहितः ५.५०.४
अभिऽहितौ १०.८५.११
अभिऽह्रुतः १.१२८.५²; १०.६३.११
अभिऽह्रुताम् १.१८९.६
अभिऽह्रुतेः १.१६६.८
अभीकम् ९.९२.५
अभीके १.७१.८; ११६.१४; ११८.५; ११९.८; १२१.१४; १७४.५; १८५.१०; ३.३९.७; ५६.४; ४.१२.५; १६.१२; २४.४; २८.३; ४३.४; ६.२४.१०; ५०.१०; ७.१८.२४; ८५.१; १०.३८.४; ५५.१; ६१.६; १३३.१
अभीद्धात् १०.१९०.१
अभीपतः १.१६४.५२
अभीरवः १.८७.६; ८.४६.७
अभीरुः ४.२९.२
अभीवर्गम् ८.४६.६
अभीशवः १.३८.१२; ५.६१.२; ८.३३.११
अभीशुऽभिः ५.४४.४
अभीशूनाम् ६.७५.६

अमतिम् ३.३८.८; ५.४५.२; ६२.५; ६९.१; ७.३८.१; २; ४५.३
अमतिऽवा ८.१९.२६
अमतेः ५.३६.३; ८.६६.१४; १०.४३.३
अमत्त २.३७.४
अमत्रः १.६१.९; ३.३६.४
अमत्रम् ४.२३.६; १०.२९.७
अमत्रिन् ६.२४.९
अमत्रे ५.५१.४
अमत्रेभिः २.१४.१; ६.४२.२
अमत्सत ८.६९.११; ९.१४.३
अमत्सुः १.८४.५
अमथ्नात् १.९३.६
अमदः ८.५४.२
अमदः १.८२.६
अमदत् १०.८६.१
अमदत् १.८०.२
अमदन् १.५२.९; ७.१८.१२
अमदन् १.५२.१५; ५३.६; १०२.१; १०३.७; ३.३१.१०; ९.८६.२४
अमध्यमासः ५.५९.६
अमनुत ४.५.१०
अमन्त १.१८९.३
अमन्तवः १०.१२५.४
अमन्ति ७.२५.२
अमन्तुः १०.२२.८
अमन्थत् १०.१२६.७
अमन्थत ६.१६.१३
अमन्थतम् १०.२४.४
अमन्थिष्टाम् ३.२३.२
अमन्दत् १.१६५.११; ८.४६.२७
अमन्दन ५.३४.२; ८.२१.१०
अमन्दथाः ८.५२.२
अमन्दन् ३.३६.४; ५१.९; ५.३०.१०; ११
अमन्दान् १.१२६.१
अमन्दिषाताम् ७.१०३.४
अमन्दिषुः ८.५०.२; ३; १०.४८.४
अमन्दिषुः १.८२.६; ८.५२.१०
अमन्दीत् ८.८०.१०
अमन्महि १.३०.२१; ४.३९.४; ८.१.१४; ४५.१९; ९०.३; १०.३५.८
अमन्महि ५.२२.३; ८.१.१३; ४.१९
अमन्यत ६.७२.३
अमन्यन्त १.११६.१७
अमन्यमानान् १.३३.९; २.१२.१०
अमन्वत १.८४.१५
अमम् १.६६.४
अममदुः ७.१८.२१
अममन् १०.३२.८
अममन्दुः ५.३०.१३
अमर्तः ५.३३.६
अमर्त्यं १.४४.१; १२९.१०; ५.१८.२; ८.४.१८; १०.२१.४; १४०.४
अमर्त्यः १.३०.१८; ५८.३; १६४.३०; ३८; १७५.२; ३.२.११; ११.२; २४.२; २७.५; ७; ४.९.२; ५.१८.१; ७५.९; ६.३.६; ९.४; ७; १२.३; १६.६; ७.१५.१०; ८.१९.२४; २५; ४८.१२; ९.३.१; ९.६; २८.३; ६८.८; ६९.५; ८४.२; १०३.५; १०८.१२; १०.८७.२१; १२२.३; १४४.१
अमर्त्यम् १.४४.११; ८४.४; १३९.८; २.११.२; ३७.४; ३.१०.९; ५१.१; ४.१.१; ८.१; ५.४.१०; १४.१; २; ८.१९.३; १०२.१७; १०.११८.६
अमर्त्यस्य ८.११.५; १०.७९.१; १४९.३
अमर्त्या ३.६१.२; ७.७३.१; १०.१२७.२
अमर्त्या ८.५.३१; २६.१७
अमर्त्याः १.१६८.४; ६.१८.१५; ९.२२.४
अमर्त्ये ७.१.२३
अमर्त्ये १.३०.२०
अमर्त्येन ६.१८.७; १०.६३.१७; ६४.१७
अमर्त्येषु १.११०.५
अमर्धन्तः ७.७६.२; ५
अमर्धन्ता ३.२५.४
अमर्धन्तीः ५.४३.१
अममंणः ३.३२.४; ५.३२.५; ६.२६.३

अमऽवत् १.५२.९; ४.५५.४; ५.३४.९; ५८.१; ८६.३; ८.७५.१३
अमऽवती १.१६८.७
अमवत्ऽतरेभ्यः १०.७६.५
अमवत्ऽसु ६.६६.६
अमऽवन्तः १.३६.२०; ३८.७; ८.२०.७
अमऽवान् १.५२.१०; ४.४.१; ५.८७.५; १०.११.७
अमविष्णवः १०.९४.११
अमहीयमानाम् ४.१८.१३
अमा १.१२४.१२; २.३८.६; ६.२४.१०; ५१.१५; ६४.६; १०.२७.२; ६३.१६; १२८.६; १८५.२
अमाऽइव २.३६.३
अमाऽजुरः ८.२१.१५; १०.३९.३
अमाजूःऽइव २.१७.७
अमात् ५.५९.२; ८.१२.२४
अमात् ५.५३.८; ९.९७.८
अमात्यम् ७.१५.३
अमात्रम् १.१०२.७
अमाद्रिषुः ९.८.४
अमानुषः १०.२२.८
अमानुषम् २.११.१०; ८.७०.११; १०.२२.७
अमानुषीषु १०.९५.८
अमाय ८.२०.६
अमितऽओजाः १.११.४
अमितऽक्रतुः १.१०२.६
अमितम् ४.१६.५
अमिता ५.३४.१; ६.६२.२; ७.८४.४; १०.५६.५
अमिताः १.११९.३; ५.५८.२
अमितानि ८.२४.२१
अमितैः ७.३.७
अमित्रऽखादः १०.१५२.१
अमित्रऽदम्भनः ४.१५.४
अमित्रऽदम्भनम् २.२३.३
अमित्रम् ६.७३.३; ७.७७.४; ८.७५.१०
अमित्रऽयन्तम् १.१३१.७; ५.३५.५; १०.१८०.३
अमित्रऽयुधः ३.२९.१५
अमित्रस्य ६.२५.२; १०.१५२.३
अमित्रऽहन् ६.४५.१४; १०.२२.८; ३४.३
अमित्रऽहा ९.११.७; ९६.१२; १०.८३.३; १७०.२
अमित्राः १.१३३.१; २.१२.८; १०.८९.१५; १०३.१२
अमित्रान् १.६३.२; ५; १००.५; ३.१८.२; ४.४.४; १२.२; ६.३३.१; ३; ४४.१७; ४६.६; ८; ७३.२; ७५.४; ७; १६; ७.१८.९; २५.२; ३२.२५; ८५.२; ९२.४; ८.१६.१०; ९.९७.५४; १०.१०३.४; १३१.१
अमित्रिणे १.१२०.८
अमित्रियम् ९.६१.२०
अमित्रिया ६.१७.१; ८.३१.३
अमित्रेषु १०.८९.९
अमित्रैः ३.३०.१६
अमिथितः ८.४५.३७
अमिनः ६.१९.१; १०.११६.४
अमिनत् १०.८८.१३
अमिनती १.९२.१२; १२४.२
आमिनती इति ४.५६.२
अमिनते ४.५.६
अमिनन्त १.७९.२
अमिनाः १.३२.४
अमिनात् ३.३४.३; ४९.२; १०.१११.४
अमिमीत १.१२६.१; ३.२९.११; ६.७.७; ८.४२.१; १०.९९.१०
अमिमीत २.४.५; ६.८.२; ४७.३; १०.६१.२; ११०.११
अमिमीथाः ५.३१.७
अमी इति १.२४.६; १०; १०५.५; ९; १०; १२७.८; १४१.१३; ४.१८.११
अमीतऽवर्णाः ४.५१.९
अमीमदन्त १.८२.२
अमीमेत् १.१६४.९
अमीमेत् १.१६४.२८
अमीवऽचातनः १०.९७.६

१८५.६; ३.१.१४; २३.१; २६.७; २९.५; १३; ५३.१५; ५.२.३; ३.४; ५७.५; ६.९.४; १५.६; ८; ३७.३; ४४.१६; २३; ४८.१; ७.१६.१; ७६.१; ८१.६; ८.१३.१२; २३.१९; ५२.७; ७४.५; ९.७४.४; ६; ११३.८–११; १०.१२.३; १३.४; ३०.१२; ९०.३; १२१.२; १२९.२

अमृतस्य १.१३.५; ४३.९; ११२.३; १२२.११; १६४.२१; १७०.४; २.४०.१; ३.१७.४; २०.३; ४३.५; ६१.३; ४.५.१३; १६.१४; ३५.३; ५८.१; ५.२८.२; ४७.२; ५८.१; ६.७.६; ७; ९.३; १६.२५; २१.३; ५२.९; ७.४.६; ५७.६; ८.४२.२; १०१.१५; ९.७०.२; ४; ९४.२; ९७.३२; १०८.४; ११०.४; १०.११.९; १२.६; ९; १३.१; ८५.२०; ९३.४; १२३.३; १८६.३

अमृता १.३५.६; ११३.१३; ३.५५.१०

अमृता ५.४२.१८; ४३.१७; ७६.५; ७७.५

अमृताः ५.५७.८; ५८.८

अमृताः १.५९.१; ६२.१०; ७२.२; १०; ९०.३; १६६.३; ३.४.११; ४.१.१०; ३.१२; ४२.१; ५.२.१२; ६९.४; ७.२.११; ११.१; ३५.१५; ६३.५; ८.४८.३; १०१.६; १०.१६.८; ६५.१४; ६६.१; ५; ६९.९; ७०.११

अमृताः ७.३८.८; ८.८०.१०

अमृतात् ७.५९.१२

अमृतात्ऽइव १०.१७६.४

अमृतान् ६.१५.१८; ७.४.५; १७.४; १०.६५.१५; ६६.१३; १५

अमृतानाम् १.२४.१; २; ७.५.१; १०.३१.३; ३३.८; ७४.३

अमृतानि १.७२.१; ३.३८.४; १०.१२३.४; १३९.६

अमृताम् १०.१७.२

अमृताय १.९१.१८; ३.२५.२; ३४.२; ४.२.९; ३.३; ७.९७.५; ८.३१.९; ९.६२.६; ८७.५; १०६.८; १०९.३; १०.५३.१०; ९१.११; १२२.५

अमृतासः १.१२३.१; १२७.८; २.१.१४; ४.३५.८; ५.४२.५; ७.७५.३; ९७.५; ९.१५.२; २५.४; १०.१०.३

अमृतासः १.१६६.१३

अमृतासु १०.९५.९

अमृते ९.११३.७

अमृते इति १.११३.२; ३.२५.३

अमृतेन ६.७५.१८

अमृतेभिः १.१८९.३; १०.२०.१०

अमृतेषु २.२.९; ३.२१.१; २६.३; २८.५; ४.४३.१; ६.१५.१०; १०.३२.५

अमृत्यवः ३.२.९; ९.७०.३; १०.९४.११

अमृत्यु ६.४८.१२

अमृध्रः ५.४३.१३; ६.१९.७; ८.८०.२; ९.८२.५

अमृध्रम् १.३७.११

अमृध्राः ३.५८.८; ५.३७.१; ६.७५.९

अमृध्राम् ६.२२.१०; ७.६७.५

अमृध्रे इति ५.४३.२

अमे १.६३.१; ६७.२; ४.१७.७; ८.५३.८

अमेन ४.२२.३; ९.९०.६

अमेनान् ५.३१.२

अमेभिः ७.३४.१९

अमेहयन् १०.१०२.५

अमैः ८.७५.१०

अमोचि ५.१.२; १०.१०७.१

अम्ब २.४१.१६; १०.८६.७[२]; ९७.२

अम्बयः १.२३.१६

अम्बरीषः १.१००.१७

अम्बरे ८.८.१४

अम्बिऽतमे २.४१.१६

अम्ब्यम् ८.७२.५

अम्भः १०.१२९.१

अम्भृणम् १.१३३.५

अम्यक् १.१६९.३

अम्यक्षि ६.११.५

अय ४.१८.२

३२.९; ३४.१३; ३९.५; ५१.९; ५२.३; ५३.१; ६०.७[३]; १२[४]; ६१.१६; १९; ६२.४; ८; ६९.७; १२; ७७.४; ८३.६; ८६.३; ९; १८; १९; ९९.९; १०[२]; १०८.७; १२३.१; १२४.६; १२६.३; १३५.७; १३७.५; १४२.१; १४४.१; २[२]; ६; १५९.१; १७३.४; १७६.३; ४; १८९.१

अर्यमानः ८.१००.८

अर्यमानम् ४.३८.५

अयष्ट ६.४७.२५

अर्यसः ६.३.५; ४७.१०

अर्यसे १.५७.३; ४.२१.७

अयस्मर्यः ५.३०.१५

अर्या ६.६६.४

अया १.८७.४; १२८.२; १४३.६; १६६.१३; २.६.२; २४.१; ३.१२.२; ४.४.१५; ५.४५.११[२]; ६.१७.१५; २२.६; ७१.६; ८.१.१८; १३.८; २३.७; ९३.१७; ९.४७.१; ५३.२; ६१.१; ६३.७; ६५.१२; ९७.५२; १०६.१४; १११.१

अर्यासम् २. ३५.१५[२].

अयाः ६.६६.५

अयाः ३.२९.१६

अर्याःऽइव १०.११६.९

अर्यात् १०.८५.७; १०

अर्यातन ५.५४.५; ८.७.२६

अयातन १.१६१.७

अर्यातम् १.११६.१८; ५.२९.९; १०.८५.१४; १५

अयातम् १.११६.१९; २०; ५.३१.८

अर्यातयन्त १.३३.६

अर्यातुः ७.३४.८

अर्यातुम् ७.१०४.१६

अयान् २.३८.३; ४.५३.१; ६.७१.५; १०.१३९.१

अर्याम १.३३.१; ५.४५.५; ८.९२.११

अर्यामन् १.१८१.७; ८.५२.५

अर्यामि १.१५३.२; ३.१४.२; ६.११.५; ७.२३.२

अयामि २.४१.२; ४.४७.१; ६.३४.४; ७.६४.५; ६५.५; ९२.१; ८.१०१.९

अर्यासः ७.५८.२

अयासः १.६४.११; १५४.६; १६७.४; ३.१८.२; ५४.१३; ४.६.१०; ५.४२.१५; ६.६६.५; ९.४१.१

अयासम् ९.८९.३; ४

अयासम् ३.३३.३

अयासाम् १.१६८.९; १६९.७

अयासिषम् १.१८.६

अयासिषुः ९.६१.१३

अर्यासिष्ट ५.५८.६

अयासीत् ९.८६.१६; ९०.१; ९२.६

अर्यासुः ७.५७.१

अयासुः ९.९७.८

अयास्यः १.६२.७; ८.६२.२; ९.४४.१; १०.६७.१; १०८.८; १३८.४

अर्युक्त १.५०.९; ११५.४; ५.१७.३; ४५.१०; ८७.४; ६.६३.४; ७.६०.३; ९.६३.८

अयुक्त १.४८.७; ९.६३.९

अर्युक्तम् १०.२७.९

अर्युक्ताः ९.९७.२०

अर्युक्तासः ५.३३.३

अर्युक्थाः १.९४.१०

अयुक्षत १.९२.२; ३.२६.४; ८.४१.६

अर्युक्षाताम् १.१५७.१; १०.३५.६

अर्युग्ध्वम् १.६४.७; ८५.४; ५; ५.५५.६; ५७.३

अयुग्ध्वम् १.३९.६

अयुजः ८.६२.२

अयुजि ५.४६.१

अयुज्महि ६.५३.१

अर्युञ्जन् १.१६९.२; ३.४१.२

अयुञ्जत १.१३०.५

अयुतम् ४.२६.७

अयुता ८.२.४१; २१.१८; ४६.२२

अयुतानि ८.३४.१५

अयुताय ८.१.५

अर्युद्धः ८.४५.३; १०.२७.१०

अयुद्धऽसेनः १०.१३८.५
अयुध्यः ४.३०.५
अयुध्यः १०.१०३.७
अयुध्यत् १०.८.८
अयुध्वी १०.१०८.५
अयुनक् १.१६३.२; ६.४४.२४; १०.१०२.७
अयुयुत्सन् १.३३.६
अयोः १.१८५.१; ६.२५.६
अयोजि ५.७५.९
अयोजि १.१२३.१; ९.८८.२
अयोद्धाऽइव १.३२.६
अयोधयः १.३३.७
अयोधीत् ४.३८.८
अयोयवीत् १.५२.१०
अरंस्त २.११.७
अरंहः ५.३२.२
अरंहत १०.१०२.७
अरंहयन्त १०.११३.६
अरक्षः ५.८७.९
अरक्षत् १.७४.२
अरक्षत ६.८.२
अरक्षन् १.१४७.३; ४.४.१३; ३३.४
अरक्षन् १.१४८.५; ४.२७.१; १०.३३.१
अरक्षसः १.१९०.३
अरक्षसम् ७.८५.१; ८.१०१.८
अरक्षसा १.१२९.९; २.१०.५
अरज्जुऽभिः ७.८४.२
अरजौ २.१३.९
अरट्वे ८.४६.२७
अरणः २.२४.७; ५.२.५; ६.७५.१९; ७.४.८
अरणम् ३.५३.२४; ५.८५.७; ८.४.१७; १०.११७.४
अरणयन् १०.८८.२
अरणस्य ७.४.७
अरणाःऽइव ८.१.१३
अरणानि ६.६१.१४
अरणिऽभिः १.१२७.४; १२९.५
अरणी इति ५.९.३; १०.१८४.३
अरणीम् १०.१२४.२

अरणे १०.६३.१६
अरण्यानि १०.१४६.१[२]
अरण्यानिः १०.१४६.२; ३; ५
अरण्यानिम् १०.१४६.६
अरण्यान्याम् १०.१४६.४
अरण्ये ६.२४.१०
अरण्येषु १.१६३.११
अरण्योः ३.२९.२; ७.१.१
अरतम् ८.५.१३
अरतये ७.५.१
अरताम् ३.३३.१३
अरतिः १.५९.२; १२८.६; २.२.२; ४.२; ४.२.१; ६.३.५; १२.३; ६७.८; १०.३.१; २; ६; ७; ४५.७; ६१.२०
अरतिम् १.५८.७; १२८.८; २.२.३; ३.१७.४; ४.१.१; ३८.४; ६.७.१; १५.४; ४९.२; ७.१०.३; १६.१; ८.१९.१; २१; १०.४६.४
अरतौ ५.२.१
अरत्नयः ८.८०.८
अरत्नौ १०.१६०.४
अरथाः ५.३१.५; ९.९७.२०; १०.९९.४
अरथीः ६.६६.७
अरदः ६.३०.३; ७.७९.४
अरदः ४.१९.२
अरदत् ७.४७.४; १०.८९.७
अरदत् ३.३३.६; १०.७५.२
अरदतम् १.११६.७
अरध्रम् ६.६२.३
अरध्रस्य ६.१८.४
अरन् १.१२५.७; ५.३१.१३
अरन्त ५.३१.८
अरन्त ४.१९.९; ९.७३.१; १०.७३.२
अरन्धनायः १.५३.१०
अरन्धयः १.५१.६; २.११.१९; ५.२९.११; ६.२३.२; ७.१९.२
अरन्धयत् ७.१८.९
अरन्धयत् १.१३०.८
अरन्धयम् १०.४९.५

अराविषुः १०.९४.६
अराविषुः १०.९४.३
अरावीत् ९.७४.५
अरावीत् ९.७१.९; १०.८.२
अराव्णः १.३६.१५; १६; ८.६०.१०; ९.१३.९; ६१.२५; ६३.५
अराव्णे ७.३१.५
अरासत १.१६६.३; ५.७९.६; ८.४७.४
अरासत ३.५३.१३
अरिः १.४.६; ९.१०; १५०.१; ७.६४.३; ८.२.१४; ५१.९; ७२.१६; ९.७९.३; १०.२८.१; ३९.५
अरिऽगूर्तः १.१८६.३
अरिच्यत २.२२.२; १०.९०.५
अरिणक् २.१३.५
अरिणाः २.२२.४; ४.३०.६
अरिणाः १.५६.६; ४.१९.५; ४२.७
अरिणात् २.१२.३; ३.३.११; ४.२८.१; १०.६७.१२
अरिणात् २.१५.६
अरिणीत ३.६०.२
अरिणीत १.१६१.७; ४.३६.४
अरिणीतम् १.११७.११
अरिताऽइव २.४२.१; ९.९५.२
अरित्रऽपरणीम् १०.१०१.२
अरित्रम् १.४६.८
अरित्राः १०.४६.७
अरिऽधायसः १.१२६.५
अरिप्रम् ७.४७.१; १०.७१.१
अरिप्रा ८.८.९
अरिप्राः ७.९०.४; १०.१२०.९
अरिम् २.८.२; ५.४८.५
अरिरेचीत् ४.२४.९; ६.२०.४; १०.१३.४
अरिषण्यन् १.६३.५; २.३७.३; ६.२४.९; २५.२
अरिषण्या २.३९.४
अरिष्टः १.४१.२; ५.१८.३; ३१.१; ८.२७.१६; १०.६३.१३; १६६.२
अरिष्टऽगातुः ५.४४.३
अरिष्टऽग्रामाः १.१६६.६
अरिष्टऽतातये १०.६०.८–१०; ९७.७
अरिष्टतातिऽभिः १०.१३७.४
अरिष्टऽनेमिः १.८९.६
अरिष्टऽनेमिम् १.१८०.१०; १०.१७८.१
अरिष्टऽनेमे ३.५३.१७
अरिष्टऽभर्मन् ८.१८.४
अरिष्टम् २.३४.७
अरिष्टऽरथः १०.६.३
अरिष्टऽवीराः १.११४.३
अरिष्टाः २.२७.२; ७; १६; ५.४२.८; ६.१९.४; ७.४३.५; १०.१२८.३
अरिष्टान् ७.४०.४; ९७.४
अरिष्टाभिः ६.५४.७
अरिष्टाम् १०.८५.२४
अरिष्टिम् २.२१.६
अरिष्टेभिः १.११२ २५; ८.२७.४
अरिष्टैः ६.६९.१
अरिष्यन्तः २.८.६; ४.५७.३; ८.२५.११; १२
अरिष्यन्तम् ८.५१.३; १०.६३.१४
अरिऽस्तुतः ८.१.२२
अरीळ्हम् ४.१८.१०
अरीत ९.७९.३
अरीरमत् २.३८.३; ६.७१.५
अरुक्षत् १०.६७.१०
अरुग्णम् ६.३९.२
अरुचः ६.३९.४
अरुजः ३.३२.१६; ४.३२.१०
अरुजः १.५१.५; ५६.६; ६.३०.५
अरुजत् ६.६१.२
अरुजम् १०.४९.६
अरुणऽअश्वाः ५.५७.४
अरुणः १.१०५.१८; १३०.९; ९.४०.२; १०.३०.२; ५५.६
अरुणऽप्सवः १.४९.१; ८.७.७
अरुणऽप्सुः ८.५.१; ७३.१६
अरुणऽप्सुम् ५.८०.१
अरुणम् १.७३.७; ७.९८.१; ८.१०१.६; ९.४५.३; ७८.४; १०.१४४.५

अरुणयः १०.९५.६
अरुणयुक्ऽभिः ६.६५.२
अरुणस्य १०.९४.३
अरुणा १.१३४.३
अरुणाः १.९२.२
अरुणान् १.९२.१५
अरुणानाम् १.१२४.११
अरुणानि १०.१६८.१
अरुणाम् ५.६३.६
अरुणाय ९.११.४
अरुणासः ६.६४.३
अरुणीः १.११२.१९; १२१.३; ४.१.१६; २.१६; १४.३
अरुणीनाम् १०.१५.७
अरुणीषु १०.६१.४
अरुणेभिः १.८८.२; ११३.१४; २.३४.१३; ५.८०.३
अरुणैः २.१.६; ३४.१२
अरुण्यः १.१४०.१३
अरुतऽहनुः १०.१०५.७
अरुपितम् ४.५.७
अरुशऽहा १०.११६.४
अरुषः ३.१५.३; २९.६. ४.५८.७; ५.१.५; ४७.३; ५६.७; ६.३.६^{२}; ४८.६^{२}; ७.३.३; ९.८.६; २५.५; ६१.२१; ७१.७; ७२.१; ७४.१; ८२.१; १११.१; १०.१.६; २०.९; ४३.९
अरुषम् १.६.१; ३६.९; ११४.५; ३.१.४; ४.१५.६; ५.४३.१२; ६.४९.२; ७.९७.६; ८.६९.१६; ९.८९.३; १०.४५.७; ८९.९
अरुषऽस्तूपः ३.२९.३
अरुषस्य १.८५.५; ३.७.५; ३१.३; ५.१२.२; ६; ६.८.१; ४९.३; १०.९२.२
अरुषा १.९४.१०; २.१०.२; ४.२.३; ६.२७.७; ७.१६.२
अरुषाः १.११८.५; ५.७३.५; ७.४२.२
अरुषाय ७.७१.१
अरुषासः १.१४६.२; ४.६.९; ४३.६; ५.५९.५; ७.१६.३; ७५.६; ९७.६; ८.३४.१७
अरुषि १.३०.२१
अरुषी ३.५५.११; ४.५२.२; ८.६८.१८
अरुषीः १.१४.१२; ७२.१०; ९२.१; २^{२}; ५.५६.६; ८.६९.५; १०.५.५; ८.३
अरुषीणाम् ८.५५.३
अरुषीभिः ९.१११.२
अरुषीम् १.७१.१
अरुषेण २.२.८
अरुषेभिः १.१४१.८
अरुषैः ३.३१.२१
अरुहः ९.८३.५
अरुहत् १.१०.२; १४१.५
अरुहत् १.५१.२; ११९.२; ३.२.१२; ५.१०.२; ४५.१०; ६.७१.५; ७.६०.४; ८३.३; ८.४१.८; ४८.११; ७२.४; ९.७५.१; ८६.४०; ८९.२
अरुहन् ८.१००.५; १०.४०.९
अरुहन् १.११०.६
अरूक्षितम् ४.११.१
अरूरुचत् ९.८३.३; ८५.९
अरूरुचत् ९.८५.१२
अरेजन्त १.३८.१०
अरेजेताम् १.३१.३; १५१.१; २.११.९
अरेणवः १.३५.११; १५१.५; १६८.४; ६.६६.२; १०.१४३.२
अरेणु १.५६.३
अरेणुऽभिः १.१६३.६; ६.६२.६
अरेपसः १.६४.२; ५.५३.३; ५७.४; ६१.१४; ९.१०१.१०; १०.७८.१; ९१.४
अरेपसम् ५.६३.६; ७३.६; ९.७०.८
अरेपसा १.१२४.६; १८१.४; ५.७३.४
अरेपसौ ५.५१.६
अरेपाः ४.१०.६; ६.३.३; १०.१०५.१०
अरैक् १.११३.२; १६
अरैक् १.११३.१; १२४.८; ३.३१.२
अरोचत १०.८८.७
अरोचत ३.२९.१४; ५.१४.४; ८.५६.५^{२}
अरोचथाः ३.२९.१०
अरोचयः ९.६३.७

अरोचयः ३.४४.२; ८.९८.२
अरोचयत् १.१४३.२; ३.३४.४; ८.३.६; ९.९.३; २८.५; ३७.४
अरोचयन् ८.२९.१०
अरोचि ७.१०.२; ७७.२
अरोदयत् १०.६७.६
अरोदयत् १०.९९.५
अरोधम् १०.३४.२
अरोरवीत् २.११.१०; ५.३०.११
अरोरवीत् ८.६.४०
अरोहत् ३.७.३; १०.८५.१२
अरोहम् १०.१३.३
अरोहयः १.५१.४; ९.८६.२२
अरोहयन् १०.६२.३
अर्कः १.८३.६; १६७.६; ३.२६.७; ६.२१.४; ७.२४.५; ८.८८.४; ८९.६; १०.६८.४
अर्कम् १.१०.१; १९.४; ६१.५; ८; ६२.१; ८५.२; १६४.२४; १६६.७; १८६.४; ३.२६.८; ५.३०.६; ३१.५; ६.४९.८; ६६.९; ७.९.२; ३९.७; ४०.७; ६२.३; ९७.५; ८.५१.४; १०; ९२.१९; १०१.१४; ९.७३.२; १०.६७.५; ७८.४; १०७.४; ११२.९; ११४.१; १५३.४; १५७.५
अर्कऽशोकैः ६.४.७
अर्कऽसातौ १.१७४.७; ६.२०.४; २६.३
अर्कस्य १.१३१.६; ८.६३.४; ९.२५.६; ५०.४
अर्काः ३.५४.१४; ५.५.४; ५७.५; ८.६३.५; ६; ९.९७.३५; १०.६८.१
अर्किणः १.७.१; १०.१
अर्किणम् १.३८.१५
अर्किणी ८.१०१.१३
अर्केण १.१६४.२४; ६.६५.५; १०.६८.९
अर्केभिः १.७.१; ६.५.५; ८.१६.९
अर्केषु १.१७६.५
अर्कैः १.३३.२; ४७.१०; ६२.७; ११; ८८.४; १४१.१३; १९०.१; २.११.१५; ३.३१.९; ११; ३४.१; ६१.६; ६२.५; ४.३.१५; १०.३; १६.४; ४४.३; ५५.३; ५६.१; २; ५.२९.१२; ३१.४; ३३.२; ४१.६; ७; ६.३.८; ४.६; २०.१३; २१.१०; ३८.३; ४९.१४; ५०.१५; ६२.१; ६९.२; ७३.३; ७.२३.६; ८.१२.२३; ९.९७.३१; १०.६.४; १५.९; ६८.६; ११६.९; १४८.५
अर्च १.५४.२; ३; ५.१६.१; २२.१; ५२.१; ५९.१; ६.१६.२२; ६८.९; ८.४१.१; ५०.१; १०.५०.१
अर्च ३.१३.१; ५४.२; ५.२५.७; ५२.५; ८५.१; ६.५०.६; ८.२३.२४; ४०.४; ४९.१; ६९.४; १०.७६.५; ८९.३; ११२.९; १४८.३
अर्चत् १.१७३.२
अर्चत् १.१६५.१४
अर्चत ६.४५.४; ८.६९.८[2]
अर्चत १.५१.१; ८०.९; ८४.५; १०१.१; १५५.१; २.१७.१; ३.५१.४; ५.५४.१; ७.५८.१; ८.१.८; ६९.८[2]; ८९.३; ९२.५; ९३.२६; ९.११.४; १०.६४.९; ९२.१३; ९४.७; ९६.२; १३३.१
अर्चतः ७.२२.४; २८.५; २९.५; ३०.५; १०.८९.१६
अर्चति ७.२२.३
अर्चति १.६.८; ९.१०; १०१.७
अर्चतु १०.३६.५
अर्चते १.८७.२; १५१.२; ५.६४.२
अर्चत्ऽधूमासः १०.४६.७
अर्चत्रयः ६.६६.१०
अर्चत्र्यः ६.२४.१
अर्चथः १.१५१.६
अर्चन् १.८०.१–१६; ३.३१.७; ८; १०.१४९.५
अर्चन् ३.१४.४; ४.१.१४; ७.४३.१
अर्चनानसम् ५.६४.७
अर्चन्तः १.६२.२; ८५.२; ३.३२.३; ५.१३.१[2]; ८.२९.१०
अर्चन्ति १.१०.१; ९२.३; १६५.१; १६६.७; ५.२९.१; ६; ३०.६; १०.१४७.३
अर्चन्ति १.१३२.५; ३.१२.५; ५.२९.१२; ६.२१.१०; ५०.१५; ७.२३.६; १०.१.३
अर्चन्तु ८.६९.८

अलिनासः ७.१८.७

अलिप्सत १.१९१.१; ३; ४

अव १.११.७; १३.११; २४.१३; १४[२]; १५; २५.२१; २८.१–४; ३२.२; ९; १२; ३३.७; ५१.७; ५४.४; ५५.६; ५६.१; ५७.६; ५८.५; ५९.६; ७१.५; ७९.७; ८०.४; ५; ८२.२; ९३.४; १०४.३[२]; १०५.३; ११६.३; १२४.११; १२९.४; ६[२]; १३०.७; १३३.३; ७[२]; १५१.६; १५२.१; १५४.६; १६१.१०; १६४.१०; ५१; १६८.४; ८; १७४.४; १७९.२; १८०.२; ३; १८९.५; २.११.२; १४.४; २०.६; २७.१७; २८.११; २९.७; ३०.५; ३३.५; १४; ३४.९; ४२.३; ३.४.१०; २९.३; ५३.१९; ६१.४; ४.१.४; ५; ४.५; १३.४; ५; १४.५; १६.२; १९.२; ४; २७.३[२]; ३०.१४; ५.२.५; ६; ३.९; ७.५; २९.४; ३०.२; १३; ३१.१२; ३२.१; ३७.२; ४१.१३; ४४.९; ४९.५; ५३.८; ५६.१; ५८.६; ६२.३; ७८.८; ६.९.१; १५.१५; २५.२; २६.५; ३०.४; ३१.४; ४०.१; ४७.१४; ४८.१३; १९; ५४.३; ६१.६; ६६.५; ७४.३; ७.२.१०; १८.२; १७; २०; २८.४; ३२.२७; ५८.५; ६०.९; ६४.२; ८६.४; ५[३]; ८७.६; १०४.१७; ८.४.३; ६.२९; १३.२५; १४.१४; १९.२०; २३; २४.३०; ३५.४–९; ३६.२; ४७.११; ५३.४; ६२.६; ६४.१; ८; ६६.१४; ६९.९; ७०.११; ७४.१५; ७९.९; ८०.६; ९२.९; ९६.१३; १७; ९.७.३; ९.७; १५.६; ३८.५; ७०.१०; ७१.९; ७३.४; ८; ९; ७४.१; ४; ६; ७; ७५.३; ८५.२; ८६.२७; ३१; ९६.१३; ९७.३३; १०७.१९; २२; १०.८.९; १६.५; २३.२; ४; ३०.२; ३४.५; ३९.६; ४०.३; ४८.५; ६; ५०.५; ५९.९[२]; ६०.११; ६१.२०; ६५.१२; ६६.१४; ६९.११; ७३.६; ८६.१०; १०५.१; ८; १०८.५; ११३.४; ५; ७; ११६.५; १२८.९; १३२.६; १३३.२; ५; १३४.२–५; १३८.२; १४४.३; १७१.२; १७९.१

अव १.७.४; ४९.२; १०२.३; ४; ३.३२.१२; ३५.३; ६२.८; ४.३२.४; ५२.६; ५.५.९; ३३.७; ३५.७; ८; ६.४१.५; ४६.११; ७.४१.३; ८.६.३२; २३.१२; ३६.२; ६०.१०; ७०.६; ७५.१५; ८०.४; १०.३८.१; ८०.७; १०२.१

अवऽअस्यत १.१६१.४; १०.२७.३

अवऽअतिरः १.१३१.४[२]

अवऽअतिरत् १.१०१.५

अवऽअर्धुः १.१५८.५

अवऽअभिनत् २.११.१८

अवऽअसृजः ६.४३.३

अवऽअसृजत् २.१२.१२; ८.३२.२५; १०.८५.१३

अवऽअस्य १.१४०.१०

अवऽअहन् ५.४०.६; ९.६१.१

अवंशात् ७.५८.१

अवंशे २.१५.२; ४.५६.३

अवः १.१७.१; ३९.७; ४२.५; ४६.१२; ११४.९; ११९.४; १२१.१२; १२७.५; १५१.१; १५८.३; २.२६.२; ३.१.१५; १७.३; २६.५; ३१.१४; ५८.२; ५९.६; ४.१.२०; २५.३; ५.३५.२; ३; ७०.१; ६.६.१; २६.१; ६५.३; ७.२१.८; ८८.७; ८.९.१३; १६.२; २४.२५; २७.१; ३८.१०; ४७.१; ६७.१; ४; ७३.१–१८; ८३.१; ९४.८; ९७.८; १०.२२.७; ३५.१; २; ३६.२–१०; ११[२]; १२; १००.११; ११५.५; १३२.५; १८५.१

अवः १.८३.२; १३३.६; १६३.६; १६४.१७; १८; ५.४०.६; ६.९.३; ८.४०.८; ९.७४.६; १०.१७.१३; २७.२१; ६७.४

अवः १.११.५

अवःऽदेवम् ८.१९.१२

अवःऽभिः १.८६.६; ११७.१९; १६७.२; १८५.१०; ११; ४.२२.७; ४१.२; ६; ५.७४.६; ६.४७.१२; ७.२०.१; ३५.१;

३६.९; ८.२६.२; ८१.२; १०.६.१; १३१.६
अवऽकर्शयन्ति ६.२४.७
अवऽक्रक्षिणम् ८.१.२
अवऽक्रामन्तः ६.७५.७
अवऽक्षिपन् १०.६८.४
अवऽखादः १.४१.४
अवऽगत्य ६.७५.५
अवऽघ्नती १.१९१.२
अवऽचक्षे ४.५८.५
अवऽचाकशत् ८.३२.२२; ९.३२.४; १०.४३.६; १३६.४
अवत २.३१.२; ७.३८.८; ५७.५; ८.३०.३; ७२.१२; १०.३५.११; ९७.१४^{2}; १०३.११; १०७.११
अवतः ८.४९.६; ५०.६
अवतम् २.४०.५; ६.५२.१६
अवतम् १.८५.१०; ११; ११६.९; १३०.२; २.२४.४; ३.४६.४; ८.७२.१०; १२; १०.१०१.५–७
अवतम् १.३१.८; ३४.५; ४७.५; १०९.७; ८; ११७.२३; १८१.७; १८२.४; २.३१.१; ५.४०.७; ७.८३.१; ५; ८.८.२०; २१; ३५.११; ५७.४; ५९.३; ५; ८५.९; ९.६९.१०; १०.६७.१२
अवऽतरम् १.१२९.६
अवतस्थिऽवांसम् ८.९६.१४
अवतस्य ८.७२.११
अवताः ४.५०.३
अवतात् १.११६.२२
अवतात् ८.३.२
अवतान्ऽइव ८.६२.६; १०.२५.४
अवताम् १.७६.२; १०.७०.१०
अवतासः १.५५.८
अवति २.१२.१४; ५.८३.४; ८.२.३५
अवति ७.१०४.१२; ८.७५.१४
अवतु २.४०.६
अवतु ५.८७.६; ६.९.७^{2}; ५०.१३; ६१.४; ७.४७.२; ४८.२; ८.१.१६; १०.९२.१३; ९७.१४; १००.१; १०२.१; १०३.७; १८२.२
अवते ४.१७.१६
अवऽत्सारस्य ५.४४.१०
अवथ ४.३६.५; ३७.६; ६.६६.८; ८.२०.२४; १०.३५.१४; ६३.१४; ६७.११
अवथ ५.५४.१४
अवथः १.११२.२; १७; २०; २२; ५.६३.१; ८६.१; ७.६९.४; ८.२२.१०
अवदः ३.३०.५
अवदत् १०.१७७.२
अवदतः १०.११७.७
अवदन् १.१७९.२
अवदन् १०.९७.१७; १०९.१
अवदन्त १०.१०९.४
अवद्यऽगोहना १.३४.३
अवद्यऽभिया १०.१०७.३
अवद्यम् ४.१८.७; ५.५३.१४; ८.६८.१९; १०.१४.८
अवद्यम्ऽइव ४.१८.५
अवद्यात् १.९३.५; ११५.६; १६७.८; १८५.१०; ३.३१.८; ४.४.१५; ६.१५.१२; ७.४.९; १२.२
अवद्यानि ६.६६.४
अवद्ये ८.८०.८
अवधम् १.१८५.३
अवऽधावति १.१६२.११
अवधीः १.५१.४; ८०.११; १०३.८; ६.२७.४; ८.१२.२६
अवधीः १.३३.१२; ८०.७; ४.३०.१५; १८
अवधीत् १.५२.२; ५.३४.४
अवधीत् १.१८७.६; ८.७२.४; ९३.२; १०.१४६.४
अवऽधून्वे १.७८.४
अवऽधून्वानः ६.४७.१७
अवध्रम् ७.८२.१०; ८३.१०
अवन् ७.४६.२
अवन् १.२४.३

अवर्तंयः ५.३०.७; १०.१३५.४
अवर्तयः १.१२१.१३; ८.१४.१३
अवर्तयत् १.८५.९; २.११.२०; ८.१४.५
अवर्तयत् ६.८.३; १०.१३५.५
अवर्तिम् १.११८.३; ३.५८.३; ५.७६.२
अवर्त्याः ४.१८.१३
अवत्रैः ६.१२.३
अवर्धन्त १.३३.११; २.१७.४; ९.७०.१; १०.९६.८
अवर्धन्त ९.४७.१; १०.११३.१
अवर्धन्ताम् १०.१३२.१
अवर्धन् ३.३२.३; ३५.९; ४७.४; १०.७३.१; ३; ११३.३
अवर्धन् ५.२९.११; ३१.१०; १०.४५.३; ९५.७
अवर्धन्त १.८५.७; १०.६.७
अवर्धयः २.११.१५; १०.१३८.२
अवर्धयत् ८.१२.७
अवर्धयत् ८.१४.५
अवर्धयन् ३.१.४; ५.३१.४; १०.९५.७; ११३.८
अवर्धयन् ५.११.३; ८.१३.१७; ४१.३
अवर्षीः ५.८३.१०
अवर्षीत् ७.१०३.३
अवऽविद्धम् १.१८२.६; ७.६९.७
अववृत्रन् १.१६४.४७; ३.३२.१५; १०.१८.३
अववृत्रन्त ४.२४.४
अवऽव्ययन् ४.१३.४
अवशत् २.२२.१
अवसः २.४.८; २७.५; ३.५१.६; ४.२१.१०; ५.२२.३; ५७.७; ८.७५.१६; ९.५८.२
अवसत् १.१४४.२
अवसम् १०.९५.१६
अवसम् १.९३.४; ११९.६; ६.६१.१
अवसा १.१७.६; २२.११; २४.५; ३९.७; ७७.४; ८५.११; ८९.७; १०२.५; १०७.२; ११०.७; १२४.१३; १३८.३; १५२.७; १६६.२; १७७.१; ५; १८५.४; ६; ९; १८७.६; ३.३२.१३; ५.४२.१८; ४३.१७; ४६.६; ४९.५; ७६.२; ३; ५; ७७.५; ६.२.११; १४.६; १५.१५; २०.१०; २५.९; ३१.५; ५०.९; ५२.५; ६; ५९.३; ७.२१.९; ५१.१; ५९.२; ८२.८; ८३.१; ३; ९४.७; ८.६१.४; ९.६१.२४; ९८.८; १०.१५.४; ३५.१३; ४०.७; ६४.९; ८९.१६; १७; १२०.७; १२१.६
अवऽसातारम् १०.२७.९
अवऽसानम् १०.१४.९
अवसानाः ३.१.६
अवसाम् ४.२३.३
अवसाय १०.१६९.१
अवऽसाय १.१०४.१
अवसि ५.६५.५; ६.२३.२; ५८.१; ८.३६.३; ३७.६; ४७.५
अवसि १०.१४०.२
अवऽसितस्य १.३२.१५
अवऽसितासः ४.२५.८
अवसिष्ट ९.८९.२
अवऽसृजन् १.१४२.११; २.३.१०
अवऽसृष्टः १०.४.३
अवऽसृष्टा ६.७५.१६; ७.४६.३
अवऽसृष्टान् १०.२८.११
अवऽसृष्टासः १०.९१.१४
अवसे १.१७.२; २२.६; १०; ३४.१२; ३५.१; ४५.५; ४७.१०; ४८.१४; ५२.१; १२; ८९.५; १००.८; १०२.१०; ११२.२४; ११४.४; ११८.१०; १२७.४[२]; १२८.८; १२९.१०[२]; १३५.७; १६४.५२; १६८.१; १८३.५; १८६.१०; २.१२.९; १६.१; २९.१; ३४.१४; ३.१३.२; २६.२; ४७.५; ५४.१२; ५७.५; ६२.२; ४.२.१३; ३.१; २०.१; २; २१.१; ३; २५.१; ४१.७; ८; ५.१७.१; २५.१; ३५.१; ४१.५; ४५.४; ६५.३; ६.१४.१; ३; १७.१३; १९.११; २१.९; २३.८; ९; २४.१०; २९.१; ३३.२; ३८.५; ४०.५; ४६.६; ४८.४; ६१.२; ७.१.२; २१.८; २६.२;

३२.८; ३८.६; ४८.४; ५१.२; ७४.१; ८५.४; ९०.७; ९१.७; ८.८.६; ९; ९.१; ११.६; ९; १२.१९; १९.३२; २२.३; १६; २३.२५; २७.१३; ३३.१०; ३४.४; ५३.७; ५४.२; ३; ७; ६१.८; ६३.४; ७०.२; ७१.१४; ८६.४; ९९.८; ९.१०८.१४; १०.३१.१; ३८.४; ३९.५; ६३.११; ६६.४; ७४.५; ८१.७; १०१.१; १४१.३; १४९.५

अवऽसै ३.५३.२०

अवस्तात् ३.२२.३; १०.८८.१४; १२९.५

अवस्थाः ३.३२.११

अवऽस्थाः ५.१९.१

अवऽस्परत् ६.४२.४

अवऽस्पर्तः २.२३.८

अवस्यते १.११६.२३

अवस्यवः १.१४.५; १०१.१; ११४.११; १३१.३; २.११.१२; १३; १९.८; २१.५; ३.४२.९; ७.९४.४; ८.१३.१७; २१.१; ६३.१०; ९.१७.७; ६३.२०; ८६.२४

अवस्यव: ९.१३.२

अवस्यवे २.६.६; ४.५०.९

अवस्युः १.२५.१९; ३.३३.५; ४.१६.११; ५.३१.१०; ७.३२.१७; ८.३५.२२–२४

अवस्युऽभिः ८.१३.९

अवस्युम् ५.७५.८

अवस्युवः ९.४३.२

अवस्युवम् ५.४६.१

अवस्रन् ४.२.१९

अवऽस्रसः २.१७.५

अवहः २.१३.८; ५.३१.८; ८.२४.२८

अवहः १.५१.३

अवहत् ३.५३.९; १०.५९.१०

अवहत् १०.२९.२

अवहन् १.५१.१०; ४.३३.२; १०.८५.३८

अवऽहन्ता ४.२५.६

अवऽहितः १.१०५.१७

अवऽहितम् १०.१३७.१

अवांसि ४.५५.५; ७.९७.२; ८.२६.२१; ६७.४

अवाः १.२७.७

अवाचः ४.२५.६

अवाचि १.५१.१५; ५.३.१२; ६.३४.५; ७.७०.१; ८.४०.१२; १०.५४.६

अवाजिनम् ३.५३.२३

अवाट् १०.१५.१२

अवातः ६.१६.२०; १८.१; ९.८९.७; ९६.८; ११

अवातः ८.७९.७

अवातम् १०.१२९.२

अवाता ६.६४.५

अवाताः ६.६७.७

अवाताः १.५२.४; ६२.१०

अवाताम् १.३८.७

अवाते ६.६४.४

अवाथ ७.४०.३

अवाथः ७.६१.२

अवादिषुः ७.१०३.१

अवामि १०.१२४.४

अवारतः १०.६५.६

अवारयेथाम् १.११६.८

अवारि ४.६.७

अवार्यंऽक्रतुम् ८.९२.८

अवावचीत् १०.१०२.६

अवावरीत् ८.१००.७

अवावशन्त ९.१९.४; ६६.११

अवावशन्त ९.९०.२

अवावशीताम् १.१८१.४

अवाशयः १.३१.४

अवासयः ६.१७.५

अवासयः ३.१.१७

अवासयत् १.१६०.२; ६.३२.२

अवासयत् ३.७.३

अवासयन् ७.९१.१

अविऽअनत् १०.१२०.२

अविंऽउष्टाः २.२८.९

अविः ९.७८.१

अविका १.१२६.७

अविऽक्रीतः ४.२४.९

अवि॑क्षत १०.१३६.२
अ॒वि॒क्ष॒त॒ १.१९१.४; १०.१२७.५
अवि॑ऽक्षितम् ८.३२.८
अवि॑ऽक्षितासः ७.१.२४
अवि॑क्ष्महि १०.१२७.४
अवि॑ऽचाचलिः १०.१७३.१; २
अ॒वि॒ऽचे॒त॒नानि॑ ८.१००.१०
अवि॑ऽचेतसः ९.६४.२१
अवि॑ऽजानन् १.१६४.५
अ॒वि॒जे॒ १०.५१.६
अ॒वि॒ड्ढि॒ २.१७.८
अ॒वि॒ड्ढि॒ १.११०.९; २.२४.१; ३०.८; ४.३१.१२; ६.४४.९; ८.९२.१५
अ॒वि॒त ७.५९.६
अवि॑त॒रिति॑ १.१२९.१०
अवि॑तवे ७.३३.१
अ॒वि॒ता १.३६.२; ४४.१०; ८१.८; ९१.९; १८७.२; २.१२.६; ३.१९.५; ६२.९; ४.१६.१८; २०; १७.१८; ३१.३; ५.४.९; ६.३३.४; ३४.५; ४४.१५; ४५.५; ४६.४; ४८.२; ७.१९.१०; २४.१; ३२.१०; ११[२]; २५; ९६.५; ८.२.३६; ४.१८; १३.१५; २६; ३६.१; ४६.१३; ८०.३; ९.६७.१०; १०.७.७; २४.३; १०३.४; १५७.३
अ॒वि॒ता॑ऽइव ८.७१.१५
अ॒वि॒ता॑रम् ६.४७.११; ७.३६.८; ८.२१.२
अवि॑तारा १.१८१.१
अ॒वि॒तारा॑ १०.३९.३
अवि॑ऽतारिणीम् ८.५.६
अ॒वि॒तुः ७.२५.४
अ॒वि॒त्री ६.६१.४; ७.९६.२
अ॒वि॒त्री इति॑ २.३२.१
अ॒वि॒त्सि॒ १०.१५.३; ९७.७
अवि॑थुराः १.८७.१
अ॒वि॒दुः ५.८३.१०
अवि॑दत् १.५३.१; ६.४४.७
अ॒वि॒द॒त् १.९२.९; ३.५७.१; ६.६३.१; ७.८९.४; ८.९१.१; १०.५.५; ७९.३
अवि॑दन् १०.९४.३
अ॒वि॒द॒न् १.७२.६; १०.९४.४
अवि॑दम् १०.१६१.५
अ॒वि॒द॒म् १०.१६१.५
अ॒वि॒ऽद॒स्यम् ७.३९.६
अवि॑दाम ८.४८.३
अ॒वि॒दा॒म १०.१०.१३; ५३.३
अवि॑ऽदीधयुम् ४.३१.७
अवि॑दुःऽतरासः १०.२.४
अ॒वि॒द्रि॒याभिः॑ १.४६.१५
अवि॑द्वांसः ६.१५.१०
अवि॑द्वान् १.१२०.२; ५.३०.३; १०.७९.६
अवि॑धत् १.१३६.५; २.१.७; ९; २६.४; ६.५४.४; ८.२३.२१; २७.१५; ६१.९; ९.११४.१; १०.८३.१
अ॒वि॒ध॒वाः १०.१८.७
अवि॑ध्यत् ५.४०.५; ९
अ॒वि॒ध्य॒त् १.३३.१२; ८.३२.२६; ७७.६
अवि॑न्दः १.६.५; ६.७.५
अ॒वि॒न्दुः ६.६१.३; ८.९६.१६; १७
अवि॑न्दत् १.२३.१४; १०१.५; १३०.३; ३.३४.४; ५.१४.४; २९.३; १०.४३.८; १०८.११
अ॒वि॒न्द॒त् १.१०३.५[२]; ५.४०.६; ४५.७; १०.४६.३; ६७.१; ६८.९; १०९.५; १३९.६
अवि॑न्दतम् १.९३.४
अवि॑न्दन् १.६२.२; ३.१.३; १०.१८१.२
अ॒वि॒न्द॒न् ३.९.४; ३१.५; ४.५८.४; ५.११.६; ४०.९; ७.७६.४; १०.४६.२; ७१.३; १११.७; १२९.४; १८१.३
अ॒वि॒न्द॒न्त॒ १.८३.४
अवि॑न्देथाम् ४.२८.४
अ॒वि॒प्रः ८.६१.९
अ॒वि॒प्रे ६.४५.२
अवि॑ऽभिः २.३६.१; ९.८६.११; ९१.२; १०७.२
अवि॑ऽमान् ४.२.५
अवि॑ऽरणाय १.१७४.८
अवि॑विक्काम् १०.११२.४

अविवेः ६.३१.३

अविंऽवेनन् ४.२४.६

अविंऽवेनम् ४.२५.३

अविवेशीः ३.३२.१०

अविवेषीः ४.१९.१०; २२.५

अविवेषीः ७.१९.५

अविव्यक् ७.१८.८

अविव्यचुः १०.५६.४

अविशत् २.२४.२; ९.३८.५

अविशत् १.१४१.५; २.१३.१

अविशन्त १०.४४.६; ५५.२

अविऽशस्ता १.१६२.२०

अविश्रन् ८.२७.१२

अविश्वऽमिन्वम् २.४०.३

अविश्वऽमिन्वाम् १.१६४.१०

अविषः ३.१३.६

अविषत् १.८१.१

अविषस्य ८.२५.२०

अविषा ६.३९.५

अविष्टन ७.१८.२५

अविष्टम् ८.५.१३

अविष्टम् ४.५०.११; ७.६४.५; ६५.५; ६७.६; ९७.९

अविष्टम् २.३०.६; ५.६२.९; ७.६७.५; ८.९.५

अविष्टाम् १.१८५.९; ५.४३.२

अविष्टु १.१११.५; १०.२६.१;९

अविष्टो इति ७.३४.१२

अविष्ठः ७.२८.५; २९.५; ३०.५

अविष्यते १०.११५.६

अविष्यन् १.५८.२; ७.३.२

अविष्यवः ८.४५.२३

अविष्यवः ८.६७.९

अविष्यवे १.१८९.५

अविष्याम् २.३८.३

अविहर्यतक्रतो इत्यविहर्यतऽक्रतो १.६३.२

अविंऽह्रुतम् ५.६६.२; १०.१७०.१

अविंऽह्वरन्तम् ४.३६.२

अवीः ६.१०.६

अवीः ६.२५.१

अवीत् ७.३४.१४

अवीताः ४.४८.१

अवीनाम् ९.१०७.८; १०९.७; १०.२६.६

अवीरता ७.१.११

अवीरतायै ३.१६.५

अवीरते ७.१.१९

अवीरयेथाम् १.११६.५

अवीरऽहा १.९१.१९

अवीराः ७.४.६; ६१.४

अवीराम्ऽइव १०.८६.९

अवीरे १०.९५.३

अवीवतन् १०.१३.५

अवीवशत् ९.३२.३; ३४.६; ७६.४; ८६.१९; १०७.२६

अवीवशन् ९.२१.७

अवीवशन्त १०.६४.१५

अवीविपत् १.१५५.६; ९.९६.७

अवीविपन् ९.७३.२

अवीवृतत् १०.१७४.३

अवीवृधत् ८.८.१५; १९; ८०.१०

अवीवृधत् ८.८.८; १०.६३.१७; ६४.१७

अवीवृधध्वम् १.१२४.१३

अवीवृधन् ७.३६.७

अवीवृधन् १.५.८; ११.१; ९.४.९; ७३.२

अवीवृधन्त ४.३२.१२

अवृकः ४.१६.१८; ६.२.२; १५.३

अवृकऽतमः १.१७४.१०

अवृकम् १.४८.१५; ६.४८.१८; ७.८८.५; ८.९.१; २७.४; १०.३६.३; १४४.५

अवृकस्य १.१५५.४

अवृकाः ४.४.१२; १०.१५.१

अवृकाणि १.५५.६

अवृकाभिः २.३१.३

अवृकाय १.३१.१३; ७.६६.८

अवृकासः ७.७४.६

अवृके ६.४.४

अवृकेभिः ६.४.८; ७.१९.७

अवृक्त ८.१०१.१६

अवृक्षम् १०.१४९.५

६५.११; ६८.११; ९७.४; १०७.७; १०; ११९.१; १४३.१; २; १८८.१

अश्वSमघा ७.७१.१

अश्वम्Sइव १०.१४९.१

अश्वम्Sइष्टये ८.६१.७

अश्वम्Sइष्टे २.६.२

अश्वSमेधस्य ५.२७.५

अश्वSमेधाय ५.२७.४

अश्वSमेधे ५.२७.६

अश्वSयते ६.४५.२६

अश्वSयन्तः ४.१७.१६; ७.३२.२३; १०.१३१.३; १६०.५

अश्वSया ८.४६.१०; ९.६४.४

अश्वयाSइव ९.१०७.८

अश्वSयुः १.५१.१४; ४.३१.१४; ८.५३.८; ७८.९; ९.३६.६

अश्वSयुजः ५.५४.२

अश्वSयूपाय १.१६२.६

अश्वयोः ६.४७.९

अश्वSयोगाः १.१८६.७

अश्वSराधसः ५.१०.४; १०.२१.२

अश्वSवत् १.४८.१२; २.४१.७; ५.५७.७; ७.२७.५; ७५.८; ७७.५; ९४.९; ८.२२.१७; ४६.५; ७२.६; ९३.३; ९.४१.४; ४२.६; ६३.१८; ६९.८; १०५.४

अश्वSवतः १.१२२.८; ७.१००.२

अश्वSवता ७.७२.१

अश्वSवति १.८३.१; ९२.१४

अश्वSवतीः १.४८.२; १२३.१२; ७.४१.७; ८०.३; ८.५.१०

अश्वSवतीम् १०.९७.७

अश्वSवते १०.४०.५

अश्वSवत्या १.३०.१७; ५३.५

अश्वSवन्तः ८.४५.११

अश्वSवन्तम् १.८३.४; ४.४९.४; ८.२.२४; १०.४७.५

अश्वSवित् ९.५५.३; ६१.३

अश्वSसाः ९.२.१०; ६१.२०

अश्वSसातमः १.१७५.५

अश्वSसाम् ६.५३.१०

अश्वSसूनृते ५.७९.१–१०

अश्वस्य १.५३.२; ८४.१४; ११६.७; १२; ११७.६; १२१.२; १६२.९; १८; १९; १६४.३४; ३५; २.३५.६; ४.३९.३; ६; ५.८३.६; ८.३२.५; ५२.५; ६१.६

अश्वस्यSइव १०.३४.३

अश्वSहयः १०.२६.५

अश्वSहयैः ९.९६.२

अश्वा १.१७४.५; ३.३५.३; ४.३३.१०; ३४.९; ६.५९.३; ६७.४; १०.२२.४; ५; ७५.७

अश्वाSइव ४.५२.२; ७.१०४.६

अश्वाः १.११५.३; ११८.५; १६३.१०; १६४.३; १८०.१; ३.१.४; ६.८; ९; ७.२; ६१.२; ५.५४.१०; ६१.२; ६.६.४; २४.६; ३७.३; ७५.७; ७.१८.१; ४१.६; ६७.४; ७५.६; ९७.६; ९.७८.२; १०.६.६; ४४.७; ९०.१०; ९५.८; १०७.११

अश्वाःSइव ५.५३.७; ५९.५; ८.२३.११; १०.९७.३; ११९.३

अश्वाजनीSइव ५.६२.७

अश्वात् १.१६१.७; ३.५३.२३; १०.७३.१०

अश्वान् १.९२.१५; १०३.५; १०४.१; १२६.२; १७१.१; २.३४.३; ८; ४.४३.६; ४५.६; ५.३१.१०; ५५.६; ५८.७; ५९.१; ६२.१; ८३.३; ६.४७.२३; ५९.५; ७५.१३; ७.३४.४; ८.१.३१; ४१.६; ६८.१७; ७५.१; ९.९७.५०; १०.३४.११; ७९.७; १०१.७; १४९.४

अश्वानाम् १.१०१.४; ५.१८.५; ६.६३.१०; ७.१०४.१०; ८.३६.५; ४६.२९; ५६.४

अश्वाम्Sइव २.३४.६

अश्वाय १.१६२.१६; ५.३१.४; ८.३०.४; ९२.२५

अश्वासः १.३८.१२; १४८.३; १८१.२; २.१२.७; ४.१४.४; ४५.२; ५.५९.७; ६२.४; ७५.६; ६.१६.४३; २९.२; ६३.७; ६९.४; ७.७४.४; ७८.४; ८.१.९; ५५.४; १०.७८.५; ९१.१४; ९५.९

१७५.४; २.१५.४; ३.३०.१२; २०; ५०.४; ५८.३; ४.५१.५; ५.२९.९; ५५.१; ५८.६; ६.३९.४; ६२.३; ६५.२; ७.१८.२; ४१.३; ४५.१; ६९.१; ७१.३; ८.५.३५; ७.२७; ९.९६.११; १०.३.७; ७.२; ११.७; ६८.१२; ७०.२; ३

अश्वैत् १.९२.१२; ११३.१५; १२४.११; ७.७७.२

अश्व्यः १.३२.१२; ७४.७; ८.६६.३

अश्व्यः ८.४६.२१

अश्व्यम् १.११७.२२; ११९.९; ४.२८.५; ५.५२.१७; ६१.५; ७.९२.३; ८.२१.१०; ३४.१६; ९.७२.९; १०८.६; १०.४८.४; ९३.१२

अश्व्यम् १.११२.१०; ८.४६.३३

अश्व्यस्य ४.४१.१०; ८.४६.२२

अश्व्यस्य ८.२४.१४

अश्व्या ५.७९.७; ७.१६.१०; ६७.९; ८.२७.६; ३४.१४

अश्व्यानाम् ८.२५.२३

अश्व्यानि ६.४४.१२; ७.१८.१९

अश्व्ये ८.१३.२२

अश्व्येन १०.८७.१६

अश्व्यैः ६.६०.१४; ८.७३.१४; १५

अषऽतरा १.१७३.४

अषाळहः ३.१५.४; ७.२०.३. २८.२; ९.९०.३

अषाळहम् १.५५.८; ९१.२१; ६.१८.१; ८.७०.४; १०.४८.११

अषाळहाय २.२१.२; ७.४६.१; ८.३२.२७

अषाळहेन ६.१९.२

अष्ट ८.२.४१; १०.२७.१५

अष्ट ७.८४.५; ८५.५; ८.७०.५; १०.१२६.१

अष्टऽकर्ण्यः १०.६२.७

अष्टमम् २.५.२; १०.११४.९

अष्टवे ४.३०.१९

अष्टा १.१२१.८

अष्टाऽपदी १.१६४.४१

अष्टाऽपदीभिः २.७.५

अष्टाऽपदीम् ८.७६.१२

अष्टाभिः २.१८.४

अष्टाऽवन्धुरम् १०.५३.७

अष्टौ १.३५.८; १२६.५; १०.७२.८

अष्ट्रा ६.५३.९

अष्ट्राम् ४.५७.४; ६.५८.२

अष्ट्राऽवी १०.१०२.८

अष्ठीवत्ऽभ्याम् १०.१६३.४

अष्ठीवन्तौ ७.५०.२

असः ६.३६.५; ७.२४.१; ८.१००.२; १०.४४.४; ५०.५; ८५.२६; ३६; १२४.१

असक्त १.३३.३

असक्राम् ६.६३.८

असक्षत ८.६४.९

असघ्नोः १.३१.३

असचऽद्विषः ८.२०.२४

असचन्त ३.३१.४

असजत् १०.१२४.७

असजात्या १०.३९.६

असत् १.९.५; ८९.५; १०७.१; ११४.१; १४३.६; १७३.९; १७६.५; १८६.३; २.२३.१४; ३.२३.३; ५१.११; ४.१६.२०; ६.२३.५; १०; २४.५; ३४.५; ७.२०.८; ५३.३; ८५.४; १०४.१२[२]; १३; ८.३१.१८; ९.८९.६; १०.५.७; २७.१; २९.२; ३७.१०; १०१.३; १२९.१; १३७.५; १४१.४

असत् १.५७.२; १२५.२; १२९.८; १५६.२; १६४.१६; १७३.१०; २.२६.१; ४.२.१०; ४.७; ८.२०.१७; २८.४; ३१.३; ६१.४; ८९.४; १०.१०.११; ८९.१४

असतः ५.१२.४; ७.१०४.८; १०.७२.२; ३

असत्ता ४.५.१४

असति १.१२४.११; ६.२३.९; ४५.१४; ८.२०.१५; १०.८५.२५; १२९.४; १९१.४

असति ५.५३.१५

असत्याः ४.५.५

असथ ५.६१.४; १०.१०३.१३

असथ ८.३०.२; १०.९७.५

असादि ७.७.५
असादि १.६०.२; ३.४.४; ४.६.२; ५.४३.७
असानिषम् ६.४७.२३
असाम १.५३.११; १७३.९; ४.२.१०; १०.५३.४
असामि १.२५.१५; ३९.९; १०^{२}; ६.१९.२; ३८.५; १०.२२.२; ३; ७४.३; ९६.५
असामिऽभिः १.३९.९
असामिऽशवसः ५.५२.५
असारयन्त १०.५६.५
असावि १.८४.१; ५.४३.५; ७.२१.१; ९.६२.४; ७७.५; ८२.१; १०.१०४.१
असाविषुः ९.२१.७
असावीत् १.१२४.१; १५७.१; ५.८१.२
असि १.१.४; १२.३; १३.४; १५.३; ४४.२; ९; १०^{२}; ५९.३; ७४.४; ८१.२^{३}; ८७.४; ९४.७; ९७.६; १२९.२; १४४.७; १६३.३^{४}; १८९.६; २.१.२; ९.४; २३.११; ३२.६; ३.३.७; ९.३; ५३.१८; ४.६.१; ३२.१३; २१; ४६.१; ५.९.४; २८.५; ३५.४; ६.२.७; ४.४; १३.२; ४०.५; ४८.१९; ७१.२; ७.१६.६; ३२.२४; ८.४.१; ६.४१; ११.८; १२.१८; १३.१५; १४.११; २३.२९; २४.२; ३९.३; ४३.२१; २८; ४४.२४; २९; ६१.१४; ६५.७; ९०.२; ९२.२८; ९३.३३; ९५.३; ९७.४; ५; ९८.५; ६; ९.६५.४; ८५.२; ९७.५५^{३}; १०.१.४; २४.३; ३५.७; ९१.१०; ९८.१
असि १.१५.१२; २७.६; ३१.१०; १२; १६; ३६.५; ९; १२; ५०.४; ५३.२; ५९.१; ५; ६२.१२; ७५.३; ४; ९१.३^{२}; ५^{२}; ९४.५; ६; १३^{२}; १०२.८; १३२.३; १६९.१; १८८.३; २.१.३; ५; ७; १०–१२; १५; ७.५; १२.१५; १३.२–१२; २०.२; २३.२; ४; २७.१०; ३३.३; ४१.२; ३.३.१०; ९.३; २५.१; २८.३; ३०.२१; ३४.२; ४५.५; ४६.२; ४७.१; ४.४.१; ९.१; २०.८^{२}; ३०.२; ७; २२; ३२.२; १९; ५२.३^{२}; ५.१.८; १३.४; ६; २८.४; २९.१; ४०.७; ४४.२; ६.२५.५; ४४.१२; २१; ४५.५; २६; ४७.२६; ३०; ४८.८; ९; ५५.३; ५६.५; ५८.१; ७.११.१; १९.१; २२.७; २९.४; ३१.६; ७; ३२.१७; ३३.११; ३७.५; ९८.६; ८.१.६; ७; २.९; ४.१; ११.१; २; १३.१५; २६; १९.३१; २१.१३; २३.३०; ३३.१०; ३६.१; ५; ५१.७; ६०.३; ५; ६; १९; ६१.६; ६४.२; ६९.१२; ७१.२; ७९.३; ८०.३; ७; ८८.४; ८९.६; ९०.२; ५; ९५.४; ९७.९; ९८.२^{२}; ९९.५^{२}; १०१.११^{३}; १२^{२}; ९.२.१०; १८.१–७; ४७.५; ५९.४; ६१.२०; ६४.१; २; ६६.३; १६; ६७.१; १३; ८६.२८; २९; ३८; ३९; ८८.३; ४^{२}; ८^{२}; ९७.२९; १०४.५; १०९.६; १०.१.२; २.१; २; ४.१; २; १०.१३; ११.५; ५४.५; ५६.३; ६१.२४; ७९.५; ८४.४; ९१.३^{२}; ९७.१८; २३; १००.५; १०२.१२; १०४.६; ११०.१; ३; १३२.४; १३३.३; ४; १४१.१; १४५.५; १५२.१; १५३.२; ३; ५; १५६.५; १८०.१; १८६.२
असिः १०.७९.६; ८९.८
असिक्नीः ७.५.३
असिक्नीम् ९.७३.५; १०.३.१
असिक्न्या १०.७५.५
असिक्न्याम् ४.१७.१५; ८.२०.२५
असिञ्चन् १०.२९.७
असिञ्चत् ३.४८.२
असिञ्चतम् १.११६.७; ११७.६
असिञ्चन् १.८५.११
असितः १.४६.१०
असितम् ४.१३.४; ५१.९
असिना १.१६२.२०
असिन्वती इति १०.७९.१
असिन्वन् २.१३.४; ७.३९.६; ८.४५.३८; १०.७९.२
असिन्वम् ५.३२.८
असिन्वा १०.८९.१२
असिम् १०.८६.१८

असिरेण ९.७६.४
असिष्यन् ६.३.५
असिसासः ८.५०.१०
असिसासत् ८.५१.२
असिसासन् ३.३१.९
असिस्यदत् ९.८१.२
असिस्यदत् ९.१४.१; २७.६; ३०.४; ४९.५; ६०.३; ७८.१; १०६.१२
असिस्यदन्त ९.६८.१
असीदः ६.१.२
असीदत् १.१४३.१; १०.८१.१
असीदत् ५.१.६; ८.४२.१
असीदतम् १०.१३२.७
असीदम् १०.५२.२
असुः १.११३.१६; १६४.४; १०.१२१.७
असुः १.१७९.२
असुतः ७.२६.१
असुतात् ६.४१.४
असुतानाम् ८.६४.३
असुऽतृपः १०.८२.७; ८७.१४
असुऽतृपौ १०.१४.१२
असुऽनीतिम् १०.१२.४; १५.१४; १६.२
असुऽनीते १०.५९.५; ६
असुन्वतः १.१०१.४; ५.३४.६; ८.६२.१२
असुन्वता ४.२५.७; ५.३४.५; १०.४२.४
असुन्वताम् १.११०.७
असुन्वन्तम् १.१७६.४
असुन्वाम् ८.१४.१५
असुम् १.१४०.८; १८२.३; २.२२.४; १०.१२.१; १४.१२; १५.१; ५९.७
असुर १.२४.१४; १७४.१; २.२७.१०; २८.७; ४.२.५; ८.९०.६; १०.९६.११; ९९.१२; १३२.४
असुरः १.३५.७; १०; ५४.३; १३१.१; २.१.६; ३.३.४; ५.१५.१; २७.१; ४२.१; ५१.११; ८३.६; ७.३०.३; ५६.२४; ८.४२.१; ९.७३.१; ७४.७; १०.११.६; ७४.२
असुरःऽइव ८.१९.२३
असुरऽघ्नः ६.२२.४
असुरऽघ्ने ७.१३.१
असुरऽत्वम् ३.५५.१–२२; १०.५५.४
असुरत्वा १०.९९.२
असुरम् ५.४२.११; ७.२.३; १०.५६.६
असुरस्य १.११०.३; १२२.१; १२६.२; २.३०.४; ३.२९.१४; ३८.४; ५३.७; ५६.८; ४.५३.१; ५.४९.२; ६३.३; ७; ७.६.१; ९९.५; ८.२०.१७; १०.१०.२; ३१.६; ६७.२; ९२.६; १३८.३; १७७.१
असुरऽहा १०.१७०.२
असुरा ७.६५.२; ८.२५.४
असुरा १.१५१.४; ७.३६.२
असुराः १.६४.२; ८.९६.९; १०.१२४.५
असुराः ८.२७.२०
असुरान् १०.५३.४; १५७.४
असुराय ५.१२.१; ४१.३; ९.९९.१; १०.१२४.३
असुरे १०.९३.१४
असुरेभ्यः ८.९७.१
असुरेषु १०.१५१.३
असुरैः १.१०८.६; १०.८२.५
असुर्य २.२३.२; १०.१०५.११
असुर्यैः ८.१०१.१२
असुर्यम् २.२७.४; ३३.९; ३.३८.७; ५.१०.२; ६६.२; ६.२०.२; ३०.२; ३६.१; ७४.१; ७.५.६; ६५.१; ९.७१.२
असुर्यस्य २.३५.२; ७.२२.५
असुर्या १.१६७.५; ७.९६.१
असुर्याऽइव १.१६८.७
असुर्याणि ४.४२.२; १०.५४.४
असुर्यात् १.१३४.५
असुर्याय ४.१६.२; ७.२१.७; ६६.२; ८.२५.३; १०.५०.३
असुवत् १.११०.३
असुस्वीन् ४.२४.५; ६.४४.११
असुस्वेः ४.२५.६

अस्ति १.२२.४; ३३.२; ३६.१२; ३७.१५; १००.२; १०८.२; १४९.२; १६२.९; १०; १६७.७; १७०.१; १७३.६; १२; १७८.१; १९०.३; २.२७.६; ३३.७; ३.२९.१^{२}; ३६.९; ४.१८.४; २०.७; २१.२; ४५.७; ५८.१; ५.७.९; ३१.२; ३९.१; ३; ४२.२; ४; ६५.४; ७०.१; ७४.६; ६.१८.३; ६; १५; २५.१; २९.१; ३४.२; ४४.१–३; ६२.८; ६५.४; ७४.३; ७.२०.५; २२.२; २७.२; ३; ३२.१९; ५६.१८; २१; ६८.५; ७१.४; ८६.६; ९७.४; ८.१.२७; ३१; ९.१५; १०.३; १८.१९; २०.२२; २३.१०; २४.९; १९; २१; २७.१०^{२}; ३०.१; ३३.६; ४६.९; ४७.१३; ५४.५; ६६.१३; ६७.३; ६; ७^{२}; ७०.८; ८१.८; ९४.४; १००.३; १०२.१९; १०.१२.५; ८२.५; १३१.३; १४२.१^{२}

अस्ति १.२७.८; ४०.८; ४१.४; ६२.६; ८४.१९; १०५.१३; १०९.१; १६४.१; १६५.९; २.१२.५; २४.७; ३३.१०; ४.३०.१; ५.३.५; २९.१४; ७७.२; ६.१८.३; १२; २१.१०; २४.५; २५.५; ३०.४; ६६.८; ७.३.२; ४.७; २९.३; ४०.३; ६०.७; ८.१४.४; ३२.१६; ६६.९; ६७.१९; ७४.१५; ७८.७; १००.३; १०.२७.२१; ३१.८; ७१.६; ११७.४

अस्तु १.१३९.१

अस्तु १.७.१०; ८.५; १३.१०; ११; १६.७; २४.९; २६.७; २७.९^{२}; ३०.५; १२; ३९.२; ४; ५५.७; ८२.५; ८६.७; ९०.७; ८; ९१.१९; ९४.८; ९८.३; १००.१९; १०२.११; १०८.२; ११४.१०; १२५.७; १४०.११; १४७.४; १६२.८; ९; ११; १४; १६५.१०; १७२.१; १८४.४; १८५.११; २.४.२; १४.११; २०.३; २८.१; ३.३०.६; १८; ४४.१; ५४.३; १८; २१; ५९.२; ४.१.१८; २.७; ४.७; १२.१; १५.९; २१.१; २६.४; ३७.६; ४६.७; ५७.३; ५.११.५; ३४.९; ४७.७^{२}; ५३.९; ७४.९; ६.१६.२६; १८.५; २३.३; २६.८; २९.६; ३७.५; ४४.१५; ४८.१८; २०; ५८.१; ६६.१; ७; ६७.८; ७.१.१४; ४.२; २०.१०; २१.१०; २५.३; ३४.१५; २२; ३५.२^{२}; ३; ४; ५^{२}; ६; ७; ९^{२}; १०; ११; १३^{२}; ३८.३; ४०.३. ४१.५; ५६.५; १७; २४; ५७.४^{२}; ५८.४; ६६.५; ६७.६; ७०.५; ८५.४; ८६.८^{२}; १००.३; १०१.५; १०४.३; ८; ११^{२}; ८.१.३२; १७.६^{२}; १०; १९.९; ६६.१५; ८३.४; ९३.१८; ९६.७; १००.२; १०२.२१; ९.६३.३; ९२.५; १०.७.४; १५.२; ३२.९; ३४.१४; ३५.१३; ४२.३; ४३.२; ४४.९; ५१.८; ९; ५९.४; ६२.१–४; ७७.७; ८०.२; ८१.६; ८५.२३; ९७.२०; २३; १००.४; ९; १०; १०२.११; १०८.६; १२१.१०; १२८.१–४; १६५.१–४; १८०.१; १८२.२; १८५.१; १९१.४

अस्तुः १.६६.४; १४८.४; १५५.२; ९.७७.२

अस्तुतः ५.६१.८; ६७.५

अस्तृणन् ३.९.९; १०.५२.६

अस्तृणन् १.१८८.४

अस्तृणात् ८.४१.८; ६३.७

अस्तृतः १.४१.६; ६.१६.२०; ८.९३.९; १५; ९.२७.४

अस्तृतम् १.४.४; १५.५; १४०.८; ८.१.११; ६६.१०; ९.९.५; १०.४८.११

अस्तृतऽयज्वनः ८.४३.१

अस्तृऽभिः १.८.४

अस्तृन् १०.६४.८

अस्ते ७.१.२

अस्तोढ्वम् १.१२४.१३

अस्तोभयत् १.८८.६

अस्तोषत १.८२.२

अस्तोषि १.१२२.१; ५.४१.१०; ८.३९.१; १०.७७.१

अस्तोष्ट १.७७.५

अस्तौत् १०.६७.३; १०५.६; ११^{२}

अस्त्रा ८.९६.२

९; ५.१०.१; ३५.१; ३८.४^{२}; ४४.६; ४७.७; ५३.१३; ५५.९; ६.१९.६; ४४.१८; ४६.८; ५१.५; ५२.१५; ५३.५–७; ७१.६; ७५.११; ७.५०.४; ६८.३; ७४.५; ७८.१; ७९.४; ८१.६; ९४.७; १०४.१४; ८.५.१२; ११.१०; २६.१५; ३०.४; ४६.१९; ६७.१९; ८१.९; ८३.१; ८४.६; ९.२.९; ७.९; २१.५; ३३.६; ४०.३; ४३.४; ४६.५; ४९.३; ६२.३; ६३.११; ६५.१३; २१; ८६.४१; ९०.४; ९१.६; ९७.२१; १०१.१०; ११; १०४.४; १०६.६; १०.१४.१२; ३०.११; ४७.१–८; ५६.२; ८४.७; ११६.९; १२६.७; १३३.७; १६९.३

अस्मऽयु १०.९३.१४

अस्मऽयुः १.१३१.७; १३५.२^{२}; १४२.१०; ३.४१.७; ४२.१; ५.७४.८; ६.४८.२; ७.१५.८; ८.१९.७; ७०.१२^{२}; ९.२.५; ६.१; १४.८; ६४.१८; ७८.५; १०.९३.११

अस्मऽयुम् २.२३.८

अस्मयू इत्यस्मऽयू १.१३५.५; १५१.७; ७.७४.४; ८.२६.१४

अस्माकं १.१७३.१०

अस्माकम् १.७.१०; १३.१०; २५.१५; २७.२; ४; ३०.११; ३३.१; ७९.११; ९४.८; १६; १०२.४; ५; ११४.३; १२९.१; ४^{२}; १३२.६; १३८.२; १३९.९; १४०.१०; १२; १५२.७^{२}; १५७.२; १७४.१०; १८७.२; २.२.१०; ३०.४; ३१.१; ३.३१.१४; ३९.४; ६२.१५; ४.१.१३; ९.७^{३}; २०.३; २२.१०^{२}; ३१.१४; १५; ३२.१; १५; ४२.८; ५.४.८; ९; ३५.७; ८; ४१.१६; ४४.७; ६५.६; ७४.९; ६.८.६; ७; ४५.३०; ४६.४; ४७.३१; ५४.६; ७.२८.१; ३२.११^{२}; २५; ५१.२; ५७.२; ५९.३; ६९.६; ८२.९; ८.१.३; १५; ४.१८; ५.१८; ६.४२; १२.१७; १७.४; २६.२०; ३३.१५^{२}; ४५.९; ५२.८; ५४.८; ५७.२; ६४.६; ६७.१९; ८८.६; ९२.३२; १०.२२.७; २६.४; ९; ३२.१; ३६.६; ३७.११; ८१.६; ८४.५; ९७.२०; २३; १०३.४; ७; ११^{३}; १०८.५; ११२.७; १३३.१; १३६.३; १५१.३; १५७.३

अस्माकासः १.९७.३; ५.१०.६; ६.२५.७; ७.७८.५

अस्माकेन ६.४५.१५; १०.४२.१०; ४३.१०; ४४.१०

अस्माकेभिः १.१००.६; २.३०.१०; ६.१२.४; ८.१५.१२; ४०.७

अस्मात् १.१७१.४; १८२.८; ३.५३.१९; १०.९८.१२

अस्मात् २.२३.५; ४.१७.१०; ५.३२.३; ८.२७.१८; ९६.६; १०.११७.४

अस्मान् १.९.६; १७.७; २४.१२; ३१.१८; ४७.५; ८१.३; ८४.२०; ९५.९; ९८.३; १०९.७; ८; १११.५; ११२.२५; १६५.१४; १७४.१; १८९.१; २; २.१.१६; २.१३; ११.१५; २८.१०; ३०.५; ६; ८; ३९.४; ३.८.१०; ३३.६; ५३.२०; ६२.३^{२}; ४.४.१५; ९.८; १२.४; ३१.१०^{३}; ११; १२^{२}; ५.४.६; ३३.५; ५५.४; १०; ६.१९.३; ४१.५; ४४.९; ४५.३०; ७.१.२२; १२.२; १५.३; १८.२; १९.९; २३.२; ३४.१२; ४८.२; ५४.१; ५५.३; ४; ९३.६; १०४.२३; ८.२.१९; ३.१; २; ८.२१; २२.४; २५.२१; ३३.१६; ४०.१२; ४८.३; ११; ५४.७; ५९.५; ६३.१२; ७०.६; ८०.६; १००.११; ९.५२.४; ८५.२; १०.१५.५; १७.५; १०; १९.१; ५३.५; ६१.२२; ७३.११; ७८.८; ९७.२३; १०३.११; ११२.१०; १३४.२; १५२.४; १६५.३; १७४.१

अस्मान्ऽअस्मान् ४.३२.४

अस्माभिः १.११३.११; ३.६२.७; ६.३४.२; ८.८१.८; १०.३८.३; ११२.३

अस्मासु १.४८.१२; ६४.१५; १२३.१३^{२}; १३९.८; २.२.६; २३.१५; ४.५१.१०; ५७.२; ८; ५८.१०; ५.४.१०; ६.७.३;

४७.६; ७.७७.६; ८.४७.१०; ५९.७; १०.५९.५; ६; ८३.४; १४४.२

अस्मिं १.१६४.३७; ६.१९.१२; ७.२५.४; १०४.१५; ८.७५.१५

अस्मि १.१०५.७; १२६.७; ३.२६.७^{२}; ४.२६.१; ५.४४.१४; १५; ७.१००.६; १०४.१६; ८.१००.४^{२}; १०.२७.१; ३३.७; ४८.७; ६१.१९; ८३.५; ६; ८६.९; ९५.२; ११९.१२; १४५.५; १५९.३; १६६.२

अस्मिन् १.१३.३; ७; ३०.६; ५१.१५; ५४.१; १००.६; १०१.९; १०९.५; ११४.१; १३२.१^{२}; १८५.७; २.६.८; १८.७; ३०.६; ३५.१४; ३.२९.१६. ३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.६; ११; ३६.११; ३८.१०; ३९.९; ४३.८; ४८.५; ४९.५; ५०.५; ६०.६; ४.१४.४; १६.२; २०.१०; ३३.११; ३४.११; ३५.१; ५०.१०; ५८.२; ५.७५.८; ६.५०.९; ५२.१३; १६; १७; ५९.७; ६८.११; ७.२३.५; २९.२; ३२.२६; ६९.५; ९२.५; ९५.४; ८.२.३; २२.१८; ४४.१३; ७५.१२; ७६.७; १०.१४.५; १७.८; १९.३; ३८.१; ४३.२; ४४.५; ९; ७०.७; ७५.९; ८५.२७; ८९.१८; ९८.६; १०२.१; १०४.११; १२८.२; ८; १३०.२; १३२.५; १४५.४; १४९.५

अस्मिन् १.६.९; ७२.१०; ७३.४; १८९.८; २.१६.२; ३.३८.७; ५७.३; ४.२३.५; ४१.४; ४५.१; ६.१९.५; ३८.३; ७.२१.१; ८७.५; ८.२.३९; १७.१३; ४४.१; ९.२१.५; ९४.१; १०.९५.७; १२४.४

अस्मृतध्रु इत्यस्मृतऽध्रू १०.६१.४

अस्मे ६.१०.२

अस्मे इति १.९.७; ८; २४.७; ३०.२२; ३४.४; ३८.१५; ४३.७; ४४.२; ४६.६; ४७.६; ५४.११; ७१.२; ७२.२; ७४.१; ७९.४; ९२.१४; ९३.१२; १०२.२; ११२.२४; ११३.१७; ११४.९; १०; ११७.२३; ११८.२; ११; १२२.१४; १२४.९; १२९.८; १३५.८; १४१.११; १५३.१; १५८.२; १६०.५; १६५.३; ७; १६७.९; १६९.३; १७३.१३; १८४.२; ४; १८६.११; २.३.९; ४.८; ९.६; ११.४; १३; १४; २१.६; ३३.१२; ३५.४; ३९.६; ४०.४; ३.१.१९; २३; ४.१; ५.११; ६.११; ७.११; ८.६; १०.८; १५.७; २२.५; ३०.१८; १९; ३५.१; ३६.१०^{२}; ३९.२; ६२.३^{२}; ४.४.८; ८.७^{२}; १७.२०; २२.९; ३२.१४; ३३.१०; ११; ३४.२; १०; ४३.७; ४४.६; ७; ४७.४; ४९.४; ५०.१०; ११; ५३.६; ७; ५.४.२; ७^{२}; ६.१०; ५३.९; ५४.१३; ७३.४; ६.१.११; १२^{२}; ६.७; १९.९; २३.८; २८.१; ३५.२; ४४.९; ४७.१३; ५०.३; ५२.१६; ६०.३; ६८.६; ११; ६९.६; ७०.२; ५; ६; ७४.२; ३; ७.५.८; २१.८; २२.९; २४.४; २५.३; २६.४; ३४.२१; ४२.६; ४५.४; ४८.१; ४; ५३.३; ५६.१७; २०; २४; ५७.४; ६७.२; ४; ७; ७०.४; ५; ७५.२; ८; ७६.७; ७७.५; ८२.१०; ८३.९; १०; ८४.४; ९१.४; ५; १०१.२; ५; ८.२.१०; ५.१५; २२.१६; ४७.२; ३; १४; ४८.१०; ५१.१०^{२}; ५४.२; ५७.४; ६३.१२; ६५.९; ८२.६; ९७.८^{२}; ९.१२.९; ३२.६; ६३.१; ३०. ६६.२१; ६८.१०; ६९.७; ८९.१; ९७.३; १०.६.६; ७.४; १०.३; १७.८; १८.९; १९.१; २२.२; १२; १३; २३.७; २४.१; ३५.१३; ३६.१३; ३७.११; ४२.६; ७; ४४.५; ४५.१२; ६१.२५; ६६.१४; ६९.४; ७०.४; ८४.३; ९१.१५; ९३.१०; ९५.१३; ९८.३; ९; ९९.८; १००.४; १०६.४; १११.१०; १३१.७; १४०.४; १४३.६

अस्मेरा: २.३५.४

अस्मेऽहिंतिः १०.१०८.१

अस्मै ५.३९.५; ६.२३.५; ३४.४; ५; ८.४३.२

अस्मै १.५७.३; ६१.१–६; ८; १२; १५; २.३५.५; १२; ५.४५.३; ६.१.१०; ६३.२;

८.४१.१; ९६.१^{२}; १०.१४.९; ४०.९; ९७.७

अस्मै १.३२.२; १३; ५३.१०; ५४.७; ६७.४; ६९.५; ७०.२; ३; ७१.५; ७६.३; ७७.१; ९१.२०; १०४.७; ११४.११; ११६.८; १२५.२; १२७.४; १४७.४; १४९.५; १६१.११; १६२.१६; १६६.३; १७३.४; ६; १७८.२; २.१२.५; १३; १३.१०; १४.६; ७; ९; १६.४; १७.१; ६; १८.२; १९.५; २६.४^{२}; २७.१५^{२}; ३०.२; ३५.२; १०; ३.१.१०; ९.९; १३.१; ३१.११; १२; ५२.८; ५६.४; ४.४.६; ७; १८.७; २४.६; २५.५; २७.३; ५.२.३; ३२.१०; ३३.१; ३४.३; ३६.६; ४७.६; ६४.२; ६.१०.२; १७.११; १८.१३; २०.६; २४.८; ३२.१; ३४.३; ५; ४०.२; ४२.१; ४४.१४; ५४.४; ७.११.२; १९.२; ३४.३; ४; ११; १४; ४५.२; ६३.५; ८.१.८; २.४१; ८.१६; ९.१; १४.२; २३.२१; २७.१८; ३१.२; ६२.१; १००.९; १०३.६; ९.११.१; ७०.१; ७२.३; ९१.३; १०.७.४; १०.९; १४.९; ११; १८.११; १२; २९.७; ८; ३०.८; ३१.४; ११; ४०.९; ४२.१; ५; ६; ५२.६; ७३.६; ९; ७९.२; ५; ८२.४; ८९.३; ९१.१२; १३; ९६.६; ९८.७; ९९.१२; १०२.१०; ११७.३; १३३.१; १३६.७; १६०.३^{२}; ४

अस्मैऽअस्मै ६.४२.४

अस्यै ४.१५.५; ५.१७.२; ६४.३; ८२.२; ६.४०.२; ८.३१.४; ९.५३.३; ६१.२९; ६६.१४; ६९.१; ७३.४; ८९.३; १०.८.३

अस्य १.४.८; १२.१; २२.१; २३.२; २६.५; ३३.१; ५२.१२; ५७.५; ६०.२; ६१.७; ९–११; १३; १४; ८६.४; ५; ९२.६; १०२.१; २; १०५.१–१८; ११६.२५; १२१.४; १२२.८; १३१.४–६; १४३.२; ३^{२}; १४५.२; १४७.२; १५३.४; १६४.१; ७; ३२; १६८.६; १८३.६; १८४.६; १९०.३; ४; २.४.४; ११.२०; १५.१; १६.७; १९.१; २; २३.१९; २४.१६; २७.५; ३२.१; ३३.९; ३५.६; ३.१२.१; ३५.६; ५०.२; ५१.१०; ४.१.६; ११; ४.११; ५.८; ११; १२^{२}; १५; १७.९; १४; १९; ३६.२; ४५.१; ४९.५; ५.१२.३; १६.३; १७.३; ४; २२.४; २९.३; ७; ३८.४; ४३.३; ४४.८; ५४.१०; ६३.२; ७१.३; ६.२९.५; ३७.२; ४४.१४; ४७.१; ४८.९; ५९.५; १०; ६२.१; ६९.१; ७; ७०.२; ७.४.३; ७.६; २९.१; ३०.१; ३१.४; ३२.२२; ३८.२; ८; ३९.३; ४०.५; ६०.७; ७३.१; ८७.६; ९४.१; १००.५; ८.१.२६; ३.८; १२; ५.१४; १३.४; १५.५; १७.११; १९.२; ३; २४.८; २६.८; ११; ३७.३; ४६.१६; ६३.९; ७६.६; ९२.६; ९४.१०–१२; ९५.२; १०२.८; ९.१.१०; २३.७; ५४.१; ८५.३; ८; ८९.३; ९७.१; ९८.५; ८; १०२.५; १०६.३; १०८.२; १०.३.४; ६; ८.७; १०.५; ६; २७.७; ३१.५; ६^{२}; ४६.७; ६१.१८; ६४.१३; ९२.१२; ९९.६; ११; ११०.११; १११.३; ११६.२; १२१.३; १२९.६; १५९.६; १६०.१; १६८.२; १८७.५; १८८.२; १८९.२

अस्य १.६.२; ७.७; ८.८; १०; २२.१७; २३.२४; २७.८; ३०.३; ३२.६; ७; ३३.११; १३; ३५.७; ४०.८; ५०.३; ५२.५; १०; १४; ५५.१; ६१.८; ६२.६; ६८.५; ७१.३; ६; ८०.१०; ८४.११; १२^{२}; ९४.१; ५; ९५.३; १०३.१; ३; ५; ११०.६; ११४.४; ११५.५; ११९.२; ५; १२१.१०; १२७.५^{२}; ६; १२८.५; १३८.१^{२}; १४०.३; ५; १४१.२; ४; ८; १४४.१^{२}; १४६.१; २; १४८.२; ४; १५२.३; १५४.५; १५५.३; ४; ५^{२}; १५६.२–४; १५८.५; १६०.३; १६२.८^{२}; १६३.२; ९^{२}; १२; १६४.१; ७; १८; १७६.४; १९१.१०–१३; २.३.११^{२}; ४.४; ५.४; ५; ११.९; १०; १२.१३; १३.१०; १४.१; २; १०; १५.१;

१७.१; ३; १८.८; २०.८; २२.२; ३५.२; ८; ११^{२}; ३६.५; ३८.२; ५; ७; ३.१.७; ९; ११.३; १३.५; २४.१; २९.३; ३०.१२; १७; ३२.४; १५; ३४.६; ७; ३६.५^{२}; ३८.५; ७; ८; ४२.२; ४८.२; ५०.१; ५१.४; ५; ५५.१८–२०; ५६.७; ४.१.७; ९; १०; ६.५; ७.१०; ९.६; १६.१; ५; १७.६; ११; १२; १८.४; २३.२^{३}; ३^{२}; ४–६; २५.५; ७; २७.४; २९.३; ३०.१३; ३८.८; ९; ४०.३; ५०.२; ५४.४; ५८.३^{२}; ५.२.१; १०; १९.५, २९.३^{२}; ६; ११; ३०.२; ९^{२}; १०; ११; ३२.५^{२}; ९^{२}; ३३.८; ३४.४; ७; ३७.३; ४५.९; ४७.४; ४८.४^{२}; ५३.१६; ५४.७; ६०.६; ६२.७; ७७.४; ६.३.४; १२.५; १८.५; १२; १९.४; २२.३; २४.७; २७.१^{४}; २^{४}; २८.२; ३०.१; २; ३५.१; ३६.२; ३७.४; ३८.२; ४४.५; १३; ४५.३^{२}; ४७.१८^{२}; ५१.१३; ५२.३; ५४.३; ६२.९; ६३.१; ६६.८; ७५.५; ८^{२}; ७.३.२; ५; ११.४; १६.३; २०.६; ३२.१२; ३४.७; १७; ३६.५; ४०.१; ४५.२^{२}; ८२.३; ६; ८६.१; ८८.२; ९०.२; ९८.२; ५; १००.३; ४; १०४.११; ८.१.३४; २.२१; ३.४; ८; १०; १३; ४.८; ६.४; ५; १३; १२.७; २१; २४; ३२; १३.८; २९; १९.१४; २३.४; ३२.१५; ४०.६; ४८.१२; ४९.२; ५०.२; ५१.५; ६०.१३; ६३.३; ६६.८–१०; ६९.३; १७; ७२.१; २; ६; १८; ७५.७; ८२.७–९; ९२.५; ९४.४; ६; ९५.६; ९७.१; ९९.४; १०३.९; ९.६.७; ७.१; ७; ८; ८.१; १४.३; २९.१; ३०.१; ४७.२; ३; ७०.३; ७१.२; ५; ८; ७८.१; ८३.२^{२}; ३; ४; ८५.१२; ८६.१४; १५^{३}; ८८.१; ८९.६; ९२.२; ९६.१; २; २२; ९७.५४; ९९.३; १०२.३; १०८.१२; १०९.१५; १०.१.३^{२}; १०.५; १२.५; ८; १३.५; १६.१; २०.६; ९; २३.२; ३; ५; ६; २७.१०; २०; २४; २९.५; ३४.४; ६; ४२.६; ४३.७; ४८.९; ५५.२; ६१.१; ३; १३; २४^{२}; ६२.११; ६९.२; १०; ७३.९; १०; ७५.९; ७६.३; ७; ७९.१; ८६.४; ५; ८८.२; ८९.६; ९०.३^{३}; ४; ६; ११; १२^{२}; १५; ९१.१३; ९२.३^{२}; ७; ८; ९६.३; ७; ९९.२; ९^{२}; १०; १०२.६; ७; १११.७; ११३.१; २; ११४.७; १२३.७; १२४.७; ८; १२५.७; १२९.७; १३२.३; १३५.७; १३८.२; १४२.५; १४७.४; १४९.३; १६०.४; १६८.१; ४; १७८.३

अस्यत् १०.६१.८

अस्यतम् ७.१०४.२५

अस्यति २.२४.८

अस्यति ३.५३.२२

अस्यतु १.११४.४

अस्यथ १.३९.१; १७२.२

अस्यथ ५.५५.६

अस्यध्वम् १०.३०.२

अस्यन् ४.२२.२; १०.४२.१; १६८.१

अस्यसि ५.८४.२

अस्याः १.८७.४; १२१.६; १४; १३१.६; १३८.४; १६४.३७; ३.८.१; १५.२; ४.१.५; ३.४; ४.३; २३.५; ४१.५; ५.३.८; ४१.१७; ४५.८; ६.१.१; ७.३६.८; ८.४६.२१; ६६.१४. ९.७५.२; १०.२९.२; ११०.४; १२२.७

अस्याः १.३२.९; ४८.३; ८; ९२.५; ११३.२; १२४.८; ३.५७.१; ४.३०.११; ३३.४; ४२.८; ९; ५.४६.१; ६.७५.११; ७.७८.१; ८.१००.१०; १०.८५.१०; २८; ३९; ८६.११; १०२.२; १०९.३; १४५.४

अस्यान् ९.८९.१

अस्याम् २.३.४; ६.२६.८; ७.१९.७; २०.८

अस्याम् ३.५७.२; १०.८५.४५

अस्यै १.१२७.११; १५८.२; २.२३.७; ३३.५; ७.१.१९; ९.९७.३०; १०.९७.१९; २१

अस्यै १०.८५.३३

अस्रवः ६.६१.३

अस्रवन्तीम् १०.६३.१०

४३.३; ५३.१२; ४.१८.२; २६.१[४]; २[३]; ३; २७.१; ४२.२–६; ५.२.८; ९.६; १२.२; ३; ४२.२; ४३.९; ४४.१४; १५; ७५.२; ६.९.२; २६.७; ४७.१०; ५०.९; ७.२९.४; ३२.१८; ८६.७; ८९.१; १०४.१४; ८.१.२०; ३१; ६.१०[२]; ११; ४६; ९.१३; १६; १०.२; १४.१; २; १९.२५; २८; ३५.२२–२४; ३८.१०; ४४.२३[२]; ४५.३५; ५३.८; ६२.११; ६७.१०; ७४.१३; ७५.१५; ७६.१२; ७८.१०; ९.९६.४; १०७.१९; २०; ११२.३; १०.९.८; १५.३; १८.१३; २५.३; २७.१–३; ५; ९; २८.५; ३२.६; ३४.२; ३; १२; ३८.५; ४०.७; ४८.१[३]; २[२]; ४–६; ८[२]; ४९.१[३]; २[२]; ३[३]; ४[२]; ५[३]; ६; ७; ८[२]; ९[२]; १०; ५१.४[२]; ५२.२; ६०.१०; ६१.१८; ७९.४; ८३.५; ८६.९; ११; १२; १४; ८८.१५; ९५.२[३]; ९७.१; ११; २०; १०८.४; १०; ११९.५; ९; १०; १२; १२५.१[५]; २[३]; ३; ५; ६[३]; ७; ८; १२८.४; १४५.३; ५; १४६.६; १४९.५; १५०.४; १५९.१; २[३]; ३; ६[२]; १६६.२; ४[२]; ५; १६७.३; १७४.५; १८३.३[४]

अहम्ऽपूर्वः १.१८१.३

अहम्ऽयुः १.१६७.७

अहम्ऽसन ८.६१.९

अहये ५.३१.४; ७.१०४.९; ८.९६.५

अहरिति १.७१.२; ६.९.१; ४८.१७; ७.१०३.७; १०.१६८.३

अहर्यत् १०. ९६.१०

अहर्यथा १०.९६.५

अहर्विः १.१८२.३

अहऽसु १.१२४.९

अहस्तः १.३२.७

अहस्तम् ३.३०.८

अहस्ता १०.२२.१४

अहस्तासः १०.३४.९

अहा १.५०.७; ११६.४; १३०.२; ९; १४०.१३; ३.३२.९; ५४.२२; ४.३०.३; ५.४८.३; ७.३०.३; ६५.२; ८.१.३; ४३.३०; ६१.१७; १०.१२.४; ३२.८

अहाऽइव ४.३३.६; ५.५८.५; ६.६१.९; ८.९६.१९

अहाः १.११६.३

अहानाम् ८.२२.१३

अहानि १.५२.११; ८८.४; १७१.३; ३.३४.४; १०; ५.४९.३; ५४.४; ७.११.२; २५.४; ७६.३; १०.१८.५; ३१.७; ३७.२

अहानिऽइव ८.४८.७

अहार्षम् १०.१६१.३; ५; १७३.१

अहावि ५.८६.६; १०.९१.१५

अहासत १.९.४; ८.७.२; ९.७३.६

अहिंसन्तीः १०.२२.१३

अहिंसानस्य ५.६४.३

अहिंस्यमानः १.१४१.५

अहिः १.३२.५; ८; १३; ७९.१; १८६.५; २.३१.६; ५.४१.१६; ६.४९.१४; ५०.१४; ७.३४.१७; ३५.१३; ३८.५; ९.८६.४४; १०.६४.४; ६६.११; ९२.१२; ९३.५

अहिःऽइव ६.७५.१४

अहिऽगोपाः १.३२.११

अहिऽघ्ने ६.१८.१४

अहिऽघ्ने २.३०.१

अहितेन ८.६२.३

अहिना २.११.२; ४.१७.१; ५५.६; ७.२१.३; १०.१११.९; ११३.३

अहिऽनाम्नाम् ९.८८.४

अहिन्वन् ३.३१.५

अहिऽभानवः १.१७२.१

अहिम् १.३२.१; २; ५१.४; ८०.१; १३; १०३.२; ७; १८७.६; २.११.५; १२.३; ११; १५.१; १९.२; ३.३२.११; ३३.७; ४.१७.७; १९.२; ३; ९; २२.५; २८.१; ५.२९.२; ३; ८; ३०.६; ३१.७; ३२.२; ६.१७.९; १०; २०.२; ३०.४; ७२.३; ७.३४.१६; ३८.७; ८.३.२०; ९३.२; १०.६७.१२; ९६.४; ११३.८; १३३.२

आ

आ **१**.१.२; ५; ७; २.१; ४–६; ३.३–८; ४.२–४; ७; ५.१[२]; ३[२]; ७; ६.९; ७.२; ३; ८.१; ३; ९.१–३; १०; १०.२; ४[२]; ११; १२.३; ४; १०; ११; १३.१; ४; १४.१; २[२]; ६; १२; १५.१; ४; १६.१; ४; ५; ९; १७.१; ३; ८; १९.१–७; ८[२]; ९; २०.७; २१.४; २२.१; ८–१०; २३.१; ७; १३[२]; २३; २४.११; १२; २५.५; १०; १५[२]; १९; २६.३; ४; २७.५[२]; ६; १३; २८.९; २९.१–७; ३०.१; २; ८; १०; १४; १५[२]; १७; २१[२]; २२; ३१.४[२]; ७; ९[२]; १७[२]; ३२.३; ६; ७; १०; ३३.१; ७; ११; ३४.५; १०–१२; ३५.२[२]; ३; ४; ७; ८; ३६.६; ३७.६; १३; ३८.७; १०; ३९.६–९; ४०.२; ४; ४१.८; ९; ४२.५; ४३.८; ४४.१; ७; ९; १३; ४५.२; ८; ९; ४६.७; १३; ४७.२; ७–९; ४८.५; ९; ११; १२; १६; ४९.१; ५०.४; ५१.२; ४; १०[२]; १२[२]; ५२.१; ४; ६; ८; १२; १३; ५३.३; ५५.७[२]; ५७.३; ५; ५८.१; २; ५; ६; ५९.३; ६०.३; ४; ६१.९; १६; ६२.८; ६३.२[२]; ५; ६; ९; ६४.९[२]; १३; ६७.४; ७०.१[२]; ७१.४; ६[२]; ८; ७२.४; ८; ९; ७३.४; ७४.६; ७६.२–४; ७७.२; ५; ७९.२[२]; ८; ९; ८१.४; ५; ७; ९; ८३.४; ५[२]; ८४.१[२]; ३; ९; १८; २०; ८५.४; ६[२]; ७; ११; ८६.५; ८७.२; ८८.१[२]; २; ४[२]; ८९.१; ७; ९१.११; १३; १६; १७; २२; २३; ९२.३; १३; १५; १६; १७[२]; १८; ९३.६; ११; १२; ९४.३; ८; ९५.४; ९७.१; ९८.२; १०१.८; १०; १०२.५; १०४.१; २; ६[२]; ९[२]; १०५.१; २; ५; १३; १४; १०६.२; १०७.१; २; १०८.१; ३; ४; ६–१२; १०९.४; ७; ११०.३; ६; ९; १११.२–४; ११२.१; २[२]; ३–१६; १७[२]; १८; १९[२]; २०–२३; ११३.१; २; १०; १४; १६[२]; १९; ११४.३; ४; ९; ११५.१; ३; ११६.१६; १७; १९; २२; ११७.१; १७; १९; २३; २५; ११८.१; २; ४; ५; १०; ११; ११९.१; २[२]; ३–५; ७; ९; १२०.६; १२१.१; ५; १०; १५; १२२.५[२]; १४[२]; १२३.१; २; ४; १२; १२४.४; ५; १२५.७; १२६.२; ३; ५; १२७.७; ८[२]; ११; १२८.६; १२९.६; ७[२]; ९[२]; १३०.१; २; ९; १३१.६; १३२.४; १३४.१[२]; ३; ४; १३५.३; ४[४]; ५[२]; ६; ७; १३६.३; १३७.१[२]; २; ३; १३९.१; ६[२]; ९[२]; १४०.३; ७; ११; १४१.२[२]; ४; ५[२]; ७; ११; १४२.१; ३; ४; ७[२]; १३[२]; १४३.४; १४४.२; ३; ५; १४५.३; १४८.४; १४९.१[२]; ३; १५०.१[२]; १५१.३; ४; ५[२]; ६; १५२.३[२]; ६; ७; १५५.५; १५६.३; ५[२]; १५७.३; ४; १५९.४; १६१.१–४; १०; १६२.५; ११; १६; २०; १६३.७; १३; १६४.८; ११; १३; १६; २१; २७; ३०; ३१[२]; ३२; ३३; ३७; ४७; १६५.२; ४; ९; १२; १४; १५; १६६.४; ९; १३–१५; १६७.२; ५; ६; ११; १६८.१; ३; ४; १०; १७१.२; १७३.१; ३; ११; १३; १७४.८; १७५.२; १७६.१; २; १७७.१[२]; २[२]; ३; ४; १७८.१; २; १७९.४; १८०.५; ६; १८१.२[२]; ३; ६; १८२.८; १८३.३–६; १८४.६; १८६.१; २; ४; ६[२]; ९; १८७.३; १८८.३; ६; ९; १८९.४; १९१.१०; **२**.१.८; १२; १६; २.२; ४[२]; ६; १३; ३.३; ८; ११; ४.३[२]; ५[२]; ६; ५.२; ५; ६.६; ८[२]; ७.१; ८.३; ४; ९.२; १०.५; ११.१५; १२.५; १५[२]; १३.१; २; ६; ९; १४.१; ३; ७; १५.२; १६.८; १७.२; ४; ६; ७[२]; १८.४[४]; ५[४]; ६[२]; १९.५[२]; २२.२; २३.१; ३; ९; १६; २४.२; ७[२]; २६.२; २७.५; १६; १७; २८.९; ११; २९.६; ७; ३०.१; ७; १०; ३२.३; ३३.१; ६; ३४.४–६; ८; ३५.२; ७–९; ३६.१–६; ३७.५; ३८.१–७; ८[२]; ११; ३९.२; ५; ४१.१–३; ९; १३[२]; १९; २१;

४३.२^{२}; ३; **३**.१.१७; १९; २२; २.४; ७^{२}; १२; १३; ३.३; ४; ९; १०^{२}; ४.१; ६; ८^{२}; ११; ५.३; ७; ९; ६.२; ४–७; ९^{२}; ७.१–४; ९; ८.४; ५; ९; ९.५; ८; १०.४; ११.९; १२.१; ५; १३.१^{२}; ४; १४.१; २^{२}; ३; १६.४^{४}; ५; १९.४; २१.४; २२.२; २३.१; ४; २४.३; २५.२; ३; २६.५; २७.६; ९; २९.१; ६; १०; १५; ३०.१; २; ११; १३; १७; १९^{२}; २१; ३१.३; ५; १४^{३}; १८; ३२.२; ५; १०; १३^{२}; १५; १६; ३३.८; १०–१३; ३४.१^{२}; ५; ३५.१; २^{२}; ६^{२}; ९; ३६.९; ३७.१; ९; ११^{२}; ३८.४; ७; ८; ३९.१–३; ५; ४०.२; ८; ९; ४१.१; ३; ४२.१; २; ४३.१; २^{२}; ३; ४; ६; ७; ४४.१^{३}; ४^{२}; ४५.१; ४; ४६.४; ४७.१; ३; ४८.२; ४९.१; ५०.१^{२}; २; ५१.३; ७; ५२.२; ५३.१–३; ५; ८; ११; १४; १५; २०^{३}; ५४.११^{२}; १५^{२}; ५५.१६; १८; ५६.२; ५; ६^{३}; ७; ८; ५७.५; ५८.१; २; ४^{२}; ५; ९; ५९.३; ५; ६०.३; ५; ६१.२; ३; ४^{२}; ६; ७; ६२.५; १५; १६; **४**.१.१–३; ७; १७; २.३; ४; ७; ८; १८; ३.१; ९; ४.३; ४; ९; ५.१५; ६.६; ९; ७.४; ६; ८.२; ९.१; ११.१^{२}; ५; ६; १२.२; १४.१–४; १५.२; ८; १६.१; ५; ८; १०; १८; १७.१४; १६; १८; १८.१; ५; १३; १९.९; २०.१^{२}; २; १०; २१.१; ३^{२}; ५; ६; २२.१; ४^{२}; ८; २३.६; ९; २४.१; २; ८; २५.७; २८.५; २९.१; २; ३०.३; ७; ११; १६; २३; ३१.१; ४; ५; ३२.१^{२}; २^{२}; ५; १०; १२; १५^{२}; १८; २०; २१; ३३.७; ८; ३४.२; ३; ५^{२}; ६; ३५.२; ६; ३६.२; ७; ८^{२}; ३७.८; ३८.१०; ४१.११; ४२.८; ४३.४; ५; ४४.३; ५; ४५.२^{२}; ३; ६; ४६.३–५; ४७.१; ३; ४८.१–५; ४९.३; ५०.३; १०; ५१.८; १०; ५२.५; ७^{२}; ५३.३; ७; ५४.४; ५५.५; ९; १०; ५७.१; ५८.३; **५**.१.७; १०^{२};

११^{२}; २.५; ८; ४.४; ५; ५.३; ७; ९; ६.१–३; ४^{२}; ५^{२}; ६; ७; ८^{२}; ९; १०; ७.३; ४^{२}; ७; ९^{३}; १०; ९.७; १०.१; २; ७; ११.५; १२.६; १३.३; ६; १६.५^{२}; १७.१; ४; १९.२; ३; ५; २१.४^{२}; २३.१; २; ४; २६.१; २; ४; ५^{२}; ९; २८.३; ६; २९.२; ११; ३१.२; ३; ९; १२; १३; ३३.३; ५; ३४.२; ५; ७; ३५.१–३; ८; ३६.१; २; ३७.३^{२}; ४; ३८.४; ३९.१–३; ४०.१; ८; ४१.३; ६; ७; १३; १४; १७; ४२.१८^{३}; ४३.१; २; ६^{२}; ७; ८; १०^{२}; ११^{२}; १२^{२}; १३; १७^{३}; ४४.६; ४५.२; ६; ९; १०; ४६.५; ६; ८; ४७.१; ३; ४८.१; २; ३^{२}; ४९.१^{२}; ५; ५०.३; ५१.१–३; ५; ८–१०; ५२.२; ६^{२}; ७; १२; ५३.२; ६; ८^{२}; ५४.१; ३; ५५.३; ५६.१; ३; ८^{२}; ९; ५७.१; ५८.३; ५९.१; ६; ८; ६०.२; ६१.१२; १६; ६२.२; ४; ८; ६३.७; ६४.५^{२}; ७; ६६.१; ६; ६७.२; ५^{२}; ६९.४; ७१.१; ३; ७२.१; ७३.१; ४; ५; ९; ७४.१; २; ५–७; ८^{२}; ७५.३; ६; ७; ९; ७६.१; ३^{२}; ४^{२}; ५^{३}; ७७.३; ५^{३}; ७८.१^{२}; २–४; ७९.६–८; ८०.५; ८२.५; ७; ८३.१; ६; ७; ८५.६; ८६.३; ८७.३; ७; ८; **६**.१.६; १०; ११; ३.३; ७; ४.६; ५.२; ६.६; ७.१^{२}; ५; ८.४; ९.४; १०.४; ११.१; १२.२; ४; १३.२; ५; १५.१; ३; ५; १७; १८; १६.२; ६; १०; १६; १९; २९; ३१; ३५; ३६; ४०; ४१; ४२^{२}; ४४^{२}; ४६; ४७; १७.१२; १३; १८.९; ११; १९.१; ३; ६–८; ९^{४}; २०.८; २१.४; १०; ११; २२.३; ८; १०; ११^{३}; २३.७; ८; २८.१; ३; २९.२^{४}; ३; ५; ३०.२; ३१.१; २; ५; ३२.४; ३५.५; ३६.३; ३७.५; ३८.२^{२}; ५; ४०.१; ३^{२}; ४; ४१.१; ४; ५; ४२.२; ३; ४४.१२; १९; २०; ४५.१; २१; ३३; ४६.५^{२}; ७^{२}; ८; १४; ४७.६; ९^{२}; २०; ३०^{२}; ३१; ४८.६^{३}; ११; १५; १६; ४९.१; ६; ११; ५०.४; ८–१०; ५१.१; २; ८^{२};

९^{२}; १५; ५२.७^{२}; १६; १७; ५३.७; ८; ५४.७; १०; ५५.१; ६; ५६.६; ५७.५; ५८.४; ५९.२; ५–१०; ६०.३; ८; ९; १४; १५; ६१.२; १४; ६२.२; ५; १०; ११; ६३.१; ३; ७; ११; ६४.४; ५; ६६.३; ५; ६; ११; ६७.३; ६; ७; ८^{२}; ६८.१; ११; ६९.३; ४; ७; ७१.४; ७२.३; ७३.१; ७५.३; १३; ७.१.८; १७; १९–२१; २४; २५; २.६; ८^{२}; ११; ३.९; ४.५; ८; ५.४; ८; ६.२; ६^{२}; ७^{५}; ७.२^{२}; ३; ५; ६^{२}; ८.१; ९.३; १०.१; २; ४; ११.१; २; ५; १२.२; १३.२; १४.३; १५.११; १६.१; ४; ६; ८; ९; १७.२; ६; १८.४; ७^{३}; २०.२; ४; ७; ९^{२}; २१.२; २२.३; २३.१; २४.१; ३^{२}; ४; २५.१; २; २७.१; ५; २८.२; २९.१; ३; ३०.१; ३२.१; २; ४^{२}; ५–७; १३; १४; १९; २०; २४; २६; ३३.२; १४; ३४.४; १०; २०; २२; ३६.१; ३; ४; ६; ३७.१; ५; ८^{२}; ३८.२; ३; ३९.२; ५^{३}; ४१.६; ४२.३–५; ४३.३^{२}; ४^{३}; ५; ४४.५; ४५.१; ३; ४६.४; ४८.१; ५०.१^{२}; ५३.२; ५६.१०; १३; १८; १९; २१; ५७.२; ३; ७; ५८.५; ५९.४; ६; ७; १०; ११; ६०.४; ८; ६१.१; २; ६२.३; ५^{२}; ६४.२; ६५.४^{२}; ६६.१५; १७–१९; ६७.४–७; १०; ६८.१; ४; ६९.१–३; ८; ७०.१^{२}; ५; ६; ७१.३^{२}; ४; ७२.१; २; ५^{४}; ७३.२; ४; ५^{४}; ७४.३^{२}; ४; ७५.१; ३; ७६.२; ७७.४; ७८.४^{२}; ७९.२; ८१.५; ८२.३; ६; ८; ८३.३^{२}; ५; ८४.१; ८७.२; ८८.३; ४; ९१.४; ६; ९२.१; ५; ९३.६^{२}; ९४.४; ७; १०; ११; ९५.२; ५; ९७.२^{२}; ४; ५; ९८.३; ९९.७; १००.७; १०४.९; ८.१.४; ९; १०; १६^{२}; १७; १८; २३^{२}; २४^{२}; २५; २७; २९; ३१; २.१४; १७; २२; २५–२७; २८^{२}; ३.२; १४; १७; ४.२^{२}; ३; ८; १०–१२; ५.७; १०; १३; १५; १६; २४; २८; ३०; ३१; ३२^{३}; ३३; ६.१६; २३; २४; ३६; ४६; ७.११; १३;

२७; ३३; ३५; ८.१; २; ३^{२}; ४^{२}; ५; ६^{२}; ७; ९–११; १३; १४; १७–१९; ९.१; ७^{२}; ८^{२}; १४; १६; १८; १०.१; ५; ६; ११.१^{२}; ७; १०; १३.५; ११; १३; १४; १४.६; १५.१; १६.३; १७.१^{२}; २; ४; ५; ११; १३; १८.४; ७; ११; १६^{२}; १९.१; ४; १५; २७; २८; ३१; ३२; २०.१; २^{३}; ५; ६; १०; १६; १८^{२}; २२; २३; २६; २१.३; ४; ८^{२}; १०; १६; २२.१^{२}; ४; ५; ८–१०; १२^{२}; १५; १७; १८; २३.१०; १२; ३०; २४.१; ३; ४^{२}; ६^{३}; १०; १३; १६; २५; २८; २९; २५.४; ६; १८; २६.४; ५; ८; ९; २०; २१; २३; २७.२; ५; ६; ८^{२}; ११; १८; २०; २२; २८.१; ४; २९.२; ३१.५; १०^{२}; ११; ३२.६; ८; १२; १८; २३; २४; ३३.२; ३; ८; ९; १२^{२}; १३; १४; १६; ३४.१; २; ४; ६–९; १०^{२}; ११–१६; १८; ३५.४–६; १०; २२^{२}; २३^{२}; २४^{२}; ३८.४–७; १०; ३९.७–९; ४०.१; २^{२}; ४१.८; ४२.१; ४; ४४.१; ३; ९; १३; १४; ४५.१; ३; ४; १४; १५; २०^{२}; २३; ३६; ३९–४२; ४६.३; ७; ९; १९; २१^{२}; २५; ३०; ३२; ४८.४; ६; ११; १३–१५; ४९.३–५; ७; ५०.३–५; ७; ५२.७; ५३.३^{२}; ४^{२}; ५^{३}; ५४.३^{२}; ६; ५५.१; ५७.१; ६०.१^{२}; ४^{२}; ५; ११; १७; १८; २०; ६१.१; ३; ६–८; ६२.४; ११; ६३.९; ६४.४^{२}; ६; ८; १०; १२; ६५.१; ३–५; ९; ११; ६६.७; ८^{२}; १२; ६७.४; ११; ६८.१; २; १५; १८; ६९.१; ३; ५; १०; १६; ७०.६; १५; ७१.११; ७२.१; ४; ८; १३; १७; ७३.२; १०; १४; १८; ७४.४; ७; ७५.५; ९; १५; ७७.५; ६; ८; १०; ७८.१–३; ९; १०; ७९.४; ८०.८; ८१.१; ६; ७; ८२.१; २; ४^{२}; ७; ९; ८३.१; ६; ८५.१; ८; ८७.१; २^{२}; ३–६; ८८.३; ४; ८९.२; ७; ९०.१; २; ४; ९१.३; ९२.१; ३; ७; ९; १०; १२; २२; ३१; ९३.१६; १७; १९; २५–२९; ९४.३; ६; ९; ९५.१;

आऽदधानः ९.९०.१
आऽदधुः ५.१६.३; ८.८४.२; १०३.१
आऽदधे ९.७७.४; १०.९७.११
आदने ६.५९.३
आऽदभत् ७.५६.१५
आऽदभुः ३.१६.२; ६.४६.१०
आऽदभे ८.२१.१६
आदम् १.१२६.२
आऽदर्ता ४.२०.६
आऽदर्दिरः ८.१००.४
आऽदर्दिरासः १०.७८.६
आदाम ५.३०.१५
आऽदाय ४.२६.६; ७; १०.१६६.५
आऽदारः १.४६.५
आऽदारिणम् ८.४५.१३
आदितेयम् १०.८८.११
आदित्य १.२४.१५; ३.५९.२; ८.५२.७; १०१.११
आदित्यः १.२५.१२; ५०.१३; १०५.१६; १६३.३; १९१.९; २.२८.४; ३.५९.५; ७.८४.४
आदित्यऽजूतः ८.४६.५
आदित्यम् १.२४.१३; ४.१.२; १०.३६.४
आदित्यस्य २.२८.१; ३.५९.३
आदित्या ५.६७.१
आदित्या १.१३६.३; २.४१.६; ५.६९.४
आदित्या ७.८५.४
आदित्याः १.४१.५; २.२९.१; ८.१८.१२; १९; २२; ४७.११; ६७.७; १५; १६; १८; २०; १०.६६.१२
आदित्याः ३.८.८; ७.३५.१४; ५१.३; ६०.४; ८.४७.४; ९.११४.३; १०.६५.१; ८५.१; २; १२८.९
आदित्याः १.१०६.२; १८८.४; २.३.४; २७.५; ६; ८; ११; १६; ६.५१.५; ६२.८; ८.२७.२२; ४७.१; ६; ८३.५; १०.३५.११; १२; ६३.७; १७; ६४.१७
आदित्यान् १.१४.३; ४५.१; ९४.३; ३.२०.५; ४.२५.३; ६.१६.२४; ५१.४; ७.४४.१; ८.६७.१; १०.३६.१; ६३.३; ५; ६५.९; ६६.४; १४१.३
आदित्यानाम् २.२७.१३; ३.५६.४; ७.५१.१; ८.१८.१; २; ३१.१२; ४७.५; ६७.३; १०१.१५; १०.३५.९; ४८.११; १०३.९
आदित्यासः १.४१.४; १०७.१; ८.१८.१०; ११; १८; ४७.२; ७; ६७.५; १४; १९; २१
आदित्यासः २.१.१३; २७.२–४; ३.५४.१०; ५.५१.१२; ७.५१.२; ५२.१; ८.२७.६; ६७.२; ७७.२; १२६.५; ७
आदित्यासः ८.१९.३४; १०.६३.१३
आदित्येन १०.७७.८
आदित्येभिः १.२०.५; ७.१०.४; ३५.६; ४४.४; ८.९.१२; ९.६१.७
आदित्येभ्यः २.२७.१
आदित्येषु ८.२७.३
आदित्यैः १.१०७.२; २.३१.१; ३.५४.२०; ४.३४.८; ५४.६; ५.५१.१०; ८.३५.१; १३–१५; १०.६६.३; ९८.१; १२५.१; १५०.१; १५७.२; ३
आऽदिदेशति १.४२.२; ६.५६.१; ९.५२.४; १०.१३३.४; १३४.२
आऽदिशः ८.६०.१२; ९२.३१
आऽदिशम् ८.९३.११; १०.६१.३
आऽदिशाम् ६.४.५
आऽदिशे ६.४८.१४; ५६.१; ९.२१.५; ६
आऽदीध्ये १०.३४.५
आऽदुरे ४.३०.२४
आऽदुहः ९.७२.२
आऽदृत्य १.१०३.६; ८.६६.२
आऽदेदिशानः ९.७०.५
आऽदेदिशानान् ६.४४.१७
आऽदेवम् ४.१.१[२]
आऽदेवासः ७.९२.४
आऽदेवीः ६.४९.१५
आऽदेवे २.४.१
आऽद्वादशम् १०.११४.६
आऽधवम् १०.२६.४
आऽधवे १.१४१.३

आऽधानम् १०.९४.८
आऽधिः १०.१०९.३
आऽधीतम् १.१७०.१
आऽधीषमाणायाः १०.२६.६
आऽधून्वते ९.७२.८
आऽधृषः २.१.९
आऽधृषे १.३९.४; १३६.१[२]; ५.८.५; ८७.२; ९.५३.३; १०.४९.४
आऽध्यः १.१०५.७; ८; १०.३३.३
आऽध्ये १०.९५.१३
आध्रः ७.४१.२
आध्रस्य १.३१.१४
आध्राय १०.११७.२
आध्रेण ७.१८.१७
आध्वम् ७.३३.१४
आध्वर्यवम् १०.५२.२
आन १०.५५.५
आनंश ८.६८.८
आनंश ४.२३.२; ८.२४.१७
आनजाना १.१०८.४
आनजे १.१०२.१; ८.६३.१
आनजे १.१६१.४; ८.६३.१
आनञ्जे १.८७.१
आनट् १.७१.८; १२१.१; १६३.७; ३.३०.१२; ६.१.९; १३.४; १५.११; ७.९०.२; ८.४.६; १०.७.२; २०.४; ७०.९; १२२.३
आनट् ४.५८.१; ६.४९.८; ७.७.७; ८.७; २८.२; ८.६.४८; ४५.२७; १०.८.१; २७.७; २९.८; ६७.७; १०२.११; १०४.६; १०८.१; १११.२
आऽनन्दम् ९.११३.६
आऽनन्दाः ९.११३.११
आनम् १.५२.१५
आऽनमम् ४.८.३
आनवम् ८.७४.४
आनवस्य ७.१८.१३
आनवाय ६.६२.९
आनवे ८.४.१
आनश ३.६०.१; १०.६२.१
आनश ३.६०.२; ४.३६.४
आनशुः १.५२.१४; २.२४.६; ५.१०.३; ६.२२.४; ८.३.१३; ९.१०८.४; १०.५३.१०; ६६.२. १४७.३
आनशुः १.११०.४; १५१.९; १६४.२३; २.२३.२; ३.६०.३; ८.३.१६; १२.१९-२१; ९.२२.३; ५; १०.६३.४
आनशे ५.७.८; १०.१००.२
आनशे १.८४.६; ५.८१.५; ९.४८.५; १०.९६.७
आनश्म १०.३१.३
आनश्याम् ६.२६.७
आऽनह्यमानः १०.१०२.८
आनाश ६.१६.२६
आऽनिनाय ८.२१.९
आनीत् १०.१२९.२
आनीत् १०.३२.८
आऽनीतः ९.९६.२४
आनुषक् १.१३.५; ५२.१४; ५८.३; ७२.७; २.६.८; ३.११.१; ४१.२; ४.४.१०; ७.२; ५; १२.३; ५.६.६; १०; ९.१; १६.२; १८.२; २१.२; २२.२; २६.८; ६.५.३; ४८.४; ८.९.१७; १२.११; १३.३०; २३.६; २६.६; २७.७; ४४.८; ४५.१; ५३.६; ९.१०२.७; १०.४९.५; ६; ८३.१; १७६.२
आनुऽस्तुभस्य १०.१८१.१
आनूकम् ५.३३.९
आनृचुः १.१९.४; ५.६.८; ८.५१.४
आनृचुः ८.५१.१०
आनृचे १.१६०.४
आनृधे १०.७९.७
आऽनेता ९.१०८.१३
आऽनोनवीति १०.६८.१२
आन्त्राणि ४.१८.१३
आन्त्रेभ्यः १०.१६३.३
आप १.१२२.९; ४.५१.७; ५.४५.६
आप १.७६.१; ४.१.९; २३.२; ४१.१; ५.४२.६; ७.९९.२; १०.३२.८
आपः १.८.७; २३.२०; २१; २३; २४.६;

३२.२; ८; १०; ११; ३३.११; ५७.२; ६३.८; ६५.२; ८३.१; २; ९६.१; १००.१५; ११६.९; १२५.५; १५३.४; १६१.९; १६९.३; १७३.८; १७५.६; १७६.६; १७८.१; २; १९०.७; २.२४.१२; ३०.१; ३५.३; ४; १४; ३८.२; ३.१.११; २२.३; ३०.९; ३३.७; १३; ३५.८; ३६.६; ५१.५; ५४.१९; ५५.२२; ५६.४; ७; ४.३.१२; १७.२; ३; १८.६–८; ३३.७; ३८.४; ४७.२; ५७.३; ५.३४.९; ४१.११; १२; ४५.१०; ४७.५; ५३.१४; ५४.२; ५८.६; ६.२४.६; ३४.४; ४०.२; ४८.५; ६६.११; ७.१८.१५; २३.४; ३४.२; ३; २३; २५; ३५.८; ४७.१; ४९.१; २^{२}; ३; ४; ५६.२५; ८५.३; ९०.४; १०१.४; १०३.२; ८.६.३४; १३.८; १५.८; ३२.२३; ३३.१; ३९.१०; ४९.३; ५०.३; ५४.४; ५९.२; ६९.११; ८९.४; ९६.१; १०२.१४; ९.२.४; ६.४; २४.२; ६६.१३; ८२.३; ५; ८८.७; ११३.८; १०.२.७; ४.५; ९.१; ३; ४; ७; ९; १७.१०; २७.२०; ३०.६; ८; १२; १३; १५; ३७.२; ६; ४३.७; ४६.९; ६४.९; ६५.१३; ६६.९; १०; ७८.५; ८२.५; ६; ८५.४७; ८८.२; ८; १८; ८९.१३; ९१.६; ९५.१३; ९८.६; १०४.८; १०९.१; १११.८^{२}; १२१.७; ८; १३७.६^{३}; १३९.४

आपः १.२३.२२; ६.५०.७; ७.४७.२; ८.७४.१५; १०.९.८; ३०.७; ११; ७५.१

आपःऽइव ३.५.८; ५.६०.३; ७.१०४.८; ८.९४.७

आपत् ९.९२.१

आपत् ८.७०.७; १०.१०६.७

आपतुः १०.११४.१

आऽपथयः ५.५२.१०

आऽपथ्यः १.६४.११

आपन् ६.१.४

आऽपनीफणत् ४.४०.४

आऽपप्राथ १०.१३४.१

आपप्रिऽवांसम् १.१४६.१

आपप्रिऽवान् १.७३.८; १०.१३९.२

आऽपप्रुषी ४.५२.६; ६.६१.११

आपयः १.११०.२; २.२९.४; ३४.१०; ५.५३.२

आपयायाम् ३.२३.४

आपये १.२६.३; २.३८.११; ७.८.६

आपानम् २.३४.७

आपानासः ९.१०.५

आपान्तऽमन्युः १०.८९.५

आपिः १.२६.३; ३१.१६; ३.५१.६; ९; ४.१७.१७; २५.६; ६.२१.८; ४४.१०; ४५.१७; ७.८८.६; ८.३.१; ४५.१८; १०.११७.७

आपित्वम् ८.२०.२२; २१.१३

आऽपित्वे ८.४.३

आऽपिप्यानम् ४.२७.५

आऽपिब्दमानः १०.१०१.११

आपिम् ८.६०.१०; १०.७.३

आपिरे ९.१०८.४

आपिषु २.२९.४

आपी इति ४.४१.२; १०.१०६.४

आऽपीतासः ८.९.१९

आपीन् ७.३१.१२

आपुः १.२४.६; ३३.१०; १००.१५; १६७.९; १७९.२

आपुः १०.५४.३

आऽपूर्णः ३.३२.१५; ९.७४.२

आऽपृक् १०.८९.१४

आऽपृचः ८.४०.९

आऽपृचे ५.५०.२

आऽपृच्छ्यः १.६०.२

आऽपृच्छ्यम् १.६४.१३; ९.१०७.५

आऽपृणन् ४.५३.२

आऽपृणन्तः ७.७५.३

आपेः २.२७.१७; २८.११; २९.७; ४.३.१३; १०.८३.६

आप्तः १.३०.१४

आप्ताः ९.११३.११

आप्त्यः १.१०५.९; ९.४१.९; १०.८.८

आप्त्यम् १०.१२०.६

आप्त्यानाम् १०.१२०.६

आप्त्याय ८.४७.१४

आप्त्ये ८.१२.१६; ४७.१३; १५; १७

आप्नानम् १०.११४.७

आप्यम् १.३६.१२; १०५.१३; ३.२.६; ७.१५.१; ३२.१९; ८२.८; ८३.१; ८.१०.३; २७.१०; ७३.६; ९७.७; ९.६२.१०; ११०.६; १०.६३.१; १४२.१

आऽप्यायमानः १.९१.१८

आऽप्यायमानाः १०.१८.२

आप्येन २.२९.३

आप्रस्य १.१३२.२

आऽप्रुषायन् १०.६८.४

आऽबभूथ १०.८४.५

आऽबभूव १०.१२९.६; ७

आऽबाधः ८.२३.३

आऽभगः १.१३६.४^{2}; १०.४४.९

आऽभगम् ८.५३.६

आभरत्ऽवसुः ५.७९.३

आऽभासि १.४९.४

आभिः ६.२५.२^{2}; ८.२३.२३

आभिः ४.१०.४; १७.१८; ५.३८.५; ८३.१; ६.१८.१; २२.१; २४.६; ४९.१०; ५२.१; ६३.६; १०.४९.३

आभिः ५.३२.१०; ६.२२.११; ७.९१.६; १०.७३.५

आभु १०.१२९.३

आभुम् १०.२७.१; ४

आभुवः १.६४.१; ६; ९.६५.२७

आऽभुवत् ८.१०२.८

आऽभुवम् १.१३३.७^{2}; १५१.४

आऽभूत्या १०.८४.६

आऽभूभिः १.५१.९; ५.३५.३

आऽभूषति १.१३६.५

आऽभूषन्तः १०.१६०.५

आऽभूषन्तीः १.४३.९

आभूषु १.५६.३

आऽभूषेण्यम् ५.५५.४

आऽभृतः २.३६.५; ४.५८.११

आऽभृतम् १.२५.१७; १६१.१०; ६.४७.२७; ९.६६.३०

आऽभृता ६.१६.४८; १०.१७०.४

आऽभृत्य १०.७१.३

आऽभोगम् ७.९४.१२

आऽभोगयम् १.११०.२

आऽभोगये १.११३.५

आभ्यः २.३२.२

आभ्यः ६.३०.३; १०.१७.१०

आभ्याम् २.४०.२

आभ्याम् ४.३२.२२

आमऽअदः १०.८७.७

आमः ९.८३.१

आममत् ९.११४.४; १०.५९.८–१०

आमयन् १०.८६.२३

आमयति १०.९७.९

आऽमरीता ४.२०.७

आमस्य १.१६२.१०

आमा ३.३०.१४; ४.३.९

आमायाम् १.१८०.३

आमासु १.६२.९; २.३५.६; ४०.२; ६.१७.६; ७२.४; ८.८९.७

आमित्रः ६.२८.३

आऽमिनाना १.९२.१०

आमिनाने इत्याऽमिनाने १.११३.२

आमिश्लऽतमः ६.२९.४

आमिषि ६.४६.१४; १०.९४.३

आऽमुरः ४.३१.९; ८.२४.५; ३९.२; ९.६१.२४

आऽमुरिम् ८.९७.१०

आऽमुष्य ३.४८.४; ८.४.४

आऽमेन्यस्य ५.४८.१

आमेन्याने इत्याऽमेन्याने १.९६.५

आऽयजन्ते ३.४.२

आऽयजसे १.९४.२

आऽयजाते ७.६०.११

आऽयुजिम् ८.२३.१७

आऽयजिष्ठः २.९.६; १०.२.१

आवताम् १०.११३.१
आवतुः १.१६१.१०
आवथुः १०.१३१.५
आऽवदन् १.११.६; २.४३.३
आवन् ४.४४.६
आवन् ३.३०.१०; ८.७.२४; ५४.१
आवम् ४.२६.३; १०.४९.३
आवयः ८.४५.३८
आवयत् १०.११३.८
आऽवयाः १.१६२.५
आऽवरः ८.१३.२१; १९.३०
आऽवरत् १.१४३.६
आवरित्याव: १०.६७.४
आवरित्याव: १.९२.४; ११३.४; १४; ३.५.१; ५.४५.१; ६.४४.८; ७.७९.१; ९५.६; ९.९७.३८
आऽवर्जते १.३३.१
आऽवर्तनम् १०.१९.४; ५
आऽवर्तयन्ति ८.६९.१७
आऽवर्त्नती: १०.३०.१०
आऽववर्तत् २.३४.१४; ६.६८.१; ७.८५.४
आऽववर्तति ५.७३.७
आऽवहन्ती १.४८.९; ११३.१५; ४.१४.३
आऽवहन्तीम् ५.८०.१
आविः १.३१.३; ८६.९; ११६.१२; १२३.६; १०; ११; १२४.४; १३१.३; १४३.२; १४६.४; २.१५.७; २३.१४; ३.३४.३; ५५.१५; ४.१.१६; ३.११; ४.५; १६.८; ५.१.९; २.९; ८३.३; ६.१७.३; ४८.१५; ६४.२; ७.५८.५; ७६.१; १०३.८; ८.८.२३; १४.८; ४७.१३; ९.३.५; ७९.५; ९५.२; १०.२७.२४; ४८.१०; ५४.५; ६८.६; ७१.१; ८८.२; ९६.११; १०७.१
आविःऽऋजीकः ४.३८.४
आविःऽकृण्वतीम् ७.८०.१
आविःऽकृण्वानः ४.१७.३
आविःऽकृण्वाना ५.८०.४; ७.७५.१
आविःऽत्यः १.९५.५
आविःऽत्यम् १०.१००.७

आविथ १.१३१.५[२]; २.१३.९; ८.३.९; १२; १२.२; ६८.१०; ८०.२; ९.६१.२२; १०.१२०.७
आविथ १.५१.५; ६; ५३.१०; ५४.६; ८.३६.७; ३७.१; ६; ७; ४६.११
आऽविदे १०.११३.३
आऽविद्वान् ४.१९.१०
आऽविवाय १०.१०७.५
आऽविवासतः ७.९४.११
आऽविवासताम् ७.१०४.२१
आऽविवासति १.१२.९; ८४.९; २.२६.३; ६.६०.११; ८.१९.१३; १०.९३.२
आऽविवासन् १.१५२.६; ७.७२.३; ९.३९.५
आऽविवासन्तः ५.४५.३; ४
आऽविवासन्ती ५.४७.१
आऽविवाससि १.३१.५
आऽविवासात् ७.२०.६; १००.१
आऽवित्रासान् २.११.१६
आऽविविद्रे ३.५४.४
आऽविवेश ६.७४.२; ८.४८.१२; १०.१६.६
आऽविशन् ५.२५.४; ७.५५.१; ८.१५.१३; ९.२५.४; २८.२; ५६.२; ६०.३; ६२.१९; ८६.१९; २३
आऽविशम् २.२४.६
आविषुः ४.३६.६
आविषुः १.११.५
आऽविष्टितः १०.५१.१
आवीत् ७.२०.२; ९.९७.३९
आऽवृणानः ४.१.२०
आऽवृणीमहे ६.१५.९; ८.८३.४
आऽवृतः १.८७.४; ८.२६.१३
आऽवृतः १०.१३०.७
आऽवृतम् १.५१.२; १६४.१४; ३.३.५; ६.४७.२७; ८.८८.२; ९.८६.२७
आऽवृतम् २.३६.६; ५.४६.१
आऽवृता ९.७४.२
आऽवृतासः १.५५.८
आऽवृते ३.४२.३
आऽवृत्य १.५६.१

आऽवृत्वत् ८.४५.३६
आऽवेशयन्तीम् १०.१२५.३
आश्य १.१६६.१३
आश १.१६२.९; ३.३६.८
आश ८.४७.६
आशत १.८.६; ८७.५; १०.९२.३
आशत १.२०.२; ८५.२; २.२१.५; ३.४५.३; ७.६६.११; ८.४३.१७; ५९.२; ६९.१८; ९७.९[२]; ९.६.४; १८.३; २१.४; २२.६; २४.२; ६७.७; ६९.७; ७३.९; ८३.१; ४; १०.९२.७; ९४.२
आशतुः ८.२५.८
आऽशयानम् १.१२१.११; २.११.९; ४.१७.७; १९.३; ५.३०.६
आऽशये ८.४१.७; १०.१६२.१; २
आशवः १.५.७; ११८.४; १३५.६; १४०.४; २.३१.२; ५.६.१; ८.१.१५; १९.६; ४६.२३; ४९.८; ७४.१४; ९.१३.६; १७.१; २२.१; २३.१; ६२.१; ६३.४; २६; ६४.४; १६; ६७.७; ६९.६; ७; ८३.२; ८६.१; २: १०.७८.५; ९४.१; ८; ११९.३
आशवे १.४.७
आऽशमः ५.३२.११; ५६.२, ८.२४.११; ६६.१२; ९२.१३; ९.१.५
आऽशसनम् १०.८५.३५
आऽशसा ४.५.११; ८.७३.९; ७८.१०; १०.१६४.३
आशाः १.३९.३; १६२.७; ४.३७.७; ५.१०.६; १०.१७.५; ७२.३; ४
आशाते इति ५.६६.२
आशाते इति १.२५.६; १३६.३; १४४.६; ५.६८.४; ५; ८.३१.६
आशाथे इति १.२.८; १५.६; १५१.८; ९; ५.६७.१
आशाभ्यः २.४१.१२
आशितम् १०.३७.११; ११७.१; ७
आशिताः १०.९४.१०
आशिनेभ्यः १.२७.१३
आऽशिरम् १.१३४.६[२]; ३.५३.१४; ८.२.१०; ११; ६.१९; ३१.२; ६९.६; ९.६४.१४; ७०.१; ७५.५; ८६.२१; १०.४९.१०; ६७.६
आऽशिरा ८.३१.५
आऽशिषः १.१७९.६; ३.४३.२; ७.१७.५; ८.४४.२३; ५४.७
आऽशिषम् ८.९३.१८; १०.६७.११
आऽशिषा १०.८१.१
आशिष्ठाः २.२४.१३
आऽशीः १०.१२८.३
आशीःऽवन्तः १.२३.१
आशीःऽवान् ८.९५.७
आऽशीर्तः ८.२.९
आशु १.८४.१८
आशुऽअश्वाः ५.५८.१
आशुऽअश्व्यम् ५.६.१०; ८.६.२४; ३१.१८
आशुः ४.११.४; २२.८; ७.१८.९; ६६.१४; ९.३९.१; ५६.१; ६४.२०; १०.१०३.१
आशुः ४.३३.४
आशुऽपत्वा ४.२६.४
आशुऽभिः १.३७.१४; २.१६.३; ३४.३; ३८.३; ५.५५.१; ६१.११; ८.५.७; १३.११; ४९.७; ६५.१; ९.१५.१; १०.४९.७
आशुम् १.४.७; ६०.५; ९१.२०; ११७.९; १३५.५; २.३२.३; ३.९.८; ४.१.३; ७.४; ११; ३८.२; ३९.१; ४३.२; ५.४४.१; ७.७१.५; ८.९९.७; ९.६२.१८; १०.१०७.१०; १७८.१
आशुम्ऽइव १०.१५६.१
आशुऽया ४.४.२; ६.४६.१४
आऽशुशुक्षणिः २.१.१
आशुषाणः ५.३६.४
आशुषाणाः १.१४७.१; २.१९.७; ४.१.१३; २.१४; १६
आशुषाणासः ४.२४.४; ७.९३.८
आशुषु ८.३४.१८
आशुहेमऽभिः १.११६.२
आशुऽहेमा २.१.५; ३१.६; ३५.१; ७.४७.२

आशुऽहेषसा ८.१०.२

आशू इति ३.३५.४

आशून् ४.२९.४; ६.६०.१२

आशून्ऽइव १०.६८.२

आऽशृण्वतीः ५.४५.१०

आऽशृण्वते ४.३.३

आऽशृण्वन्ति १.१९०.१

आशोः ४.३८.९

आश्राम् १०.९५.१६

आऽश्रवयति ५.८२.९

आश्रवयन्तःऽइव १.१३९.३

आश्रुत्ऽकर्णं १.१०.९

आश्वऽघ्नस्य १०.६१.२१

आश्वपःऽतरेभ्यः १०.७६.५

आश्वऽमेधस्य ८.६८.१५

आश्वऽमेधे ८.६८.१६

आश्वश्वऽतमाः ५.४१.४

आश्विनीः ९.८६.४

आष्ट १.१२१.६

आष्ट्रयाम् १०.१६५.३

आस ५.२.५; ७.१.२; १०४.१४; ८.२०.१५; १०.२७.११

आस ४.२७.२; ३५.४; ५६.३; ५.४४.२; ५३.१; ६.४७.२; ७.३२.१०; ८६.४; १०.३१.७; ६१.१८; ८१.४; ८३.२; १२०.१; १२४.६; १२९.२

आसः ७.९९.७; १००.७

आसक्तिः १०.८५.२८

आऽसङ्गः ८.१.३३

आऽसङ्गस्य ८.१.३२

आसत १०.९५.७

आसतुः १.१६१.१२

आसते १.१९.६; १६८.३; ७.३२.२; ९.१५.२; २५.४; ११३.११; १०.१७.४; ६३.१

आसते १.३६.७; ४८.६; १०५.११; १६४.३९; २.१३.४; ३.२.६; ९.३; ६.४७.१९; ८.८.८; ३३.१; ६९.१७; ९.१०.७; ७३.३; ८६.१; ३९; १०.२१.३; २५.२; ३८.५; ४०.७; ६५.७; ९४.९; १०९.७; ११४.२; १३०.१; १५१.४; १५३.१; १५४.१; १७९.२

आऽसत्सि ३.३०.१८

आसथुः १०.३९.५

आऽसदम् ३.६२.१३; ४.९.१; ८.१.८; ९.३.१; ८.३; २५.६; ३०.४; ५०.४; ६२.१६; ६४.२२; ७१.१; ६; ८२.१; १०१.१४; १५

आऽसदे १.१३.७; ३.४१.९; ५.२६.८; ४६.५; ८.६०.१; ६५.६; १०.१८८.१

आऽसद्य १.१०९.५; २.३६.२; ६.५२.१३; ६८.११; १०.१७.८

आसन् १.१०९.७; १७९.२; ३.३२.४; ५.३०.१०; ७.९१.१

आसन् ३.२६.७; ५.१८.४; ६.७.१; ८.९६.३; १०.७३.३; ८७.२; ९८.२; ३

आसन् १.१६४.४३; ५०; १७१.४; ४.४२.८; ५.५२.१२; ७.२९.४; ३३.६; ७६.३; ४; १०.२७.४; १७; ८५.८; ९०.१५; १६; १२९.५[२]

आसनि १.७५.१; ४.४०.४; ५.६.९; ८.१२.१३; ३९.३; ९.६९.२; १०.५३.११

आसन्ऽइषून् १.८४.१६

आसऽभिः १.३४.१०; १६६.११; ४.४५.३; ९.९९.३; १०.७६.७; ९४.२

आसम् १०.२७.४

आसया १.२०.१; १२७.८

आससे ८.८०.५

आऽसस्राणासः ६.३७.३

आसा १.७६.४; १२९.५; १४०.२; १५२.६; १६८.२; २.१.१४; ४.५.१०; ५.१७.२; ५; २३.१; ६.३.४; ११.२; १६.९; ३२.१; ७.१६.९; ८.६.२०; १९.२४; १०.१.३; २०.३; ४०.६; ६७.१०; ११५.३

आसात् १.२७.३; ४.२०.१

आसाते इति २.४१.५

आसाथे इति ५.६२.५

आसाथे इति १.१८२.३

आसानः ६.१०.६

आसानेभिः ६.५१.१२

आसाम् १.१२४.९; १०.९२.१४
आसाम् १.६८.४; ८८.६; १३३.३; २.३०.१; ३.३१.२०; ३४.५; ५६.४; ४.५१.६; ५८.५; ५.४४.९; ११; ४५.८; ६.२८.३; ७.३४.१०; ८.७०.१२; ९.८७.३; १०.२२.१२; ६८.७; ७५.४; १०३.८; १११.८[२]; १०; १३९.४; ६
आऽसाव ८.१०३.१०
आऽसिचम् २.३७.१; ७.१६.११
आऽसिञ्चन्तीः ५.८५.६
आऽसिञ्चाः १०.३०.५
आसिथ ६.४५.११; १७
आऽसिस्विदाना १०.१०६.१०
आसीः १०.९५.५
आसीत् १.३२.११; ५.३०.१५; १०.१७.२; ७१.१; ८८.४; १२१.८; १२९.३; ४; १८१.२
आसीत् १.३२.९; १६३.९; १६४.९; १६५.६; ४.१८.१२; ७.१८.६; ८.५८.१; १०.३३.१; ३४.२; ५१.१; ८१.२[२]; ८५.६–८; १०[२]; १५; ९०.६; १२; १४; १०२.६; १०८.१; १०९.२; १२१.१; १२९.१[४]; २[२]; ३; १३०.३[४]
आसीत् ७.२०.७
आऽसीदन्ति १०.८५.३२
आसीनः २.४३.३; १०.२७.१३
आसीनम् ८.१००.५
आसीनाः ३.३१.१२; ९.७८.३
आसीनासः १०.१५.७
आसीनेषु ६.४७.१९
आसी३त् १०.१२९.५
आसी३त् १०.१२९.५
आसु १.१७३.८; ४.३७.१; ६.५.३; २८.८; ४४.१८; ७.६७.६; ८८.७; १०.८६.११; १४४.३
आसु १.९५.५; ३.५५.९; ४.३८.६; ६.६१.१३; ७२.४; ८.४१.७; ८; ९.८६.४३; ९९.७; १०.२७.८; ४९.१०[२]; ६१.२०; ९५.८; ९; १०४.९
आसुः ६.१९.४; २१.५; ११
आसुः ४.५१.७; १०.९२.३
आऽसुतिः ८.१.२६
आऽसुतिम् १.१०४.७; २.१.१४; ७.९७.७
आऽसुनोति १०.४२.५
आसुरः ३.२९.११; ५.४०.५; ९
आसुरस्य ५.८५.५
आसुरे १०.१३१.४
आऽसुवन्ति ४.५४.६
आसे ७.२०.३
आऽसेचनानि १.१६२.१३
आस्क्राः १.१८६.२; ७.४३.५
आस्क्रे इति ३.६.४
आस्तम् १.१२०.७
आस्ताम् ३.४.११; ७.२.११
आस्ताम् ८.५९.२; १०.८५.९–११
आस्ते ७.५५.६; १०.७१.११; १०७.१०; १३९.२
आस्त्रऽबुध्नाय १०.१७१.३
आऽस्थाता ६.४७.२६
आस्नः १.११६.१४; ११७.१६; ८.६७.१४
आस्ना ५.७३.६
आस्ने २.३९.६
आस्यत् ४.३०.२०; १०.७२.८; १३८.३; ४
आस्यम् २.१.१३; १३.८
आस्यात् १०.३९.१३
आस्ये १.३८.१४; १६२.८; ४.४९.१; ५.१२.१; ७.१५.१; १०२.३; १०.९१.५; १५
आस्येन १.६१.३
आह २.२८.१०; ४.२५.४; ५.३७.१; ७.४१.२; १०४.१५; १६[२]; ९.७०.९; १०.४९.७
आह ४.१९.१०; ३३.५[३]; ५.४४.१४; १५; ७.१८.४; ८.१.३४; १००.३; १०.२७.१८
आऽहवः १०.८५.१२
आहनः १०.१०.६; ८
आहनसः ९.७५.५
आहनसम् १०.१२५.२
आहनाः २.१३.१; ५.४२.१३
आऽहवनानि ७.१.१७; ८.५

इ

इच्छसे ८.२१.१३
इच्छस्व १०.१०.१०
इच्छात् १०.२७.९; ९५.१२
इच्छामि ६.२८.५
इच्छामि ३.३८.१
इच्छेत् १०.११७.४
इटतः १०.१७१.१
इळः १.१२८.१[२]; २.१०.१; ३.४.३; ५.४२.१४; ६.१.२; ५८.४; ७.४७.१; १०.१७.९; ७०.१; ९१.१; १९१.१
इळया ३.५३.१; ५४.२०; ५९.३; ५.४.४; १०.६४.११
इळा १.१३.९; १४२.९; २.१.११; ३.८; ३१.४; ३.४.८; ७.५; ५५.१३; ४.५०.८; ५.५.८; ४१.१९; ७.२.८; १६.८; ८.३१.४; ९.५.८; १०.३६.५; ७०.८; ११०.८
इळा १.१२८.७; ३.२४.२; २७.१०
इळानाम् ९.१०८.१३
इळाभिः १.४८.१६; १८६.१; ५.५३.२; ७.३.७; ६५.४; ८.३२.९
इळाम् १.३१.११; ४०.४; ३.१.२३; ५.११; ६.११; ७.११; १५.७; २२.५; २३.५; ६.१०.७; ५२.१६; ७.४४.२; ६४.२; १०२.३; ९.६२.३
इळायाः ३.२३.४; २९.३; ४; १०.१.६; ९१.४
इळावतीम् ९.९७.१७
इळावन्तः १०.९४.१०
इळावान् ४.२.५
इळासु ५.६२.५; ६
इळै १.१८८.८
इव १.१.४; ६; ४.२; ५; ६; ७.१; २; ९.५; १०; १०.६; ७; १५.५; १६.८; १७.६; २१.१; २२.१४; २४.१२; २५.६; २६.६; २७.३; २८.१–४; ६; ३०.२; ३२.१५; ३३.२; ३४.२; ३६.१; ६; २०; ४०.२; ६[२]; ४१.८; ४६.१२; ४७.८; ५१.४; ८; १३; १४; ५२.११; ५३.३; ७; ५४.९; ५५.४; ५; ५९.१; २; ६१.१–१५; ६४.८; ६७.४; ६८.२; ७१.३; ७२.३; ६; ७४.५; ७७.१; ७९.११; ८०.१; ७; ८१.१; ८२.१; ८३.१; ६; ८४.२; ७; ८५.८; ८७.५; ८९.१; ९; ९२.३; १०४.५; १०५.२; १०६.५; ११४.३; ४; ८; ९; ११५.४; ११६.६[२]; १०; २५; ११७.१९; १२०.२; १२२.१०; १२३.४; ८; १२४.६; १२५.६; १२८.६[२]; १२९.११; १३१.५; १३२.५; ६[२]; १३३.७; १३४.६; १४०.१३; १४१.४–६; १४४.३; १४५.२; ३; १४७.३; १४८.२; १४९.१; १५०.३; १५२.४; १५४.३; १५५.२; ४[२]; ५; १५६.२; १६१.१; ४[२]; १६२.३; २१; १६३.७; ९; १६४.८; १५; २२; २३; ३२; ३७; ३९; ४७; १६५.१०; १२; १६८.९; १७०.३; १७१.२; १७९.३[२]; १८५.८; १८७.८–१०; १९०.५; २.२.२; ११.३[२]; ११; १५; १६[२]; १७; १३.१०; १४.१; २३.२; ५; १३; २४.५; ९; ११; १२; २५.१; ५; २६.१[४]; ३; २८.९; २९.४; ३४.१४; ३५.८; १०; ३७;२; ३९.१; ४१.४; १९; ३.१.१४; २.१५; ४.७; १०; ५.२; ६; ७.८; ८.१०; ९.९; १८.५; २६.८; २९.१५; ३०.५; १२; ३१.५; ११; १५; ३२.४; ७; ३८.३; ७; ८; ४०.६; ४२.८; ४३.१; ५३.४[३]; १३; ५४.८; ५५.३; ४.१.१; ८; १८[२]; २.४; ५; १०; १६; ३.१२; १३; ४.७[२]; १३; ५.३; ७; ७.७; ९[२]; ८.४; ९.६; १२.५; १६.१; १६; २०; १७.५; १९.१; २१.२; २२.५; १०; २३.१०; २४.३; ४; ५[४]; ६; २५.६; २९.३; ३०.३; ५; ८; २२; ३१.७; ८; ३२.४; २०; ३३.२; ३५.८; ३७.६; ३९.५; ४०.१[२]; ४१.७; ४४.४; ५०.७; ८; ५१.९; ५४.२; ५६.३; ५.२.४; ११; ३.७; १२; १२.२; १६.४; १७.५; २५.२; २८.२; २९.१३; ३०.४; ६; ८; ३१.७; ३२.३; ५; ३४.४; ५; ३५.६; ३६.३; ३९.५; ५३.९; ५५.६; ७; ५६.२; ५८.५; ७; ५९.५; ६०.४; ६१.८; ७३.९; ७७.४; ७९.९; १०; ८१.१; ३; ५; ८५.४;

७; ८६.३; ६.१.५; ९; १२; ३.५; ७.६; ९.३; १४.२; १५.१; ११; १८.४; १९.१३; २०.१३; २१.३; २२.१; २३.१; १०^{२}; २८.२^{२}; ३; ५; २९.६; ३०.१^{२}; ४; ३३.२; ३४.३; ४२.३; ४; ४४.५^{२}; १०; ४५.६; १६; १७; ४६.१; ४७.१५; २२; ५०.६; ९; ५१.८; ५२.१४; ६६.३; ६; ६८.५; ७०.४; ७२.४; ७५.३; ७.१.१४–१६; २.३; १०; ३.५; ४.२; ८; ८.५; ११.२; १६.११; १८.४; ६; ९; १४; २४; १९.८; २०.७; २२.६; ७; २३.२; ६; २५.४; २८.१; ५; २९.४; ५; ३०.५; ३१.२; ३२.८^{२}; ९; १२; १४; १६; १८–२१; ३३.३^{३}; ५; ६^{२}; ७; ९; ४०.३; ४१.५; ५६.२३; ५८.३; ७२.४; ७६.३; ४; ८१.२; ८२.४; ८५.४; ८६.३; ६; ९१.३; ९४.१२; ९६.१; ३; ९८.१; २; ५; १००.६; १०२.३; १०४.१२; २१; ८.१.१; ७; १४; १७; ३०; २.४; १३^{२}; १७; २५; ३१; ३३; ३.५; ८; १६; २४; ४.९^{२}; १४; ५.३८; ३९; ६.१०–१२; १८; २१; २२; ३०; ३७; ४४; ९.३; ९; १०; १०.२; १२.८; १०–१२; १७; २४–३०; १३.९; ११; १५; १७; १८; २०; २६; १४.१; १२; १६.५; ६; १८.१४; १९; १९.६; १४; १७; १८^{२}; २९; ३५; २०.१३; १७; २१.२; ७; १३; १४; १७; १८^{२}; २२.१४; २३.८; १३; २४.१६; १९; २६.१७; २८.४; ३०.१; ३१.१^{२}; २; १२; १५^{२}; १६^{२}; १७^{२}; १८^{२}; ३२.१७^{२}; ३३.१०; १८; ३५.७; ३६.७; ३७.४; ७; ४०.१; २; ४२.१; ४३.३; २९; ३०; ४४.१५; ४५.२; ३; १०; १९; ३०; ३१; ३३; ३९; ४६.१२; २९; ४७.४–६; ५१.४; ७^{२}; ८^{२}; ९; ५३.५; ८; ५४.६; ५५.१; ५; ५६.४; ५७.३; ६०.५; १०; १५; १६; ६१.४; ११; १२; ६२.१२; ६६.४^{२}; ६; १३; १५^{२}; ६७.८; ६८.७; ६९.११; १३; १४; ७०.१४; ७१.२; ७२.११; ७४.१०; १५; ७५.१४; ७६.८; ९; ७७.३; ५; ७; १०; ७८.७; ९; १०; ७९.१; ५^{२}; ८०.३; ६; ९; ८२.७–९; ८३.१; ६; ९०.५; ९२.३; ५; २१; ३२; ३३; ९३.१; ५; १८; ३०; ९६.१७; १९^{२}; ९७.१; ७; ९९.३; १००.१; ६; ९.१.५; १०; ११.६^{२}; २१.३; ४२.४; ४७.२; ४८.४; ५९.४; ६१.१४; ६४.२; ७०.३; ७३.२; ३; ७७.२; ८३.१; ९५.३; ९६.१५; ९८.७; १०६.३; ११२.४; १०.२.३; ४.७; ५.६; ७.३; ८.९; १३.५; १४.१६; १६.७; ११; १७.१०; १४; २०.६; ८; २२.१५; २३.३–५; २७.२–५; ८; १०; १८; २०; २१; २८.१; २९.१; ३०.६; ३१.६; ३२.३^{२}; ४^{२}; ८; ९; ३३.८; ३४.५; ७; ८; १३; ३५.८; ३९.३; ४; ४२.९; ४३.२; ३^{२}; ४८.५^{२}; ९; ४९.११; ५०.५; ५१.४; ५२.६; ५३.११; ५४.२; ५; ५५.६; ६१.२; ११; १३; ६२.५^{२}; ६३.१६; ६८.२; ७३.९; ७५.४^{२}; ७६.३; ८१.४; ८२.१^{२}; ६; ८५.४; ६; १६; ३४; ८६.३; १४; १६; १७; ८८.८^{२}; ११^{२}; १७; ८९.७; १०^{२}; १३; ९१.३; ६; ८^{३}; ९; ९२.३; ९३.१५; ९४.१०; १३^{२}; ९७.५; ९९.६; १००.१; ८; ११; १०१.३; ७; १०६.१; १०८.८; १०९.३; १११.९^{२}; ११२.६; ११४.८; ११५.१; ५; ६; ११६.८; ११७.१; ३; ५–७; ११९.१०; १२०.१; १२१.३; १२२.७; १२४.६; १२७.३; १३२.१; १३६.३; १३७.६; १३९.५; १४१.४; १४५.३; १४६.५; १४७.२; ४; १५३.२; १५७.५; १५९.२; १६०.३; १६८.४; १७२.३; १९१.१

इत ८.८३.७

इतु १.५.१; ३३.१; ३.५३.११; ५.४५.६; १०.१४.९^{२}; ३०.२; ३; १०३.१३; १०६.१०; ११

इतऊती इतीतःऽऊती १०.३१.७

इतः १.६.१०; ९८.१; ११९.८; १३०.५;

७७.४; ८४.२; ४; ८५.४; ८६.१६; २६; ८७.२; ९१.२; ९३.३; ९६.९; २३; ९७.५; १०–१२; २४; ४०; ४१; ४५; ५६; ९८.२; ३; ९; १०१.२; ५; १०५.२; १०७.३; २६; १०९.९; १३; २२; ११०.१०; ११; १०.२६.३; १४४.१

इन्दुना १०.१४४.६

इन्दुऽभिः १.२३.१५; ३०.१; ५३.४^{२}; ६.१६.१६; ४२.२; ३; ८.६.२७; ७.१४; १२.१६–१८

इन्दुम् १.१३५.५; ३.३५.६; ५.१८.२; ६.४०.२; ८.२४.१३; ९.९.५; ११.६; २६.२; ३२.२; ३८.२; ४३.२; ४५.५; ५३.४; ६०.१; ६१.१३; ६२.२९; ६३.१७; ६५.१; ८; ८८.१; ९४.२; ९७.२२; ५७; १०९.१२; २०; १०.९९.८; ११५.३

इन्दून् ६.४७.१४

इन्दो इति ८.४८.२; ९.१.५; ४.१०; ६.२; ८.७; ११.९; २३.६; २४.५; २६.६; ३०.५; ३१.६; ३५.२; ४३.४; ४५.१; ६; ५०.५; ५२.३; ५५.२; ५९.४; ६३.२८; ३०; ६४.१२; १३; २५; ६५.१४; ६६.१४; ६७.५; ६९.१०; ८१.३; ८५.८; ८६.१८; २३; २४; ९०.६; ९३.४; ९७.२९; ९८.१; ४; १०४.५; १०५.५; १०६.७

इन्द्रो इति १.४३.८; ९१.१; १७६.१; ५; ४.२८.२; ३; ७.५४.२; ८.४८.४; ८; १३; १५; ९१.३; ९.२.१; २; ७; ९; १०; १२.९; १३.४; २९.६; ३१.२; ४०.३; ४; ६^{२}; ४१.४; ४४.१; ५१.३; ५२.४; ५; ५४.४; ५६.४; ५७.४; ६१.१; ३; २६; २८; २९; ६२.७; ९; २०; ६४.३; २२; २६; २७; ६५.५; १३; १७; ६६.१३; १६; ६७.६; ७०.१०; ७२.९; ७९.५; ८२.५; ८५.३; ८६.२२. २८; ३७; ३९; ४१; ४७; ४८; ९०.५^{२}; ९१.४; ९३.५; ९५.५; ९६.८; २१; ९७.१६; १७; १९; २१; २८; ३३; ४४; ५२; ५५; ९९.८; १००.२; १०५.४; ६; १०६.४; १०७.१९; ११२.१–३; ११३.१–११; ११४.१–४; १०.२५.९

इन्दोः ८.९२.४; ९.११४.१

इन्द्र १.३.४–६; ५.६; ७.४; ८.३; ४; ९.१; ६; ८; १०.४; ७; ९; १५.१; १६.१; ४०.१; ५१.१२; ५२.८; ६१.१६; ८०.३; ७; १४; ८४.१९; १०४.७; १२९.३; १३२.४; १४२.१३; १६५.५; ७; १७०.५; २.१३.१३; १४.१२; १६.६; १८.६; २१.६; ३.३०.१; १५; ३१.२०; ३२.१; ३४.२; ३५.१; १०; ३६.२; ३; ९; १०; ३७.१–३; ६–९; ११; ३९.१; ४०.१–४; ६; ९; ४१.८; ४२.५; ४३.२; ३; ७; ४४.२; ४५.४; ४६.१; ४७.३; ५१.७; ५२.१; ४; ५३.२; ५; २१; ६०.५–७; ४.२९.१; ३०.८; ३१.१२; ३२.७; ९; १२; १३; ३७.८; ४१.११; ५.२९.१५; ३०.३; ३१.५; १०; ३५.१; ३८.५; ३९.२; ४३.५; ४६.२; ६.१९.७; ९; २५.३; ५; ७^{२}; ८; ९; २७.३; ३०.४; ५; ३५.२; ३७.१; ४०.१; ३; ४; ४१.१; ४४.१०; १८; २०; ४५.१०; २५; ४६.५; ९; ११; ४७.७; १०; ६०.३; ७.२२.९; २४.५; ३२.२४; २६; ३६.४; १०४.२४; ८.१.१३; २.३; ११; १६; २९; ३.७; १२; ४.२^{२}; ६.२६; ४१; १२.५; १३.१२; २६; १४.४; ११; १४; १५.३; १७.१; ९; २१.१६; २४.४; ९; १७; ३२.१९; ३३.२; ३६.७; ३७.१–७; ४५.१३; ४६.१९; ४९.५; ९; १०; ५२.२; ५३.५; ६१.४; ५; १६; १७; ६२.४; ६३.५; ६४.३; ६५.३; ५; ७; ६६.८; ११; १३; ६८.१; १०; ७६.११; ७८.१; ८०.४; ७; ८१.६; ८; ८२.६; ९०.३; ९२.१६; ९५.१–५; ८; ९; ९७.६; ९८.५; ६; ९.१६.५; १०.२४.१; ३; ६०.५; ६४.१२; ९८.४; १००.१; १०४.३; ६; ९; ११२.१; ११६.२; १२८.८; १३१.५; १३४.३; ४; १६०.१; २; १७१.१; १८०.१; ३

इन्द्र **१**.४.९; ५.७; १०; ६.५; ८.१; ९; ९.४; ५; ७; १०.३; ११; ११.२; ७; १५.५; १६.४; ६; २८.१–४; २९.१–४; ५^{२}; ६; ७; ३२.४; १२; १४; ३३.३–५; ७; ९^{२}; १४; ५१.४; १३; १५; ५२.६; ७; १०; ११; १५; ५३.२; ३; ५; ७; १०; ११; ५४.८; ११; ५५.३; ७; ८; ५६.५; ६; ५७.४–६; ६२.४; ५; १२; १३; ६३.१–९; ८०.४; ८; ११; १३; ८१.३; ५; ९; ८२.१–३; ४^{२}; ५; ८३.१; ८४.१; ४; ६; १००.१७; १०१.९; १०; १०२.२–५; ८; १०; १०३.३; ७; ८; १०४.१; ६; ८; ११०.९; १२१.११–१४; १२९.१; २; ९–११; १३०.१; २; ४; ५; ७; १०; १३१.३^{२}; ४^{२}; ६; ७; १३३.५; ६; १३९.६; १६५.३; १६७.१; १६९.१–६; ८; १७०.२; १७१.६; १७३.१२; १३; १७४.१–१०; १७५.२; ६; १७६.६; १७७.२^{२}; ४; ५; १७८.१; ५; **२**.११.१–४; ६; ७; ११–१८; २१; १२.१५; १३.११; १५.१०; १६.३; ४; ९; १७.८^{४}; ९; १८.४; ५; ७; ९; १९.७–९; २०.१; २; ९; २२.४; २७.१४; ३०.४; ५; ३६.१; **३**.३०.५–७; ८^{२}; ९; १०; १७–१९; ३१.१७; ३२.२; ३; ५; ६; ९; १०; १२; १६; ३५.४; ६–८; ९^{२}; ३६.३; १०; ३७.१०; ३९.७; ४०.५; ४१.१; ४; ७; ९; ४२.१; २; ७–९; ४३.६; ४४.१; ४५.१; ५; ४६.५; ४७.१; २; ४; ५१.६; ८; १२; ५२.२; ५; ८; ५३.६; १८; २२; २४; ५५.२२; **४**.१६.१९; २१; १७.१; ६; ७; १८^{२}; २१; १९.१–३; ५; ६; ११; २०.३; ४; १०; ११; २१.९; ११; २२.५; ७; १०; ११; २३.११; २४.११; २८.४; २९.५; ३०.१; ३–६; ९; १२; १४; १८; २२; २३; ३१.६; १३; १४; ३२.१; ४; ६; ८; ११; १४; १५; २०; ३४.७; ३५.७; ४२.७; ५०.११; **५**.२९.१; ९; १४; ३०.४; ८; ३१.२; ८; ३२.१; २; १२; ३३.२–७; ३५.२–५; ७; ८; ३६.४; ३८.१; २; ३९.१; ४०.१–३; ६; ४२.४; **६**.१७.१–५; ७; ८; ११; १२; १४^{३}; १८.३; ९–११; १५; १९.३; ८; १०; २०.१; २; ४; १०–१३; २१.४; ६; ८; १२; २२.४; ९; १०; २३.१^{२}; २^{२}; ६–८; २४.३; ४; ६; १०; २५.१; २; ९; २६.१; २; ४–८; २७.४; ६; २८.८; ३०.३; ३१.१–३; ३३.१–५; ३४.१; ३५.२–४; ३६.४; ३९.३; ४०.२; ३; ५; ४१.२; ४; ५; ४३.१–४; ४४.१–३; ११; १७; १८; ४५.१२; १३; १७; ३०; ४६.१; २; ७; १०; १३; ४७.६; ८; ९; १४; २०; २२; ३१; ६०.२^{२}; ३; **७**.१८.१; ३; १८; २०; १९.२; ६; १०; ११; २०.४; ७; ८; १०; २१.३; ५; ६; ८–१०; २२.१; २; ८; २३.२; ४; ५; २४.१; २; ४; ६; २५.१; २; ४; ६; २७.२; ५; २८.१–४; २९.१; ३; ४; ३०.१; ३; ४; ३१.३; ४; ७; ३२.११; १४; १६; १८; २२; २३; ३७.४–६; ९८.२–४; ६; ९९.६; १०४.८; १९; २२; **८**.१.३; ६; २३; २४; २८; २.१०; १५; ३.१; १०–१२; १४; १७–२०; ४.१; ४; ५; ९; ६.९; १२; १४; १६–२०; २२–२५; ३१; ३२; ३६; ३९; १२.१; १६; २५; २९; ३१; ३३; १३.४; ५; १३; २२; २७; ३१; १४.१; ३; ६; १०; १३; १५; १५.८; १०; १२; १६.१२; १७.२; ३; ७; ११; २१.२; ४; ५; ७; १२; १३; १५; २४.२५; ३२.३; ७; २०; २२; ३३.१३; ३४.१; ३६.१–६; ४०.९; ४५.१०; १६; १९; ३१–३३; ४१; ४६.१; ८; ४९.३; ६; ५०.७; ५१.१; ६; ७; ५२.१; ४; ८; ५३.१; ५४.१; २; ५; ८; ६१.३; ७; ९; १३; १४; ६२.३; ५; ७; ८; १०; ६३.११; ६४.१२; ६५.१; ४; ८; ६६.५; १२; ७०.५; ९; १०; १२; ७६.७–१०; ७७.७; ७८.४; १०; ८०.१–३; ८१.१; ८२.३; ५; ७; ८३.७; ८८.३; ५; ८९.२; ९०.३; ५; ६; ९१.५; ७;

९२.९; १०; १४; १७; २२–२४; २६;
२९; ३१–३३; ९३.४; ६; १०; २७–३०;
९५.२; ९६.४; ५; ७; ९; १६; १७;
९७.१–४; ७[२]; ८[२]; १४; १५[२]; ९८.२–४;
७; १०; ९९.१; २; ५; ६; १००.१; ६;
९.९.५; ७२.४; ५; ८५.२; ८६.१३;
८७.४; ८; ८८.१; ९७.४६; १०.१९.६;
२२.७; ९; ११–१३; १५; २३.६; ७;
२८.३; ७; २९.३–६; ३२.२; ३३.३;
३८.१–३; ५; ४२.३; ४; ७; ४७.१;
३–५; ८; ५०.३; ४; ५४.१; २; ५; ५७.१;
५९.१०; ६१.१५; २२; ६३.१४; ७३.३;
४; ८; ७४.४; ८५.२५; ४५; ८६.२; ४;
१५; १८; २२; ८९.८; ९; १२; १४;
१५; १७[२]; ९३.११; ९६.५; १२; १३;
१०२.३; १२; १०३.५; १०४.१; २; ४;
५; ८; १११.१०; ११२.२–४; ५[२]; ६–८;
११६.१; ३; ६–८; १३१.१; १३३.२–७;
१३४.१; १३८.१; १४८.१; २; ४; ५;
१५२.३–५; १५३.२–५; १६०.५; १६४.४;
१६७.१; १६९.३; १७१.३; ४; १७९.२;
३; १८०.२

इन्द्रऽइषितः १०.८.८

इन्द्रऽइषिताः ५.३१.५

इन्द्रऽइषिताम् २.११.८

इन्द्रः १.२.५; ६; ५.९; ७.२[२]; ३; ९; ८.५;
१०.२; ६; ११.४; १६.८; १७.५; १८.४;
५; २३.२४; ३०.१६; ३२.५; ९; १३;
१५; ३३.१०–१३; ४०.५; ५१.९; ११;
१४[२]; ५२.२; ५; ५४.१०; ५५.२;
६१.९; १०; १५; ८०.५; ६; १०;
८१.१; ६; ८३.६; ८४.७–९; १३; ८५.९;
८९.६; ९०.४; ९; १००.१–१५; १९;
१०१.२; ४; ५; १०२.६; ९; ११; १०७.२;
३; ११०.७; १२५.२; १२९.८; १३०.३;
४; ८; १३२.२; ३; १३३.७; १३५.४;
७[२]; १६१.६; १६२.१; १६३.२; ९;
१६४.१९; १६५.१०; १६६.१२; १७३.४;
६; ९; १०; १७७.१; १७८.२[२]; ३; ४;
१८६.६; २.१.३; ११.९; २०; १२.१–१४;
१४.२; ६; १५.१–९; १९.१–६; २०.३;
५–७; २१.४; ३०.३; ८; ३१.३; ३८.९;
४०.२; ४१.१०–१२; ३.४.६; २२.१;
२५.४; ३०.३; ११; १४; ३१.४; ११;
१५; ३३.६; ३४.१; ३–५; ७; ९; १०;
३६.५; ६; ८; ३९.४–६; ४३.४; ४४.३;
५; ४५.२; ४६.३; ४८.४; ५०.१; ५१.३;
५३.९; १७; ५४.१५; ५७.१; २;
४.१६.५; १७.५; १०–१२; १९; २०;
१८.३; ८; ११; १९.४; ७; ८; २०.१;
२; ६; २१.१; ३; १०; २२.१; २३.३;
२४.२; ७; २५.३; ६; ७; २७.५;
२८.१–३; ५; २९.३; ३०.१६; १७; २०;
२१; ३४.१; ३७.६; ४२.३; ५; ४३.३;
४७.२; ३; ४९.३; ५०.१०; ५४.६;
५५.१०; ५७.७; ५८.४; ५.२.८; ३.१;
२९.३[२]; ४; ७; ३०.६; ९–११; ३१.१;
३; १२; ३२.३; ६; ७; ३४.६; ८; ३६.१;
३७.४; ४०.४; ४१.२; ४२.५; ४९.३;
५१.६; १४; ६.१७.९; १८.१; ८; १९.१;
२०.३; ५; ८; २१.४; २२.७; २३.३;
९; १०[२]; २४.५; २७.१; २; ५; २८.२;
५[२]; २९.६; ३०.१; ३२.५; ३४.२; ५;
३७.२; ४; ५[३]; ३९.२; ४४.१२; १४;
१५; ४५.१; २; ४७.२; ११–१३;
१६–१८; ५१.११; ५२.६; ११; ५६.२;
५७.४; ६९.८; ७.१८.४; ५; ९; ११;
१३; १६; १७; २०.१–४; २१.१; ४;
७; २३.३; २६.३; ४; २७.३; ४; ३२.१०;
१२; ३३.२; ३; ५; ३४.४; २५; ३५.६;
४०.२; ४७.२; ४; ४८.३; ४९.१; ५१.३;
५६.२५; ८२.१०; ८३.१०; ८४.२; ९३.८;
९७.१०; ९८.१; ७; १०४.१६; २१; २५;
८.२.४[२]; ३२; ३४; ३.६[२]; ८; २१;
४.११; ६.१; ५; ११; १२.९; १२; १३.१;
१४.७; १६.५; ६; ७[३]; ११; १७.८; १४;
२१.१७; २५.१४; २७.६; ८; ३२.१२;
१८; २८; ३३.५; ९; १७; ३४.१६; ४०.५;

४५.१–३; ७; ९; २६; ५२.१०; ६१.१; १५; ६२.९; ६३.३; ४; ६६.३; ४; १०; ६७.८; ६९.७; ११; १४; ७०.७; ७२.८; ७६.२; ३; ७७.४–६; १०; ७८.५; ८९.२; ९०.१; ९२.२–४; ९३.३; ८; ३२; ३४; ९४.६; ९६.१२; १३; १५; २०; २१; १००.३; ७; ९.१.१०; ५.७; ९; ११; ६.२; १९.२; २३.७; ६३.९; ८८.४; ९५.५; १०६.३; १०८.१४; १०९.२; ११३.१; १०.८.९; १९.२; २२.१; २; २३.२–४; २९.१; ८; ३०.४; ३२.१; ६; ३६.५; ३७.६; ४२.११; ४३.३; ११; ४४.१; ११; ४८.२; ५; ४९.११; ५०.२; ६५.१; ६६.३; ६७.६; १२; ७३.५; ६; १०; ७४.६; ८३.२; ८६.१–१२; १३[२]; १४–२३; ८९.२; ३; ७; १०[८]; ११; ९०.१३; ९२.४; ६; ९३.९; ९४.९; १००.४; ५; ११; १०२.१; ७; १०३.१; ३; ७; ८; ११; १३; १०४.१०; १०५.३; ४[२]; १०८.३; १०; १११.३–५; ११३.२; ५; ७; ९; ११६.४; १३१.६; ७; १३८.३; १३९.३; ४; ६; १४४.६; १५२.२; १५७.१–३; १५९.४; १६०.३; १६१.३; १७३.३; ५; ६; १७४.१; ४

इन्द्रःऽइव १०.८४.५; १६६.२; १७३.२

इन्द्रऽगोपाः ८.४६.३२

इन्द्रऽजूतः ३.३३.११

इन्द्रऽजूतम् १.११८.९

इन्द्रऽज्येष्ठाः १.२३.८; २.४१.१५; ६.५१.१५; ८.६३.१२; ८३.९

इन्द्रऽज्येष्ठान् ४.५४.५; १०.७०.४

इन्द्रऽज्येष्ठासः ७.११.५; १०.६६.१

इन्द्रऽतमा १.१८२.२; ७.७९.३

इन्द्रत्वाऽऊताः १.१३२.१; ८.१९.१६

इन्द्रऽद्विष्टाम् ९.७३.५

इन्द्रनासत्या ८.२६.८

इन्द्रऽपत्नी १०.८६.९; १०

इन्द्रऽपातमः ९.९९.३

इन्द्रऽपानः ९.९६.३; १३

इन्द्रऽपानम् ६.४४.१६; ७.४७.१; १०.३०.९

इन्द्रऽपानाः १.५४.९

इन्द्रऽपीतम् ९.८.९

इन्द्रऽप्रसूताः १०.६६.२

इन्द्रम् १.४.४; ५.१; २; ६.१०; ७.१[३]; ५[२]; १०; ९.९; ११.१; ८; १६.२; ३[३]; २३.७; ३०.१; ७; ३२.७; ३३.१; २; ८; ५१.१; २; ५२.१; ३; ४; ९; ५४.२; ५५.१; ५६.४; ८०.१२; १५; ८४.२; १७; ८७.५; १०१.६; ७; १०२.१; १०४.२; १०६.१; ६; १११.४; १२९.४; ७; १३१.१; २[२]; १३६.६; १४२.४; १६४.४६; १७३.५; ७; ११; १७६.१; २.३.३; ११.११; १४.३; ४; १०; ११; १६.१; ७; २०.४; २२.१–३; ३.१२.३; ३०.२२; ३१.२२; ३२.७; १३–१५; १७; ३४.८; ११; ३५.२; ११; ३६.११; ३७.५; ३८.१०; ३९.१; ९; ४०.७; ४१.५; ४२.३; ४; ४३.८; ४६.४; ४७.५; ४८.५; ४९.१; ५; ५०.३; ५१.१; २; ९; ५३.१२; ४.२.१७; १६.१५; १६; १७.८; १६; १८.५; १०; २०.५; २१.४; ५; २४.१; १०; २५.८[५]; ३२.१७; ३५.१; ३९.४; ४१.८; ९; ४२.८; ५.५.३; २९.२; ६; १२; ३०.१; २; १३; ३१.४; ३२.११; ३९.४; ६.४.७; १७.८; १३; १९.२; ४; ११; २०.९; २१.२; ९; २२.१; ३; ५; २३.९; २४.७; २८.५; २९.१; ४; ३४.३; ३६.३; ३७.३; ३८.२; ३; ४[२]; ४२.२; ४४.४; ४६.३; ४७.१; ११[४]; ४८.१४; ५०.६; ५७.६; ६०.१२; ६१.५; ७.१०.४; १८.१९; २४; २१.७; २३.१; ६; २४.२; २६.१; २; ५; २७.१; २८.५; २९.५; ३०.५; ३१.१२; ३२.२०; ३३.२; ३७.७; ३९.५; ४१.१; ४४.१; ८३.६; ८४.५; ८५.३; ५; ९३.७; ९७.३; १०४.२०; ८.१.१; १०; १५; २.३७; ३.५[४]; १६; ४.१४; ६.३; १५; ३४; ३५; ४४[२]; ७.२४; ३१; १२.२०; २२[२]; १३.३; १६[२]; १७; १४.५; १२; १५.१; १३;

इन्द्राग्निऽभ्याम् १.१०९.३; ५.८६.६; ८.४०.५; १२; १०.११६.९; १२८.९

इन्द्राग्नी ७.९४.८

इन्द्राग्नी इति १.२१.५; ६; १०९.१; २; ४; ३. १२.१; २; ५–९; ५.२७.६; ८६.१; ६. ५९.१; २; ५–१०; ६०.७–९; १५; ७.९३.१; ४; ९४.१–३; ७; ९; ८.३८.१–९; ४०.१

इन्द्राग्नी इति १.२१.१–४; १३९.९; ३.१२.४; ५.४६.३; ८६.२; ४; ६.६०.४; ५; १४; ७.३५.१; ९३.३; ९४.१०; ८.४०.३; ४; ७; १०.६५.२; १२५.१; १६१.४

इन्द्राग्नी इति १.१०८.१–५; ७–१३; १०९.५–८; ६.५९.४; ६०.१३; ७.९३.६; १०.१६१.१

इन्द्राग्न्योः ८.३८.१०; ४०.८

इन्द्राणि १०.८६.१२

इन्द्राणी ५.४६.८

इन्द्राणीम् १.२२.१२; २.३२.८; १०.८६.११

इन्द्रात् १.३३.६; १७१.४; २.१६.२; ५.३०.५; ८.१५.११; ७६.१२; ९.६९.६; १०.९२.८

इन्द्रापर्वता ३.५३.१

इन्द्रापर्वता १.१२२.३; १३२.६

इन्द्रापूषणा ७.३५.१

इन्द्रापूष्णोः १.१६२.२

इन्द्राबृहस्पती इति ४.४९.५

इन्द्राबृहस्पती इति ४.४९.१–४; ६

इन्द्राब्रह्मणस्पती इति २.२४.१२

इन्द्रामरुतः २.२९.३

इन्द्राय १.४.१०; ५.४; ८.१०; ९.२; १०; १०.५; १३.१२; २०.२; २८.६; ८; ५३.१; ५५.५; ६१.१; २; ४; ५; ८; ८०.९; ८४.५; १३१.१[२]; १४२.५; १२; १५६.५; १६५.११; २.१४.१; ५; ८; ९; २०.८; २१.१; २; ३०.१; ३.३०.२०; ३१.१३; ३६.२; ७; ५०.४; ५१.५; ५३.३[२]; १३; ४.१६.२०; २४.६; ७; २५.४; ३३.१०; ५.५.११; २९.८; ३२.१०; ३३.१; ३७.१; ५; ३९.५; ५१.४; ७; ६.२३.५[२]; २८.१; ३४.५; ४१.३; ४४.६; १३; ७.३१.१; ११; ३२.४; ८; ८५.१; ९२.२; ९७.१; ९; ८.१.१९; २.२३; ४.१३; १२.१४; २४.१; १३; ३३.४; ४५.२१; ५२.९; ६९.६; ९; १०; ८९.१; ३; ९१.१; ३; ९२.१९; ९६.१; १०; ९८.१; १००.३; ९.१.१; ९; ४.४; ६.७; ११.८; १२.१; १३.८; १६.३; २१.१; २३.६; २४.३; २६.६; २७.२; ३०.५; ६; ३२.२; ३३.३; ३४.२; ४; ३७.६; ३८.२; ३९.५; ४३.२; ४५.१; २; ४६.६; ५०.५; ५१.१; २; ५३.४; ५६.४; ६१.१२; ६२.८; १४; १५; २९; ६३.२; ३; १०; १५; १७; १९; ६४.१२; २२; ६५.८; २०; ६६.७; ६७.२; ८; १६; ६९.१०; ७४.९; ७६.५; ७८.२; ८०.२; ८४.१; ८५.१; ४; ६; ८६.३५; ८९.७; ९६.८; ९; ९७.१४; ३२; ४४; ९८.१०; ९९.८; १००.५; ६; १०१.४; ५; १०६.२; ४; ५; १०७.१७; १०८.१; १५; १०९.१; १९; २०; २२; ११०.११; ११२.१–४; ११३.१–११; ११४.१–४; १०.२७.२२; २९.७; ३०.७; १३; १५; ५४.६; ६७.१; ७६.८; ८९.४; ९४.१; ९६.२; ६; ९८.११; १२०.८; १३३.१

इन्द्रावरुणयोः १.१७.१

इन्द्रावरुणा ६.६८.३; ७.३५.१; ८२;२

इन्द्रावरुणा १.१७.३; ७–९; ६.६८.१०; ११; ७.८२.१; ३–५; ७; ८३.३; ४; ८.५९.१; २; ६; ७

इन्द्रावरुणा ३.६२.१–३; ४.४१.१; ४२.९; १०; ६.६८.४; ७; ८; ७.८२.८; ९; ८३.१. २; ७; ९; ८४.१; ४; ८.५९.३–५

इन्द्रावरुणौ ६.६८.१; ७.८३.५

इन्द्रावरुणौ ६.६८.६; ७.८३. ८; ८५.२

इन्द्राविष्णू इति ४.२.४; ६.६९.२; ८.१०.२; १०.६६.४

इन्द्राविष्णू इति १.१५५.२; ४.५५.४; ६.६९.१; ३–७; ७.९९.५

इन्द्रासोमा ७.३५.१

इन्द्रासोमा २.३०.६; ६.७२.१; २; ४; ५; ७.१०४.१–७

इन्द्रासोमौ ६.७२.३

इन्द्रियः ८.३.२०; ९.४७.३; ८६.१०

इन्द्रियम् १.५५.४; ५७.३; ८४.१; ८५.२; १०३.१; १११.२; २.१६.३; ४.२४.५; ३०.२३; ६.२७.३; ४; ८.३.१३; १२.८; १५.७; ५२.७; ५९.५; ९३.२७; ९.२३.५; ३०.२; ४८.५; ९२.१; १०.३६.८; ६५.१०; ११३.१; ३; १२४.८

इन्द्रियाः ९.१०७.२५

इन्द्रियाणि ३.३७.९; ५.३१.३

इन्द्रियाय १.१०४.६; ६.२५.८; ९.७०.५; ८६.३; ८९.६; १०.११६.१

इन्द्रियेण १.१६५.८

इन्द्रियेभिः ४.३५.९

इन्द्रियैः १.१०७.२

इन्द्रे १.४.५; ३०.१३; ८०.१६; १३२.५; १६६.११; २.१४.८; २१.५; ३.५४.१७; ४.२५.५; ६.२४;१; ३४.१; ४; ३८.३; ७.२०.६; २५.५; ३२.२; १३; ३३.४; ४२.५; ९४.४; ८.३.६[२]; १३.१६; ५४.७; ६३.६; ७; ७२.१५; ९.११.६; ९६.१२; ९७.१०; ४१; १०.४२.६; ९२.७; ९६.३

इन्द्रेण १.६.७; १४.१०; २०.५; २३.९; ५३.४; ८४.१०; १०१.११; २.१८.८; २३.१८; ३.४.११; ६०.४; ४.३४.११; ५.११.२; ५१.१०; ६.४४.२२; ४७.२९; ७.२.११; १८.१५; ३२.६; ४८.२; ८.९.१२; १४.९; ३५.१; ४०.६; ७६.४; ९१.४; ९६.६; ९.११.९; ६१.८; ८७.९; १०३.५; १०.१५.१०; ६२.७; १०३.२; १०८.४

इन्द्रेषिते इतीन्द्रऽइषिते ३.३३.२

इन्द्रोते ८.६८.१५; १७

इन्धताम् १.१७०.४

इन्धते १.४४.७; २.३५.११; ६.१६.४८; १०.६९.१

इन्धते ४.८.५; ५.७.२; ८.४३.२७; ४५.१

इन्धते १.२२.२१; ३६.४; ७; ४४.८; ३.१०.१; ९;१३.५; २७.११; ६.२.३; ७.१६.३; ८.६०.१५

इन्धन्वऽभिः २.३४.५

इन्धानः १.१४३.७; २.२५.१; ८.१९.३१; १०२.२२; १०.४५.१

इन्धानाः १०.३.४; १२८.१

इन्धानासः ८.२३.११

इन्धे ७.१.१६; ८.१

इन्ध्वम् १०.१०१.१

इन्व ५.४.७

इन्वतः १.१०.८; १४१.४

इन्वतम् १.१६०.५; ७.६४.२

इन्वताम् ६.७०.६

इन्वति १.५४.७; ५५.४; १२८.५; ६.५.१; ९.२०.२

इन्वति १.१८.७; २.५.२; ४.५३.५; ७.८४.२; ८.१५.११; ५२.६

इन्वतु १.१६२.६; १२; ४.५३.७; १०.१८८.३

इन्वथः १.११९.७

इन्वन् ५.३०.७; ९.९७.१०

इन्वन्तः ३.४.५

इन्वसि ५.२८.२; ८.१३.३२

इन्वसि १.९४.१०; १४१.१०; १७६.१; ९.१०७.२१

इन्वात् १०.१६.१०

इन्विरे ५.६.६

इभः ९.५७.३

इभम् ६.२०.८

इभाय १.८४.१७

इभेन ४.४.१

इभ्यान् १.६५.४

इमः ८.९६.८

इमऽथाः ५.४४.१

इमम् १.५.९; १०.९; १२.१२; १३.८; १४.११; १६.५, ९; २२.१३; २५.१९; २६.१; १०; २७.४; ३१.१६; ८४.४; ९१.१०; ९३.१; ९४.१; ९५.२; ४; १०२.९; ११८.३; १३५.५; १३९.११;

१४२.८; १६४.३; १७९.५; १८८.७; २.४.२; २७.२; ३५.२; ४१.१३; २०; ३.१.२२; ४.२; ५; १२.२; १६.२; १७.२; २१.१; ३०.२०; ३२.१; ३४.५; ३५.२; ६; ८; ४२.७; ५०.४; ५४.१; १०; ५८.३; ४.१४.१; २०.२; ३; २४.१०; ३४.१; ६; ४४.४; ५८.१०; ५.२.१२; ४.५; ५.२; ७; ४०.७; ६५.६; ७१.१; ७४.१०; ६.९.४; १०.६; १५.१; १७; ३९.३; ५२.७; १२; १३; ५६.५; ६८.१०; ७.११.५; १८.२५; ४२.५; ५१.१; ८.२.११; ६.३६; ७.९^{२}; ८.१२; १७; १२.४; ५; १७.१; २३.१९; ३२.२१; ४३.१६; २२; २४; ४५.१८; ४६.२७; ५८.१; ६६.८; ७३.५; १०; ७६.१; ८५.२^{२}; ८६.३; ९१.२; ९.१.९; ५.८; १०.१४.४; १५.६; १६.८; १०; १४; १७.११; १८.४; १३; २४.१; २६.९; ४४.९; ४६.२; ३; ७५.५; ८६.४; ९२.२; ९७.२; १०२.९; १०३.६; १२३.१; १२४.१; १२८.७; १३०.६; १५०.२; १६१.३; ४; १६७.२; ४; १७३.३

इमसि १.१.७; १६१.३; ८.९१.३

इमस्थ ८.१३.२१

इमा १.१०३.४; १२२.६; १६३.५^{२}; १६४.२; ६; १६५.४; १४; १७७.४; २.१२.४; २४.१०; ४१.१८; ३.१.२०; १४.७; २१.१; ३०.२; ४१.३; ५५.१९; ५८.४; ४.३८.१०; ५.७३.१०; ८२.९; ६.१६.५; ४०.४; ५२.११; ७.२२.३; ४; ७; २९.२; ३; ५९.५; ६२.५; ७०.६; ७; ७१.६; ९५.५; १०४.६; ८.८.१७; ९.१४; ३८.५; ४४.८; ५१.४; ९०.३; ९६.६; ९.६२.२७; ८६.३०; ३७; ९६.७; ११०.९; १०.१५.४; ३२.८; ६६.१२; ८१.१; ५; ८२.७; ११२.७; ११६.८; १२०.८; १४८.४; १५७.१; १७०.४

इमाः १.१०.१२; १६.२; २४.६; २६.५; ३६.११; ४५.५; ८०.४; ९१.२२; ९६.२; ११४.१; १२७.२; १३१.४^{२}; १९०.४; २.६.१; ११.१; २७.१; ३९.७; ३.३४.५; ३८.२; ५; ३९.७; ४०.८; ४३.२; ५७.४; ६२.१; ४.३.२; ३४.५; ४१.९; ६.२१.१; २८.५; ४५.२५; २८; ४७.३१; ७.१८.३; ४५.४; ४६.१; ६१.५; ७४.१; ८.३.३; ६.७; १९; ७.१९; १३.२९; ५७.४; ९६.७; ९.३४.६; ८६.२८; २९; १०.७.२; १७.५; १८.७; ३०.१४; ४३.८; ५२.५; ९१.१२; ९७.११; १०८.५; १२१.४; १५९.६

इमान् ४.३.१५; ५.५०.२; ५३.३; ९.९७.१७; १०.६०.९; १५५.५; १६६.३

इमानि १.९३.११; १२५.६; ३.६०.६; ७.६१.६; ८२.५; ८.५९.१; ९१.५; १०.८२.४

इमाम् १.३१.१६; ४०.६; ८८.४; १०२.१; १२९.१; १३०.६; २.६.१^{२}; २४.१; ३.१८.३; ३२.८; ३४.८; ३६.१; ५४.१७; ५५.२१; ४.५.२; ४३.१; ५७.५^{२}; ५.५४.१; ८५.५; ६; ६.४७.२८; ७.१५.६; २२.३; ३६.२; ४१.३; ७०.७; ७१.६; ७३.३; ९३.६; ८.५.३०; ६.३२; ४३; ७.९; ८.६; १२.३१; ३८.६; ४२.३; ९१.६; ९.९६.३; ९७.१३; १०.६७.१; ७०.१; ८५.३३; ४१; ४५; ८८.३; ९; ८९.१६; ९१.१३; ११९.८; ९; १२१.१; १४५.१

इमे १.२.१; ४; ३.४; ५.५; १६.६; २३.१; ५७.४; १०२.५; १०९.७; १३५.६; ९; १३७.१^{३}; २; १३९.६; १६४.१२; ३९; १८३.४; ३.३६.३; ४०.४; ४२.५; ४३.१; ५३.७; २४; ५८.५; ४.१४.४; ५.३.१२; ७६.४; ७९.५; ६.१७.४; २१.१०; २३.८^{२}; ५४.२; ६०.७; ७.१.१०; ३२.२; ४; ५६.१९^{३}; २०; ५७.३; ६०.५^{२}; ६; ७; ९७.५; ८.१.३; २.१०; ३.१८; ५.३९; ९.८; १४^{२}; २१.३; ४०.७; ४३.१; २९; ४५.१६; ४६.३२; ४७.४; ४८.५; ७४.६;

इरज्यति ८.४१.९
इरज्यथः १.१५१.६
इरज्यन् १०.१४०.४
इरज्यन्त ७.२३.२
इरज्यन्तम् ८.४६.१६
इरज्यन्ता ६.६०.१
इरज्यवः १०.९३.३
इरज्यसि १०.७५.२
इरज्यसि १.५५.३; ८.३९.१०
इरधन्त १.१२९.२
इरध्यै १.१३४.२
इरस्यः ७.४०.६
इरस्यति १०.१७४.२
इरस्यसि १०.८६.३
इरस्या ५.४०.७
इरा ५.८३.४
इराऽवत् ७.४०.५; ६७.१०; ६९.८
इरावती इतीराऽवती ७.९९.३
इराऽवतीः ५.६९.२
इराऽवतीम् ५.६३.६
इरिणम् १.१८६.९; ८.४.३; ८७.४
इरिणे ८.८७.१; १०.३४.१; ९
इरी ५.८७.३
इर्यः ७.१३.३; ८.४१.४
इर्यम् ५.५८.४; ६.५४.८
इर्याऽइव १०.१०६.४
इलयत १.१९१.६
इलीबिशस्य १.३३.१२
इषः १.३.१; ९.८; २७.७; ३४.३; ३६.११; ४८.१५; ८६.५; १२१.१५; १३०.३[२]; १६५.१२; १६७.१; १८१.६; १८६.३; १८८.२; २.६.५; ३.१.२२; २.१०; ३.७; १२.५; २२.४; ३०.१८; ५३.१; ५४.३२; ५८.८; ५९.९; ६२.१४; ५.४.२; ६.८; ७९.८; ६.१.१२; १७.३; ३५.४; ३९.१; ५; ५२.१६; ६०.१२; ७.५९.२; ९९.६; ८.५.९; १०; २०; २१; ३१; ७.१९; २२.९; २३.२९; २५.६; २७.१६; ९.३.१०; १३.४; १५.७; २३.३; ३९.२; ४०.४; ४२.६; ४९.१; ६१.३; ६२.२४; ६६.४; १८; ७२.९; ७४.२; ८७.९; ९७.२५; १०८.२; ९; १०.२.६; ५.४; १७.८; १३४.३; १४०.३; १४३.६
इषः १.१६३.७; १७८.४; ३.३०.११; ४.३९.४; ४०.२; ५५.४; ५.७.३; १०; ६८.५; ६.२४.९; ६३.७; ८.२३.३; २५.५; २६.३; १७; ९.१४.७; ७९.१; ९८.५
इषःऽस्तुतः ५.५०.५
इषणः ४.१६.९; २२.१०
इषणत् ४.१७.१४
इषणन्त १.१३४.५; ४.२३.९
इषणयन्त १०.६७.८
इषणि २.२.९
इषण्य ३.५०.३
इषण्यत ५.५२.१४
इषण्यति ८.२२.४
इषण्यन् ३.६१.७; ९.९६.८
इषण्यन्ति ५.६.६
इषण्यया ८.६०.१८
इषण्यसि १०.९९.१
इषध्यै ७.४३.१
इषन्त १.१३४.५
इषम् १.१२.११; ४६.६; ४७.८; ६३.८; ९२.३; ९६.८; १११.२; ११७.२१; १४०.१३; १६८.२; २.१९.८; २२.४; ३४.७; ८; ४.१६.२१; १७.२१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११; ३२.७; ४०.२; ५३.७; ५.६.१–१०; ७.१; ३८.२; ४१.१८; ७०.२; ७६.४; ८६.६; ६.१४.१; ४७.९; ४८.१३; ५०.१२; ६२.४; ६३.८; ६५.३; ७.५.८; ७.७; ८.७; २४.६; २५.६; ३६.२; ४२.६; ४८.४; ६६.९; ७०.३; ७७.५; ९६.६; ८.१.१०; ६.२३; ७.१; ३; ८.१५; १३.२५; ३५.४–६; ४३.१५; ५४.७; ६९.१; ७०.७; ७२.१६; ९३.२८; १००.११; ९.८.९; २०.४; ४१.४; ६१.६; १५; ६३.२; ६५.१३; २१; ६६.१९; ८६.१८; ३५;

९४.५; १०१.११; १०.११.७; २०.१०; ४०.४; ४८.८; ६१.४; ९९.१२; १२२.६; १४०.५; १६५.५

इषम् १.१६५.१५; १६६.१५; १६७.११; १६८.१०; १६९.८; १७१.६; १७३.१३; १७४.१०[२]; १७५.६; १७६.६; १७७.५; १७८.५; १८०.१०; १८१.९; १८२.८; १८३.६; १८४.६; १८५.११; १८६.११; १८९.८; १९०.८

इषऽयते ६.१६.२५

इषयध्यै १.१८३.३; ६.४९.५; ६४.४

इषयन् ६.१.२; ९.८४.३; १०.९१.१

इषयन्त १.७७.४; २.२.११; ७.८७.३

इषयन्तः ५.४९.४; ६.१६.२७

इषयन्तम् ६.१.८; १८.५

इषयन्ता ८.५.५

इषयन्ती इति ४.५६.४

इषयन्तीः ३.३३.१२

इषयन्तौ ८.२६.३

इषऽयुः १.१२०.५

इषये ६.५२.१५

इषयेम १.१८५.९

इषवः २.२४.८; ६.७५.११; १०.१०३.११

इषऽवान् १.१२९.६

इषा १.३०.१७; ५३.४; ५; ८८.१; ११२.१८; ११७.१; १०; १२९.७; १६५.१५; १६६.१५; १६७.११; १६८.१०; १८५.९; ६.२०.६; ६८.५; ६९.१; ७.६४.३; ६८.९; ८.५.३४; ३६; २०.२; २२.१२; ८२.३; ९२.१०; १०.८२.२; १०६.५

इषाम् १.१६८.५; १८१.१; ३.२३.२; ६.४७.९; ६०.१३; ७.६९.१; ८.४६.२; ७१.१३

इषितः १.३.५; ३.३.२; ४.३; ३२.४; १६; ३३.११; ६०.५; ६.५.६; ११.१; ७.३९.१; ९.३७.६; ७७.२; १०.११.४; ८८.३; ९१.७; ९८.१०; ११०.३; ९; १६५.१; २

इषितत्वता १०.१३२.२

इषितम् २.३८.५; ८.१.२१

इषिता ३.१२.१; ७.३३.१३; १०.१०८.२

इषिताः १.१८२.६; ३.४२.३; ६२.१२

इषितासः ६.४९.१०

इषिधः ६.६३.७

इषिर १.१२९.१

इषिरः ३.५.४; ५.४१.१२; ६.२९.३; ७.३५.४; ९७.७

इषिरम् ३.२.१४; ५.३७.२; ६८.४; ९.९६.१५.

इषिरस्य ८.९८.९

इषिरा ५.७५.५

इषिराः २.२९.१

इषिराः ३.५६.८; १०.६८.३; ९४.५

इषिराम् १.१६८.९; ३.३०.९; ५.३७.३; ९.८४.४; १०.९८.३; १५७.५

इषिराय १.१२८.५; ८.४६.२९

इषिरासः ९.७३.७

इषिरेण ८.४८.७

इषिरेभिः ३.६०.७; १०.७३.५

इषिरैः ६.६२.३

इषुः ८.७७.७; ९.६९.१; १०.९५.३

इषुकृताऽइव १.१८४.३

इषुऽधिः ६.७५.५

इषुऽधीन् १.३३.३

इषुऽधेः १०.९५.३

इषुध्यति ५.५०.१

इषुध्यते १.१२८.६

इषुध्यवः ५.४१.६

इषुध्यसि ८.६९.२

इषुध्याऽइव १.१२२.१

इषुऽबलाः ६.७५.९

इषुम् १.३९.१०; ६४.१०

इषुऽमन्तः ५.५७.२

इषुऽमान् २.४२.२

इषुऽयते १.१२८.४

इषुऽहस्तेन १०.१०३.२

इषुऽहस्तैः १०.१०३.३

इषूः १०.८७.४

इषे १.५४.११; ७१.८; १२०.९; १२१.१४; १८०.२; ६.१३.२; १७.१४; ६८.१; ७.२०.१०; २१.१०; ८.२०.८; ९३.३४; ९.६४.१३; ६५.३; १०.४८.९; ५०.३

इषे ४.२३.६; ६.२२.५; ८.४६.१७; १०.२०.७

इषेम ८.४४.२७

इष्करम् १०.४८.८

इष्कर्तं ८.२०.२६

इष्कर्ता ८.१.१२

इष्कर्तारम् ८.९९.८; १०.१४०.५

इष्कृणुध्वम् १०.५३.७; १०१.२

इष्कृतऽआहावम् १०.१०१.६

इष्कृतासः ७.७६.२

इष्कृतिः १०.९७.९

इष्टऽअश्वः १.१२२.१३

इष्टनिः १.१२७.६[2]

इष्टम् १.१६२.१५

इष्टयः १.१४५.१; ६.७४.१

इष्टऽयामा ९.८८.३

इष्टये १.३०.१२; ५७.२; ११२.१; २; ११३.५; ६; १२९.४; ५.४४.४; ७२.३; ७४.३; ७८.३; ६.७०.४; ७.९२.३; ८.३८.४; ९.९७.४२; १०.३६.६; ४९.९; ७०.११; ९२.१३; ११५.४

इष्टऽरश्मिः १.१२२.१३

इष्टऽव्रताः ३.५९.९

इष्टस्य १०.११.२

इष्टाः ८.९३.२३

इष्टानि १.१६४.१५; १०.८२.२

इष्टापूर्तेन १०.१४.८

इष्टिः ४.४.७

इष्टिऽभिः २.१.९; १८.१

इष्टिम् १.१६६.१४

इष्टिषु १०.१४७.२

इष्टीः ७.९३.८

इष्टे १.१४३.८; ६.८.७

इष्टेः १.१२५.३

इष्टैः ४.५५.६

इष्टौ १.६२.३; १४८.३; २.२८.७; ४.६.७; ६.११.३; १०.४४.९

इष्ट्या १०.१६९.२

इष्णत् १०.६१.५

इष्णन् १.१८१.६; २.२०.५; ४.१७.३; ९.१७.५

इष्णानः १.६१.१३

इष्णासि १.६३.२

इष्मिणः १.८७.६; ५.८७.५; ७.५६.११

इष्मिणम् ५.५२.१६

इष्यत १.१५.९

इष्यति १.३४.१०

इष्यति ९.१२.६; ३०.१; ३५.४; १०.११.६

इष्यते ९.६९.१

इष्यन् १.६१.१२; ९.९५.५

इष्यसि ९.६४.९; २५

इष्यामि ८.९६.१४

इष्ये ४.३३.१

इष्वाः १०.१८.१४

इष्वै ६.७५.१५

इह १.१.२; १२.३; १०; १३.३; १०; १४.९; १२; १५.४; १६.२; २१.१; ४; २२.१; ९; १०; १२; २४.११; २८.५; ३४.११; ३५.१; ६; ३६.२; १०; ३८.१५; ४२.७–९; ४४.७; ४५.१; ९; ७४.६; ७६.२; ४; ८९.७; ९२.१४; १८; ९४.१६. १०६.४; ११०.१; ११३.७; १२; १२१.८; १३४.१; १३५.५; ६; १४२.४; १६१.३; १६४.७; १८; ४९; १७७.४; १८१.२; १८३.६; १८४.६; १८५.११; १८६.६; १८८.६; १९१.७; २.३३.१५; ३५.१३; ३६.४; ३७.५; ४१.४; २१; ४२.२; ३.२.५; ३.५; ७.९; ८.१; ९.२; १२.३; १४.७; १९.५; २०.५; २५.१; २; ४; २८.४; २९.१६; ३०.९; ३२.१; ३५.३; ३७.११; ४०.९; ४१.८; ४३.४; ४७.५; ५०.२; ५१.७; ८; ५३.५; ५४.५; ५७.५; ५८.५; ६०.६; ७; ४.२.२; ४.९; ५.१४; ७.१; ८.२; १४.४; १६.१; २१.१; २; ३१.११; ३५.१; २;

३६.९[३]; ४६.५; ७[२]; ५६.१; ५.१.११; २.७; ५.३; ९; ४०.७; ५६.७; ६०.१; ७३.२; ७४.६; ७५.७; ७६.१; २; ७८.१; ६.९.२; १६.२४; १९.४; ११; २८.१; ४७.२; १९; ४९.१; ५४.९; ५८.१; ५९.३; ९; ७४.४; ७.१.८; ९; ११.१; ३; ५; १७.२; ३२.१; ३५.६; ४१.५; ४२.५; ४९.१–४; ५०.१; ५६.९; ५९.६; ८.२.२७; ५.३३; ८.४; ९; १३.२७; २२.३; २६.९; ३०.४; ३२.२९; ३४.२; ४; ११; ३५.३–६; ३९.९; ४४.३; ९; २३; ४५.१७; २४; ४७.१२; ६२.४; ६६.७; ६९.११; ७२.५; ७३.१०; ९३.२४; ९९.१; १००.४; ७; १०२.१०; ९.४९.२; ६२.१५; ६७.२१; ८५.१; १०.१.६; ७; २.१; ३.७; ९.२; १०.६; ८; ११.९; १२.९; १४.५; १२; १५.३; ५; ७; ११; १३[२]; १६.९; १८.६; ९; १९.३[२]; २२.२; ३८.५; ५२.१; ५८.१–१२; ५९.६; ६१.१९; ६३.२; ६९.३; ७०.२; ३; ८१.६; ८४.५; ८५.२७; ४२; ८७.८; ९०.४; ९८.१२; १००.१; १०१.३; ९; १२; १०४.२; ३; १०६.११; १०८.८; ११०.८; ९; ११४.७; ११९.९[२]; १०[२]; १२८.५; १२९.६; १३०.५; १३७.५; १४१.१; ४; १५१.५; १६०.१; २; १६५.३; १६७.२; १६९.२; १७३.२[३]; १७८.१; १८०.१; १८३.१[२]

इहऽइव १.३७.३; ८.५.१

इहऽइह १.१८१.४; ३.६०.१; ४.४३.७; ४४.७; ५.३०.१०; ४७.५; ७.५९.११; १०.१३१.२

इहि ८.३२.२२[२]

इहि १.४.४; ९.१; १०.४; ७१.१०; ७६.२; ८०.३[२]; १०४.९; ३.३५.६; ४५.१; ५.१६.५; ३५.८; ७८.८; ८३.६; ६.१६.१६; ५४.६; ५५.१; ८.४.८; १२; १७.९; ११; ३२.२१; ५३.५; ६१.७; ६४.४[२]; १०; १२; ६५.५; ९.६४.१३; ९७.३३; १०७.१९; १०.१४.७[२]; ८; १०; १८.१; ८; ३०.५; ३३.७; ३७.९; ५१.५; ५३.६; ६०.७[२]; ८३.३; ५–७; ८४.३; ८६.२०; २१; ९५.२; १३; ९८.१; १०३.१२[२]; १२४.१; ५; १५५.२; १६४.१

इहेहऽमातरा ६.५९.२

इहो इति ९.६५.५

ई

ईक्षयत् १.१३२.५

ईक्षे ४.२०.८; ६.१९.१०; ८.७९.९

ईक्षेण्यासः ९.७७.३

ईङ्खय ९.५२.३[२]

ईङ्खयन्ति १.१९.७

ईङ्खयन्तीः १०.१५३.१

ईङ्खयावहै ७.८८.३

ईङ्खितम् १०.१४३.५

ईजते ५.४८.२; ६.६४.३

ईजानः ४.५१.७; ७.५९.२; ८.२४.३०

ईजानम् १.१२५.४; १०.१३२.१[३]

ईजानस्य ६.४८.२०

ईजानाय १.११३.२०

ईजिरे १०.६६.७

ईजे ६.३.२; १६.४

ईजे ६.१.९

ईट्टे १.१८०.२; ३.५२.५; ५.१२.६; ७.९३.४; ८.१०३.१३

ईट्टे १.८४.१८; १३४.५; ४.२५.१; ३; ७.२४.५; ९१.२; १०.१०४.१०

ईळत १.९६.३

ईळते १.१४.५; ३६.१; ३.६.३; ५.१४.३; ६.२.२; ७.९४.५; ८.७४.६; १२; १०.३०.४

ईळते १.१५.७; १२८.८; ३.१०.२; १३.२; २७.१४; ५.१.७; ८.३; ९.१; १४.२; २१.३; ६.१४.२; १६.७; ७०.४; ७.८.१; १०.५; ११.२; ४५.४; ७६.६; ८.२३.२५;

ईरयाम १०.१११.१
ईरयामहे ७.९४.४
ईरयामि २.३३.८
ईरयाव ७.८८.३
ईरयेथे इति १०.१०६.१०
ईराथाम् ८.७३.१
ईरिरे ३.११.९; २९.१५; ६०.३; ६.५.२
ईर्ते ९.९१.३
ईर्ध्वम् १.११३.१६
ईर्मऽअन्तासः १.१६३.१०
ईर्मा ४.२७.२; ५.६२.२; ७३.३; ८.२२.४; १०.४४.६
ईर्ष्व १०.१८.८; ८५.२१; २२
ईर्वत् ५.४९.५; ८.४६.२१
ईर्वतः ४.१५.५; ४३.३; ७.२३.१; ५६.१८
ईर्वते ४.४.६; ६.७३.२
ईशत १.२३.९; ३६.१६; २.७.२; २३.१०; ४२.३; ६.२८.७; ७१.३; ७५.१०; ७.९४.७; ८.४८.१४; ९.८५.८; १०.२५.७; ३६.२
ईशते ७.६६.६; ८.४७.४; १०.४३.३
ईशाथे इति ७.९७.१०; ९८.७
ईशानः १.५.१०; ७.८; ६१.६; १२; १५; ७९.४; ८४.७; १७५.४; २.२४.१५; ४.१६.११; ७.१.१६; १५.११; ८.६.४१; १७.९; ४०.५; ९.६१.६; १०१.५; १०.७३.८; ९०.२
ईशानः १.८७.४; १३०.९; ९.८६.३७
ईशानऽकृत् १.६१.११; २.१७.४; ६.१८.६; ८.५२.५; ६५.५; ९०.२
ईशानऽकृतः १.६४.५
ईशानम् १.५.२; ११.८; २४.३; ८९.५; ६.५४.८; ५५.२; ७.६.४; २१.८; ३२.२२^{२}; ८.१.२०; २६.२२; ३२.१४; ४६.६; ५३.१; ६८.६; ७६.१; ८१.४
ईशानम् ७.७.७; ८.७; ९.६२.२९
ईशानयोः ७.९०.५
ईशाना १.११३.७
ईशाना ५.७१.२; ७.८२.४; ९४.२; ९.१९.२
ईशानाः १०.९.५
ईशानात् २.३३.९
ईशानाय ७.९०.२
ईशानासः ८.८३.५
ईशानासः १.७३.९; १२२.१३; १२९.२, १४१.३; ७.१.१७; ९०.६; १०.६३.१७; ६४.१७
ईशिरे १०.६३.८
ईशिरे ५.५८.१; १०.५६.४
ईशिषे १.९१.२३; २.२४.१; ३६.१; ४.३२.७; ६.४१.३; ८.४४.१८
ईशिषे १.१७०.५; २.१.६; ७; १०; १३.६; १६.६; ४.५२.३; ५.८१.५; ८.३७.५; ६४.३; ७१.८; ८२.७–९; १०.४४.५
ईशीत ४.१५.५; ८.२३.१५
ईशीय ७.३२.१८; ८.१४.१; १०.३३.८
ईशे २.२८.६; ३.१६.१^{२}; १८.३; ४.२१.४; ६.१८.११; ७.४.६^{२}; ३७.७; १०१.२; ८.२५.२०^{२}; ६८.७; ७१.२; १३; ९.७४.३; १०.६.३^{२}; १२१.३; १८५.२
ईशे १.७१.९; १००.७; १२७.७; १६५.१०; ३.१६.१; ५१.४; ४.१२.३; ५५.८; ६.५१.८; ७.११.४; ७५.५; १०.८६.१६^{२}; १७^{२}; ८९.१०
ईषति ९.७१.६
ईषते १.३९.८; १२४.६
ईषते १.८४.१७; १४१.८; १४९.१; ५.३४.४^{२}; ६७.५^{२}; ८३.२; ८६.३; ६.४२.३; ८.४५.३७; ७८.९; १०.९३.६
ईषथुः १.११२.१६
ईषन्त ८.९६.३
ईषन्ते ६.६६.४
ईषमाणः १.१७१.४
ईषमाणाः ४.५८.६; ८.९६.७
ईषा ३.५३.१७; ८.५.२९
ईषुः ३.१.२
ईषे १०.८९.३
ईषे १.१८६.४; ५.४९.१
ईष्टे ५.८७.३

उ

उक्षत १.८७.२
उक्षतम् १.१५७.२; ३.६२.१६; ५.६३.५; ७.६२.५; ६५.४; ८.५.६
उक्षते १०.९२.५
उक्षन् ४.१.१०
उक्षन्तम् १.११४.७
उक्षन्ति १.१६६.३
उक्षन्ते २.३४.३; ५.५९.१
उक्षऽभिः १.१३९.१०[2]; २.७.५; ६.६४.५; ७.७९.१
उक्षमाणः ५.४२.१४
उक्षमाणम् २.२.४; ९.९९.५
उक्षमाणाः ४.४२.४; ५.५७.८; ५८.८; ६.६६.४
उक्षमाणे इति ४.५६.२
उक्षयन्त ६.१७.४
उक्षा १.१४६.२; ३.७.६; ४.५६.१; ५.४७.३; ९.६९.४; ८३.३; ८९.३; १०.३१.८
उक्षाऽइव ९.७१.९
उक्षाणम् १.१६४.४३
उक्षितः १.३६.१९; २.२१.३; ५.८.७; ९.७२.७
उक्षितम् १.११४.७; २.१६.१
उक्षिताः ५.५५.३
उक्षितासः १.८५.२
उक्षिते इति २.३.६
उक्षेथाम् ७.६४.४
उक्ष्णः ८.७.२६; १०.२८.११; ८६.१४
उखऽछित् ४.१९.९
उखा १.१६२.१५; ३.५३.२२
उखायाः १.१६२.१३
उग्र ८.२४.७; ४६.२०
उग्र १.३३.५; १२९.५; ३.४६.२; ४.२.१८; २०.७; २४.४; ५.३२.२; ६.१७.१; १०; २३.८; २५.१; ३७.१; ४१.३; ५३.४; ७.२२.८; २५.१; ४; २८.२; ८.६.१४; १८; ३३.१०; ३७.२; १०.११३.३
उग्रः १.७.४; ५१.११; ५५.३; १००.१२; १२७.११; १३०.७; १५२.२; १६५.६; १०; १७१.५; १७९.६; २.२३.१२; ३३.९; ३.३०.३; ३६.५; ४८.४; ४.१६.२०; २०.१; ६; २२.२; २३.७; ५.३२.८; ७३.७; ६.१८.६; २३.३; ७.२०.१; ३४.१०; ३८.६; ४०.३; ५६.२३; ८२.५; ८.१.२७; ३.१७; २१.२; २९.५; ३२.२; ३३.९; ४९.७; ५२.५[2]; ६५.५; ९.१०९.२२; १०.२९.३; ४२.७; ७३.१; ९७.१२; १०३.५; १०९.१; ११३.६; १२०.१
उग्रःऽइव ६.१६.३९
उग्रऽदेवम् १.३६.१८
उग्रऽधन्वा १०.१०३.३
उग्रऽपुत्रे ८.६७.११
उग्रऽबाहवः ८.२०.१२
उग्रऽबाहुः ८.६१.१०.
उग्रम् १.८४.९; १०२.१०; ११६.१२; ११८.९; १२९.१०; २.३३.११; ३.२६.५; ३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.११; ३६.४; ११; ३८.१०; ३९.९; ४३.८; ४६.४; ४७.५; ४८.५; ४९.५; ५०.५; ४.३८.१; ५.३०.२; ३१.८; ३५.६; ६.१७.१३; १८.१; ४; १९.६; ११; २६.१; ३८.५; ४६.६; ४७.१५; ५१.८; ७.३३.२; ४१.२; ५६.७; ८.१.२१; २०.३; ४९.६; ५०.६; ६१.१२; ६८.६; ७०.४; ९७.१०; १३; ९.६१.१०; ६२.२९; ९७.२१; १०.२८.७; ४४.३; ४७.३; ८४.३; ८९.१८; १०३.९; १०४.११; १२५.५; १२६.५; १२८.९
उग्रम्ऽउग्रम् ६.४७.१६
उग्रस्य २.२३.११; ३.४६.१; ५.२०.२; ६.१८.४; ८.४.७; १०.३४.८
उग्रा १.२१.४; ५.६३.३; ६.६०.५; १०.१२१.५; १५९.२
उग्रा १.१५७.६; ४.४१.४; ६.६२.३; ७२.५; १०.१०६.७
उग्राऽइव १०.१०६.४
उग्राः १.१९.४; २३.१०; १३४.५; ६.६६.६;

५२.८; १७; ५५.५; ५६.५; ५९.४; ७६.१; ८३.३; ४; ८; १०; ६.१६.४५; १७.६; १८.१३; ३२.२; ३८.१; ४४.१२; ४७.३; ५; ४८.१७; ५१.१; ५७.६; ६४.१; २; ६; ७१.१; ४; ५; ७२.२; ७५.१६; ७.१.२०; २५; ३.३; ८.६; १६.३^{२}; ११; २२.८; २३.१; ३२.१२; ३३.५; १३; ३४.७; ३५.८; ३८.१; २; ४१.३; ४३.२; ४५.२; ६०.२; ४; ६१.१; ६२.१; २; ६३.१–४; ६६.१४; ६९.७; ७२.३; ७६.१; ७७.२; ८१.२; ९९.२; १०४.४; ८.३.१५; ६.४८; ७.३; ७; १७^{४}; १४.८; १३; १९.२३; २३.४; ५; २४.१७; २५.१९; २१; २७.१२; ४३.१०; ४४.४; १७; ६१.७^{२}; ६२.१०^{३}; ६३.२; ६४.१; ६६.४; ६९.७; ७०.९^{२}; ७३.१; ७९.६; ९३.१; ९.५.५; ३३.४; ४७.१; ५०.१; २; ५३.१; ७२.१; ८४.४; ८६.४०; ४१; १०.५.५; ८.१; १०.९; ११.६; १५.१^{३}; १७.१०; १८.८; ११; १३; २३.४; २७.१५; २३; ३५.६; ८; ३७.२; ३; ९; ३९.२; ८; ९; ४३.९; ४५.७; १०^{२}; ५३.८^{२}; ५५.१; ५९.१; ६७.३; ४; ८; ६८.७; ७३.२; ७५.३; ८५.२१; २२; ९०.४; ९७.८; १०१.१; १२; १०२.२; ७^{२}; १०३.९; १०^{४}; १०५.१०; १०८.११; १११.२; ११८.२; ११९.२; ३; १२३.२; १३०.२; १३७.१; १३८.२; १३९.१; १४०.२; १४२.६^{४}; १५३.३; १५९.१^{२}; १६६.५; १६७.४; १७९.१

उ॒त १.१.२; ४.५; ६; १०.६; ११.८; १७.६; २०.६; २३.१९; २२; २४.८; २५.१५; २८.६; ३१.१८; ३२.४; १३; ३४.१; ५^{२}; ३६.६; १५; १७; ३९.२; ४१.६; ४५.१; ४७.६; ५१.३; ५२.१४; ५३.८; ६७.५^{२}; ७४.३; ९; ७६.४; ७९.६^{२}; ८०.१५; ८१.१; ८२.५; ८४.१७; ८५.५; ८६.३; ९०.५; ७; ९१.५; ९४.५; ६; ८; ११; १६; ९५.११; ९६.९; ९८.३; १००.१९; १०१.११; १०२.११; १०३.८; १०५.१९; १०६.३; ७; १०७.३; १०८.३; ५; ९; १०; १३; १०९.१; २; ८; ११०.९; १११.५; ११२.१५; २५; ११३.२०; ११४.२; ७^{३}; १०; ११; ११५.६; ११६.१०; २५; ११७.१९; ११९.९; १२२.४; ६; १२७.९; १२९.३; १३७.२; १३९.८^{२}; १४०.१२^{२}; १४१.१२; १४७.५; १५१.२; ९; १५३.४; १५४.४; १५९.२; १६१.३; १६२.५; ६; १०; २२; १६३.१; १६४.२६; १६७.८; १७०.१; १७१.३; १७५.५; १८०.९; १८१.८; १८३.४; १८६.५–८; १८९.४; ६; १९१.३; २.७.२; ३; ९.६^{२}; १०.२; ११.६; १२.५; १३.८; १६.६; २३.७; २४.१; २; १३; २७.३; ८; ११; १४; २८.८^{२}; ३०.७; ९; ३१.३; ४^{२}; ५; ६^{२}; ३५.११; ३६.२; ३७.४^{२}; ३.४.६^{२}; ५.४; ६.२; ७.५; १३.६; १६.४; १९.३; २५.१; २९.१६; ३०.५; ११^{२}; ३२.८; १२; १३; ३४.२; ८; ९^{२}; ३५.३; ३६.३; ३७.२; ३८.२; ३; ४१.७; ४७.३; ५१.५; ५४.७; १९; ५५.२२; ५६.३; ५; ५९.१; ४.२.४; ३.१५; ९.३; ४^{२}; १२.५; १५.८; १७.८; १०^{२}; १३; १८.४; ११; २०.८; २१.३; ९; २४.७; २५.८; २६.५; २७.२; ३०.४; ६–८; १२–१८; २२; २३; ३१.७; ८; ३३.११; ३४.२; ३; ३८.२; ५–८; ९^{२}; ३९.१; ४०.३; ४; ४२.४; ४५.३; ४८.५; ५०.९; ५२.३^{३}; ५५.५; ५.१.६; १०; २.१०; ५.९; ६.१०; ७.३; ९; ९.३; ४; ७; १०.७; १६.५; १७.५; २४.१; २९.३; ३०.२; ३१.१३; ३३.७–१०; ३४.३; ४१.३; ११; ४२.५; ८; १२; १८; ४३.९^{२}; १७; ४६.२; ४^{७}; ५^{१}; ६; ८; ४७.७; ५२.८; ९^{२}; ५३.८; ५५.२; ७; ५६.७; ५८.१; ५९.५; ६०.६; ६१.५; ६; ८; ९; १८; ६२.३; ६९.१; ४; ७०.३; ७५.४; ७६.३; ५; ७७.२; ५; ७९.८; ८१.१; ४^{४}; ५^{३}; ८३.२^{२}; १०; ८५.४; ८; ६.१.१०; १५.११^{२}; १३; १६.८; ४७; १७.३; १८.७; १९.१; ८; २१.५^{१};

१२; २३.१०; २५.३; ७; ९; २८.१; ३३.५; ३८.४; ४०.१; ४४.१३; ४५.३; ५; ४७.१[२]; ७; १९; २९; ४८.२; ४[२]; १७; १९; ५०.३; ९; १०; १३; १४; ५१.८; ५२.१; १३; ५३.१०[२]; ५४.६; ५६.२; ३; ६०.१; ६१.३; ७; १०; ६२.८; ११; ६३.९; ६४.४; ६७.६; ६८.७; ७.२.६; ५.४; १२.२; ३; १५.३; १७.१; २[२]; १९.५; २०.९; २५.३; २६.४; ३१.२; ७; ३३.१०–१२; ३४.१८; २३; ३५.१४; ३६.७; ९; ३८.५; ४०.३; ४१.१; ४[४]; ४९.२[२]; ५४.३; ५६.११; ५७.६; ५८.१; २; ४; ६३.५; ६४.२; ६६.६; ६८.६–८; ७२.२; ७४.६[२]; ८२.८; ८६.२; ९०.३; ९५.४; ९७.१०; ९८.२[२]; ७; १०४.२२[२]; २४; ८.१.६; ३१; २.३३; ४२; ५.९[२]; २१[२]; २६; ६.२२–२४; ३२; ३३; ३९; ७.१२; २४; ९.१०; ११[२]; १२.७; १४; २१; १३.२३; १४.११; १५.७; १८.७; ८; ११[२]; १६; १९.१९; ३७; २०.१५; १६; २१.८; २३.२; २४.४; २५.१०; १४; २६.१०; १८; ३०.४; ३१.१८; ३२.८; ९; २०[२]; ३५.१३; १४; १६–१८; ४०.९; ४३.१२; १३; १७; ४४.२२; ४५.६; १७; १८; ३३; ३४; ४६.१०; २८; ४७.५; १२; ४८.१; ५; ८; १४; १५; ५२.८; ५३.७; ५४.६; ५७.३; ६०.९; ६१.२; १५; ६६.१०; १४; ६७.१०; ६९.८; ७०.५; ७१.१; ७५.२; ७८.३; ४; ८०.१०; ८३.९; ८४.३; ८६.४; ८८.४; ८९.५; ६; ९२.२८; ९४.४; ९७–१०; ९.१.४; ९; २.१०; ४.३; ६.३; १३.४; २२.५; ६; ३२.६; ४५.३; ५१.५; ५५.३; ६१.८; ६२.२४; ६३.९; १२; ६८.७; ७९.३[२]; ८२.३; ८७.९; ८९.६; ९३.३; ९६.३; ५; ९७.१३; २४; ५३; ५८; १०७.२०[२]; १०.२.२; ४.७; ७.७[३]; ९.८; १०.५; १६.६; ८; १७.२; १८.१; २०.९; २२.९; १५; २५.१; ३; २७.२४; २८.१; ३१.२; ४; ११[२]; ३२.७; ३३.८; ३४.२; ३९.९; ४०.५; ४२.९; ११[२]; ४३.३; ५; ११[२]; ४४.११[२]; ४८.८; ५३.४; ७[२]; ११; ५५.३; ६[२]; ५६.४; ६०.३; ६१.९; १४[२]; १५; २३; ६२.१०; ६३.२; ६४.१०; ६६.११; ६७.३; ६९.४; ५; १०; १२; ७१.४[२]; ५; ७३.३; १०; ७५.८; ७८.६; ८१.३[२]; ५; ६; ८२.२; ८३.६; ८५.१०; ८६.९; १४; ८७.३; ६; ७; २०; ८८.२; ३; ९; १४[२]; १५; ८९.४; १७; ९०.२; ९१.११; ९२.१२; ९३.५–७; १०; ९५.५; ७; ९६.१०; ९७.२; १६; ९९.९; १०२.७; १०४.१०; १०७.७; १०८.५; १०९.६; ११०.२; १११.९; ११६.८; ११७.१[२]; ३; १२१.१; १२४.१ १२५.१; २; ५; ७; १३१.३; १३६.५; १३७.१[२]; १३९.५; १४१.२; १४२.३[२]; १४६.३[२]; १४८.३; ४[२]; ५; १५८.३; १५९.३; १६१.१; १८६.२[३]

उतऽइव १.१६३.४

उत्ऽअगाः ८.९३.४

उत्ऽअजायन्त ४.१८.१; १०.५५.७

उत्ऽअञ्चनः ५.४४.१३

उत्ऽअमन्दिषुः ९.८१.१

उत्ऽअयत् ७.१०४.३

उत्ऽअयनात् १.४८.७

उत्ऽअये ८.४१.२

उत्ऽअर्के १.११३.१८

उत्ऽअवता ६.१८.९

उत्ऽअसृजः २.२३.१८

उत्ऽआचरत् ७.५५.७

उत्ऽआजत् २.१२.३; १४.३; २४.१४

उत्ऽआजत १.११२.१२

उत्ऽआजन् १०.६२.२

उत्ऽआनट् १०.१९.५[२]

उत्ऽआरः १०.४५.५

उत्ऽआरिथ २.९.३

उत्ऽइतः १०.१२१.६

उत्ऽइता १.१०८.१२; ११५.६; ५.६२.८;

६९.३; ७६.३; ६.५१.१; ७.६.७; ४१.४; ७६.३; ८.७२.१७; १०३.११

उत्ऽईतिम् ६.१५.११

उत्ऽईते ३.१५.२; ५.५४.१०; ७.६३.५; ६५.१; ६६.४; ७; १२; ८.१.२९; १३.१३; २७.२१

उत्ऽइनक्षन्तम् १०.८.९

उत्ऽइयर्षि १०.३७.४

उत्ऽईरत् ४.२.७

उत्ऽईरते १.८१.३; २.१७.१

उत्ऽईरयन्ति १.१६८.८

उत्ऽईरयन्ती १.११३.८

उत्ऽईरयन्तीम् ८.१०१.१६

उत्ऽईराणाः ४.३९.५; ७.४४.२

उत्ऽईषितः १०.११९.१२

उत्ऽउत् ४.२१.९

उत्ऽऋचि १.५३.११; १०.७७.७

उत्ऽऋषन् १०.१५५.२

उतो इति १.२३.१५; ११६.१४; १३१.६; १३४.६; १५३.४; १६२.६; १२; २.११.५; १८.२; ३.७.६; १०; ५४.४; ४.९.४; ३८.१; ५.६.९; २५.८; ३८.४; ५५.४; ६.४७.१; ७.१.८; ९; २९.४; ५३.३; ८.६.३१; १३.९; २८; ३१; २१.८; २५.२३; २६.११; ३३.१७; ४०.१०; ११; ७२.६; १८; ९३.५; ९४.६; ९.५७.४; ६४.२६; ९९.४; १०.७१.४; ७३.९; ११७.१; २; १४६.३; १६८.१

उत्ऽओजसः ५.५४.३

उत्ऽओजसम् १०.९७.७

उत्ऽचरत् ७.६६.१६

उत्ऽचरन्तम् ४.२५.४; ६.५२.५; ७.१०४.२४; १०.५९.४; ६

उत्ऽचरसि १०.३७.५

उत्ऽचरातः ८.४०.८; १०.६८.१०

उत्ऽजिहानाः ५.१.१

उत्तभिता १०.८५.१[२]

उत्ऽतमः ३.५.१०; ९.८५.३; १०८.१६; १०.१५९.३; ४; १६६.५; १७४.४

उत्ऽतमम् १.२४.१५; २५.२१; ५०.१०; १५६.४; १६३.७; २.१.१२; २३.१०; ४.३१.१५; ३६.८; ५४.२; ५.२५.५; ५९.३; ९.२२.५; ६; ५१.२; ६३.२९; ६७.३; २८; १०७.१; १०.७५.१; १७०.३

उत्ऽतमा ३.५६.८; १०.९७.१८; २३

उत्ऽतमानि १.९१.१८; ५.२८.३

उत्तमाय्यम् ९.२२.६

उत्ऽतमे १.३१.७; २.४१.५; ५.६०.६; ८.५१.४; ९.६१.२९

उत्ऽतमेभिः ६.६०.३

उत्ऽतरः ४.१८.९; ३०.१; ८.१४.१५; ९.१०७.१८; १०.८५.४०; ८६.१–२३; १०२.१०

उत्ऽतरम् १.५०.१०; ९५.८; १५४.१; २.२३.८; ६.१६.१७; ९.१०७.२; १०.८४.६

उत्ऽतरस्मात् १०.४२.११; ४३.११; ४४.११; ९८.५

उत्ऽतरस्मिन् १०.९८.६

उत्ऽतरा १.३२.९; ३.३३.८; ७.९५.४; ८.२०.६; ३३.१८; १०.१०.१०; २८.६; १४५.३[२]

उत्ऽतराणि ८.४१.९; १०.६७.१०

उत्ऽतरात् ४.२६.६; ५.६०.७

उत्तरात् ६.१९.९; ८.६१.१६

उत्तरात्तात् १०.२७.१५; ३६.१४

उत्ऽतरान् १.११३.१३

उत्ऽतराभ्यः १०.१४५.३

उत्ऽतराम् १.५०.११

उत्तराम्ऽउत्तराम् ४.५७.७

उत्ऽतरे १.७.७; ६.१९.१३; १०.७२.१; १०३.११

उत्ऽतरे १०.१४५.३

उत्तानः ४.१३.५; १४.५

उत्तानऽपदः १०.७२.३; ४

उत्तानऽपर्णे १०.१४५.२

उत्तानयोः १.१६४.३३

उत्तानऽहस्तः ६.१६.४६; ६३.३

उत्तानऽहस्ताः ३.१४.५; १०.७९.२

उत्तानाम् ५.१.३; १०.२७.१३; १४२.५
उत्तानायाम् १.१६४.१४; २.१०.३; ३.२९.३
उत्ऽतिष्ठन् ७.३३.१; ८.७६.१०
उत्थितम् १०.१४९.२
उत्ऽनिनीथः १.१८१.१
उत्ऽनीताः ९.८१.१
उत्ऽनीयमानाः ३.८.९
उत्ऽपतन् २.४३.३
उत्ऽभित् ८.७९.१
उत्ऽभिदः १.८९.१; १३९.६[2]; ५.५९.६; १०.११६.९
उत्ऽभिदम् १.१०२.९
उत्ऽभिदा १०.७६.१
उत्ऽभृतम् ३.२१.५; ६.४७.२७
उत्ऽमदिताः १०.१३६.३
उत्ऽयत् ७.८१.२
उत्ऽयतः ६.६८.१; ९.८६.४६
उत्ऽयतम् १.८०.९; ८.६९.९; ९.६८.५; १०३.१; १०.२२.७; ५०.६
उत्ऽयता २.३१.७; ८.७४.३; १०१.७
उत्ऽयतानि १०.८.२
उत्ऽयति ८.२७.१९
उत्ऽयतिम् १.१९०.३
उत्ऽयन् १.५०.११; १२४.१; १६३.१; ७.६०.१; १०.८८.६
उत्ऽयन्तम् १०.३७.७
उत्ऽयन्ता १.१७८.३
उत्ऽयमीयसी १०.८६.६
उत्ऽव्रतः ३.२.१०; ५.८३.७; ७.५०.४; ८.६.२९; १०.१२७.२; १४२.४
उत्ऽवता १.३५.३
उत्ऽवरीवृजत् ६.५८.२
उत्ऽवर्धयन् ९.११४.२
उत्ऽवावृषाणः ४.२०.७; २९.३
उत्ऽश्वञ्चमाना १०.१८.१२
उत्ऽश्वासे ९.८६.४३
उत्सः १.१५४.५; ५.४५.८; ८.६१.६; ९.८९.६; १०७.४; १०.३०.८
उत्सऽधिम् १.८८.४
उत्सम् १.६४.६; ८५.११; १२१.८; २.१६.७; २४.४; ३.२६.९; ५.३२.१; ५२.१२; ५४.८; ६.४४.२४; ७.५७.१; ८.७.१०; १६; ९.९७.४४; ११०.५; १०.३०.९; ४५.२; ८४.५; १०१.११; १४३.६
उत्ऽसवे १.१०२.१
उत्ऽसवेषु १.१००.८
उत्सस्य १०.५.१
उत्साः ५.५७.१
उत्सान् ५.३२.२
उत्ऽसिनाति १.१२५.२
उत्ऽसिसृप्सतः ८.१४.१४
उत्ऽस्नाय २.१५.५
उत्ऽहर्षयन्ति ५.२७.५
उदक् ३.५३.११; ८.४.१; २८.३; ६५.१
उदकम् १.१६१.८; १०; १६४.७; ४०; ५१; १९१.१४; ९.६७.३२; १०.१०२.१०
उदकात् १०.१६६.५
उदकात्ऽइव १०.१६६.५
उदक्तात् ७.७२.५; ७३.५; १०४.१९; १०.८७.२०; २१
उदऽग्राभस्य ९.९७.१५
उदञ्चः १०.८६.२२
उदञ्चम् २.१५.६
उदऽधिम् ७.९४.१२
उदधीन्ऽइव ३.४५.३
उदऽधेः १०.६७.५
उदन् १.१०४.३
उदनि १.११६.२४; १०.६८.८
उदनिऽमान् ५.४२.१४
उदन्यजाऽइव १०.१०६.६
उदन्यन् १०.९९.८
उदन्यवः ५.५४.२
उदन्यवे ५.५७.१
उदन्याःऽइव २.७.३
उदन्युवः ९.८६.२७
उदनूऽवता ५.८३.७
उदनूऽवतीः ७.५०.४

५१.१२; ५३.३; ५४.७; ५५.५; ६२.४[२]; ६३.३; ६५.३; ७१.१; ३; ७५.८; ७८.१–३; ६.१.६; ८.४; १५.६; १६.३७; ३८; १७.७; २०.८; २१.११; २८.२; ४; ८[४]; ३१.५; ३६.४; ४०.४; ४१.१; ४; ४५.२३; ४७.८; २९; ४८.११; १६; ५०.६[२]; ५२.८; ९; १३; ५५.४; ५७.२; ६०.९; १४; ६२.४; ६७.२; ३; ६८.१०; ६९.४; ७; ७२.२; ७५.८; १३; ७.१.३; ६[२]; २.१; २; १०; ६.६; १४.३; १५.९[२]; १६.११; १८.३; ४; १९.११[२]; २३.३; २६.५; २८.१; २९.२; ३१.९; ३२.१; ३३.९; १४; ३७.७; ४४.३; ४६.२; ५५.२; ६९.६; ७०.६; ७१.४; ७२.२; ७३.४; ७४.३; ४; ८३.३; ९२.१; ५; ९३.६; ९५.४; ५; १०३.३; ८.१.४; ८; ४.९; ११; १४[२]; ५.७; १३; ३०; ६.८; २७; ४०; ४२; ७.११; २७; ८.६; ११.४; १४.१२; १७.२; ४; १८.१४; १५; २०.१४; १८; २२; २१.२; २२.७; १२; १३; २४.२३; २५.२१; २६.४; ७; ९; २७.११; २०; ३२.६; १७; ३४.१; ३५.७; २०; २१; ४०.८; ४१.२; ४३.४; ४४.३; ५; ४५.७; ४६.३०[२]; ४९.५; ६; ५०.३; ४; ५२.३; ५४.३; ७; ५७.३; ४; ६७.१०; ६८.१४; ६९.१३; १७; ७१.९; ७२.७; १२; १५; ७३.३; १४; ८१.५; ७; ८६.२; ८७.३; ४; ९०.१; ९१.५; ९२.१०; ९३.३१[२]; ३२; ३३; ९६.८; १२; ९८.७; १२; ९९.१; ४; १००.११; १०२.९; १३; १०३.१४; ९.११.१; ६; १५.७; १९.६; ४९.२; ६७.२९; ६९.१; ४; ७१.५; ७२.९; ७६.३; ७८.१; ८६.७; ३२; ३९; ९२.२; ९३.५; ९५.३; ९७.५; २०; ३३; ३८; १०२.२; १०.१०.१०; १४.१०; १६.५; १८.८; १०; १२; २४.२; २८.१२; २९.३; ३१.१; ३; ५; ३२.२; ३४.१०; ३५.७; ३६.७; ४०.७; ४२.२; ६०.४; ६१.९; १०; १२; ६६.७; ७०.९; १०; ७२.८; ९; ७३.४; ५; ११; ८३.६; ८५.१५; ८६.२०; ८७.१–३; ८८.१९; ९१.११; ९४.५; ९५.१७[२]; ९७.४; १४; ९८.९; १२; ९९.८; १२; १०२.७; १०४.१; ६; ७; १०६.११; १०९.७; ११४.२; ११७.१[२]; ५; ११९.४; १२३.६; १२४.१; १२५.४; ७; १२७.७; ८; १३०.२; १३६.७; १३७.७; १४०.२; १४५.६; १५१.४; १५३.१; १५४.१; १६७.२; १६९.४; १८३.२

उपऽअंशु १०.८३.७
उपऽअयने २.२८.२
उपऽअरणे ८.३२.२१
उपऽअरे ७.८६.६
उपऽअवति १०.१४६.२
उपऽअवसृज १०.११०.१०
उपऽआगहि १.९१.१०; २.३२.५; १०.१५०.२
उपऽआचरत् १.४६.१४
उपऽआचरेत् १०.१५९.२
उपऽआजतु १०.१९.२
उपऽआभृति १.१२८.२
उपऽआयातम् ७.७१.२
उपऽआरिम १०.१६४.३
उपऽआरुहः ९.६८.२
उपऽआसते १.१६२.१२; १०.१२१.२; १९१.२
उपऽइतयः १०.६९.१
उपऽइतिः १.७६.१
उपऽइतौ ३.१८.१
उपऽइव ८.३.२१
उपऽईयुषः १०.३९.८
उपऽईषे १.१२९.८
उपऽउप १.१२६.७; ८.५१.७; ७४.९
उपऽकक्षासः १०.७१.७
उपऽक्षितः ८.१९.३३
उपऽक्षियन्तः ३.५९.३
उपऽक्षेतारः ३.१.१६
उपऽक्षेति १.७३.३
उपऽगन्तवै १०.१६०.५

उपऽस्थाय ३.४८.३
उपऽस्थायम् १.१४५.४
उपऽस्थे १.३१.९; ३५.५; ९५.५; १०९.३; ११५.५; ११७.५; १४४.२; १४६.१; १८५.२; ५; २.१४.७; ३.५.८; ८.१; २६.९; २९.१४; ५.१.६; १९.१; ६.७.५; ८.४; ७५.१; ४; ७.५.१; ३४.२५; ५६.२५; १०४.९; ८.४०.४; ४२.२; ९४.२; ९६.१५; ९.२६.१; ७१.५; ७४.५; ७६.५; ८६.२५; ८९.१; १०९.१३; १०.५.१; ७; ८.१; ७; १५.७; ४५.३; ४६.१; ६९.१०; ७०.६; ७; ७९.३; ८५.२; ९५.१४; १०१.१०
उपऽस्पिजम् १०.८८.१८
उपऽस्पृशः १०.२२.१३
उपऽह्वरनुम् २.३३.११
उपऽहस्वानः ८.४५.२३
उपऽहूताः १०.१५.५
उपऽह्वरे १.६२.६; ८.६.२८; ६९.६; ९६.१४
उपऽह्वरेषु १.८७.२
उपाकऽचक्षसम् ८.६.२५
उपाकयोः १.८१.४
उपाके १.२७.६; १७८.३; ४.१०.५; ११.१; १६.१४; २०.४; ७.३.६; ४२.३; ७३.२; ८.९६.३
उपाके इति १.१४२.७; ३.४.६; १०.११०.६
उपानसः १०.१०५.४
उपो इति १.३९.६; ६१.१४; ८२.१; १२४.४; ३.३५.३; ७.६७.२; ७७.१; ८४.३; ८६.३; ९२.१; ९३.३; ८.२३.९; २४.१४; ९६.६; १०३.१; ९.६१.१३; ६९.२
उप्यते १.१७६.२
उब्जः ४.१९.५
उब्जतम् ७.१०४.१
उब्जतम् १.२१.५
उब्जन् १.५२.२
उब्जन्तु ६.५२.१
उब्धम् ४.१.१५
उभयतः ५.८१.४; ९.८६.६
उभयत्र ३.५३.५
उभयम् १.१९०.७; २.९.५; ८.६१.१; १०.३२.१; ६४.१४; ८४.७
उभयम्ऽकरम् ८.१.२
उभयस्य ४.५३.६; ६.१९.१०; ४७.१६; ७.९.१; ३३.१२; ८२.४; ८३.५; ८.१०१.१०; ९.८१.२; १०.१३.५[२]
उभया २.६.७
उभया १०.१०८.६
उभयाः २.१२.८
उभयादतः १०.९०.१०
उभयान् १.१८९.७; ४.२.२; ६.१५.९; ३३.३
उभयानि ६.१९.१३; ७.२.२
उभयाय १.३१.७; १०.३७.११
उभयाविन् १०.८७.३
उभयाविनम् ८.१.२
उभयासः १.६०.२; २.२.१२; ४.२४.३; ६.१.५; ७.१.२०; २५; ८३.६
उभयाहस्ति ५.३९.१
उभयाहस्त्या १.८१.७
उभये २.२४.१०; ३.३२.१४; ४.३९.५; ५.५९.७; ७.८२.९; १०.९२.२
उभयेभिः १.१८५.४
उभयेभ्यः १.९१.२३
उभयेषाम् १.२६.९
उभयेषु १.१२२.१४; ४.४४.६
उभयोः १.१२०.१; ६.२५.६
उभा १.२२.२; २३.२; ४६.१५[२]; १११.४; १२०.१२; १२४.५; १४०.३; १४१.४; १८२.४; १८५.९; २.२७.१५; ३.३.११; ४.४.१४; ५.३८.३; ४४.१२; ४६.२; ६८.२; ८६.१; ६.६०.१३[४]; ६९.८; ७.१.१७; ३७.३; ९३.१; ८.५.२९; ३१.८; ६१.१८; ७२.१२; ७७.११; ८६.१[२]; १०१.७; ९.५.७; १०.१४.७; ८५.९; ८६.१४; ८७.३; १०५.२; १२५.१[२]; १२८.७; १३१.५
उभाभ्याम् ९.६७.२५

उरुधाराऽइव ८.९३.३; ९.६९.१
उरुऽधाराम् ८.१.१०
उरुऽनसौ १०.१४.१२
उरुज्जम् ९.७७.४
उरुऽभिः १०.७.१
उरुम् १.२४.८; ५७.६; ९३.६; २.२२.१; ३.४१.५; ४६.४; ५.१५.५; ६.२३.७; ४७.८; ७.३३.५; ६०.९; ८४.२; ९९.४; ८.६५.३; ६८.१३[३]; ९.८५.४; १०.४७.३; १८०.३
उरुऽयुगे ८.९८.९
उरुऽलोकम् १०.१२८.२
उरुव्यचःऽतमम् ८.२६.१४
उरुऽव्यचसम् ६.३६.३; ८.२.५; १०.१८.१०
उरुऽव्यचसा १.१६०.२
उरुऽव्यचसे ७.३१.११
उरुऽव्यचा १.१०८.२
उरुऽव्यचाः १.१०४.९; ३.५०.१; ५.४६.६; १०.१२८.८
उरुऽव्यञ्चम् ५.१.१२
उरुऽव्रजे ८.६७.१२
उरुऽशंस १.२४.११
उरुऽशंस १.१३८.३; ८.४८.४
उरुऽशंसः ४.१६.१८
उरुऽशंसस्य २.२८.३
उरुऽशंसा ३.६२.१७
उरुऽशंसाः २.२७.९
उरुऽशंसाय १.३१.१४; २.३८.११
उरुषु १.१५४.२
उरुष्य १.५८.९; ९१.१५; ५.२४.२; ८.७१.७; १०.७.१
उरुष्य १.५८.८; ४.२.६; ११
उरुष्यत् ३.५.८
उरुष्यत् १०.८०.३
उरुष्यत ५.८७.६; ८.२५.११; ४७.६
उरुष्यतम् ४.४३.४; ७; ४४.७
उरुष्यतम् ५.६५.६; ८.१०१.४[२]
उरुष्यताम् ८.२५.१०
उरुष्यताम् ७.८५.१; १०.९३.६
उरुष्यति २.२६.४; ६.१४.५
उरुष्यति १.१५५.२; १०.१७६.४
उरुष्यतु ८.४७.९
उरुष्यथः १.१५५.२
उरुष्यथः १.११९.६; १०.४०.८
उरुष्यन्तु ८.२५.१०
उरुष्यवः ८.४८.५
उरुष्या ६.४४.७
उरुष्याः ७.३.८
उरुष्यात् ७.१.१५
उरुष्येत् १.१५२.६; १५८.४; ४.५५.५
उरुऽसाम् ५.४४.६
उरूचि ८.६७.१२
उरूची १.२.३; ३.३१.११; ५७.५; ७.३५.३
उरूची इति ४.५६.४; ६.११.४
उरूचीम् ७.४५.३
उरोः १.२५.९; ३.४६.३; ५.३८.१; ६.७५.१८; ७.६१.३; ९.९६.३
उरौ २.२७.१६; ३.१.११; ६.८; ५४.९; ५.४२.१७; ४३.१६; ५२.७; ७.३९.३; ८.९८.९; ९.९७.१६; १०.७०.६; १३१.१
उर्वरा ८.९१.६
उर्वराऽजिते २.२१.१
उर्वराणाम् १०.१४२.३
उर्वराऽपते ८.२१.३
उर्वराम् ८.९१.५
उर्वराऽसाम् ४.३८.१; ६.२०.१
उर्वरासु १.१२७.६; ४.४१.६; ५.३३.४; ६.२५.४; १०.५०.३
उर्वशी ५.४१.१९[२]; १०.९५.१०
उर्वशीः ४.२.१८
उर्वशीम् १०.९५.१७
उर्वश्याः ७.३३.११
उर्वारुकम्ऽइव ७.५९.१२
उर्विऽऊतिः ६.२४.२
उर्विया १.९२.९; १२; ११३.५; १२४.१; १४१.५; २.३.५; ३५.८; ३.१.१८; ५.२८.१; ४५.९; ५५.२; ६.६.४; ३०.२; ६४.२; ३; ७.१७.१; ८.८६.५; १०.१०.२;

४५.८; ६९.२; ९२.१२; ११०.५; ११३.१०
उर्वी १.२४.९; १८९.२; ६.४७.२०; ७.३६.१; ८.८०.८; ९.७४.३
उर्वी इति १.६१.८; १८५.६; ७; ३.६.१०; ३८.३; ५६.७; ४.४२.३; ५६.३; ६.१०.४; ६७.५; ६८.४; ९; ७०.१; ४; ७.१२.१; १८.२४; ३४.२४; ५७.१; ८६.१; १०.१२.३; ८८.१४; ९३.१; १७८.२
उर्वीः १.८.७; ३.३३.६; ६.४७.३; १०.१४.१६; ७९.३
उर्वीः १०.१२८.५
उर्वीम् २.४.७; ३.३३.३; ५.६२.५; ६६.३; ६.१७.७; ७.३८.२; ७७.४; ९.७८.५; ८५.८
उर्व्याः १.१४६.२
उलपस्य १०.१४२.३
उलूकः १०.१६५.४
उलूकऽयातुम् ७.१०४.२२
उलूखल १.२८.६
उलूखलक १.२८.५
उलूखलऽसुतानाम् १.२८.१–४
उल्काः ४.४.२
उल्काम्ऽइव १०.६८.४
उल्बम् १०.५१.१
उवाच १.११६.१२; ७.८७.४
उवाच २.३०.२; ५.२.८; ७.९८.३; १०.३२.६
उवास १.४८.३
उवास १.११३.१३; १०.११.३
उवाह १.११६.१८
उवे १०.८६.७
उवोच ७.४.३
उवोच ७.२०.४; २१.१
उवोचिथ ७.३७.३
उशतः १.१२.४; ७१.६; २.३७.६; ६.४.१; ७.१७.२; ३९.४; १०३.३; ८.६०.४; १०.१.७; २.१; १६.१२; ७०.४
उशता ६.४०.४; १०.१६०.३
उशताम् १०.११.३
उशती १.१०९.४; १२४.७; ४.३.२; ५.४३.११; ९.९३.४; १०.७१.४; ८५.३७; ९१.१३
उशती इति ३.३३.१
उशती इति १०.७०.६
उशतीऽइव ५.३२.१०
उशतीः १.२२.९; ६२.११; ७१.१; १२४.१३; १४५.४; २.४.३; ५.४६.७; ७.१०.१; १७.२; ९.९५.३; १०.३०.२; ६; १५; ४३.१; ७०.५
उशतीःऽइव १०.९.२; १११.१०
उशतीम् ६.४७.३
उशते ३.४३.७; ४.१७.१७; २४.६; ७.९३.१; ९.९७.४६; १०.९१.१३
उशत्ऽभिः १०.१५.८
उशत्ऽभ्यः १.१६२.११
उशधक् ३.६.७; ३४.३; ७.७.२
उशन् १.१०१.१०; २.३६.४; ३७.६; ४.२०.४; २५.१; ६.४.१; १०.६; ७.९८.२; १०.१५.८; १६.१२; ३०.६; ७०.९
उशना १.५१.१०; ८३.५; १२१.१२; १३०.९; ४.२६.१; ५.२९.९; ३१.८; ३४.२; ८.७.२६; २३.१७; ९.८७.३; १०.२२.६
उशनाऽइव ४.१६.२; ९.९७.७
उशनाम् १०.४०.७
उशने १.५१.११; ६.२०.११
उशन्तः ८.९३.२२; १०.१६.१२[२]; ७०.६; ८५.३७
उशन्तः १०.३०.२
उशन्तम् १.६२.११; ७१.१; २.११.६; ३.५.७; ४.२२.३; ९.६८.६; ९५.३; १०.११.३
उशन्ता ७.४२.५; ९१.२
उशन्ति १.२.४; १०.१०.३
उशन्ति ९.९६.४
उशमानः ४.१९.४
उशानः ३.५.७; ४.२३.१; ६.३९.२
उशिक् १.६०.४; ३.३.७; ११.२; १०.४५.७
उशिक्ऽभिः १.१८९.७; ३.३४.४
उशिक्ऽभ्यः २.४.५

उशिजः १.६०.२; १३१.५; २.२१.५; ३.२.९; १५.३. ६०.१; ४.१.१५; ६.११; १६.६; ५.३.४; ७.१०.२; ५; ९०.४; ९.८६.३०; १०.४५.११; ४६.२; ४; १०४.४

उशिजम् ३.२.४; ३.८; २७.१०

उशिजाम् १.१२८.१; १०.९२.१२

उशिजाम्ऽइव २.३१.६

उशीनराण्याः १०.५९.१०

उशेन्यः ७.३.९

उश्मसि १.३०.१२; ८६.१०; ९४.३; ८.४५.२०; १०.३८.२; ७४.६

उश्मसि १.२१.१; २२.६; १२९.४; १५४.६; ५.७४.३; ८.८०.९; ९.३१.६; ६६.१४; १०.३९.२; ४०.११

उषः १.४८.४; ९; ११; १२; १४; १५; ४९.१; ३; ५७.३; ९२.७; ८; १३; १४; ११३.७; ९; १२३.३; ५; १३; १२४.१२; ३.६१.१–३; ४.५२.६; ७; ५५.९; ५.७९.१; ६; ७; ६.६४.२; ५; ६; ७.७५.२; ८; ७६.३; ६; ७७.५; ६; ७८.१; ८१.३; ५; ८.४७.१६; १८; १०.९५.४; १२७.७

उषः १.६९.१; ५; ३.६.७; ७.१०.१; ८.४१.३

उषः १.३०.२०; ४८.१; २; १२; १६; ४९.२; ४; ९२.१५; ११३.१२; १२३.११; १२४.१०; ४.५२.३; ५.७९.१०; ६.६५.५; ७.७९.४; ८१.२; ८.९.१७; १८; १०.५५.४

उषःऽउषः १०.८.४

उषःऽबुधः १.१४.९; ४४.१; ९; ९२.१८; १३२.२; ४.४५.४; ७.७६.६

उषःऽबुधम् ३.२.१४; ४.६.८; ६.१५.१; ९.८४.४

उषःऽबुधे १.१२७.१०

उषःऽभुत् १.६५.५; ६.४.२

उषत्ऽभिः १.६.३

उषमाणः ४.२२.२

उषसः १.३४.३; १०; ४४.१; १०; ७९.१; ६; ९०.७; ९२.१; २; ९४.५; ११३.१७; १८; २०; ११८.११; १२१.६; १२३.६; ११; १२; १२४.९; १३१.६; १३४.३[२]; ४; १३७.२; १५१.५; १७९.१; १८०.१; २.२.२; ७; ८; १५.६; २०.५; २१.४; २८.९; ३४.१२; ३.५.१; २; ७.१०; १५.२; १७.३; ३०.१३; ३१.४; ५५.१; ५८.१; ४.१.५; १३; १७; २.१५; १९; ५.१३; १४.१; ४; १९.८; २३.५; ७; ३९.१; ३; ४०.१[२]; २; ४५.२; ५१.१–३; ६–९; ५.३७.१; ४५.१; ५९.८; ६२.८; ८१.२; ६.१५.५; २८.१; ३८.४; ३९.३; ४४.२३; ५०.८; ५२.४; ६०.२[२]; ६४.१; ६५.२; ७.६.५; १८.२०; ३५.१०; ३९.२; ४१.६; ७; ६७.२; ६९.५; ७१.१; ७२.३; ४; ७५.३; ७६.२; ७८.३; ७९.२; ८०.३; ८८.४; ९०.४; ८.९६.१; ९.१०.५; ७१.७; ७५.३; ८३.३; ८६.१९; २१; ९०.४; १०.६.३; २९.२; ३१.७; ३५.१; ५; ६; ३९.१; ४१.१; ७३.६; ८८.१२; १८; १९; ८९.१२; ९२.२; १११.७; १२२.७; १३८.१

उषसः १.१२४.१३; ४.५१.४; ५; ११; ६.६५.३; ४; ७.७८.५

उषसम् १.३२.४; ४४.८; ५६.४; ७१.१; ११३.११; ११५.२; २.१२.७; ३.२०.१; ५; ३१.१५; ३२.८; ४४.२; ६१.५; ६; ४.३.११; १२.२; ३०.९; ५.१.१; ५.६; २८.१; ८०.१; ६.१७.५; ३०.५; ७२.२; ७.३३.७; ४४.१; ३; ७५.६; ७; ७६.४; ७८.४; ८०.१; ८५.१; ९१.१; ९९.४; ८.५.२; ९.८४.२; १०.३५.२; ५८.८; ६४.३; ६५.१०; ६७.५; १०१.१; १२७.३

उषसा १.४४.२; १४; ६२.५; ७३.७; १८३.२; ३.१४.३; ५.१.४; ५१.८; ७.४२.५; ४४.४; ८.२७.२; ३५.१–२१

उषसानक्ता १.१२२.२; १८६.४; २.३.६; ३१.५; ४.५५.३; ५.४१.७; ७.२.६; १०.३६.१; ७०.६; ११०.६

उषसाम् २.२८.२; ३.६१.७; ४.१३.१; ५.७६.१; ६.४७.५; ७.५.५; ८.१; ९.१; ३; १०.२; ६३.३; ६८.९; ८.११.३१;

ऊ

ऊपथुः १.११६.११

ऊपथुः १.११७.५; १२; १०.३९.८

ऊपिषे १.३१.९

ऊपे १०.६८.३

ऊँ इति १.२४.८; २६.५; २७.४; २८.१–४; ३०.२; ४; ३२.१५; ३४.२; ६; ३५.६; ३६.१३; ३७.१०; ४५.५; ४६.१०²; ११; ५०.१; ५२.८; ५३.१; ६१.१–८; ११–१५; ६२.६; ७७.२; ७८.२–४; ८०.७. ८२.६; ९१.१८; ९२.१; ९३.६; १०५.२; १०८.४; ११०.१²; ११२.१–२३; ११३.२; ४; ५; ११; ११६.१७; १२३.८; १२४.५; १३८.४; १३९.४; १४०.४; ११; १४३.७; १५४.४; १५६.१–३; १६१.१; १६२.२१; १६४.५; १६; १९²; २६; २८; ४८; १६८.१; १७३.५; १७८.५; १७९.१; २; १८१.१; १८४.२; १९१.५; २.२.५; ३.११; ५.३; ६.१; ८.३; ९.२; १८.२; २०.४; २४.६; ११²; २९.३; ३०.६; ३३.९; ३५.३; १०; १५; ३७.२²; ३८.१; ४१.७. ३.१.३; २.९²; ४.१०; ५.२; ३; ९; ८.४; २०.२; २४.४; २९.८; ३१.७; ११; ३२.१५; ३६.१; ३७.११; ३८.२; ४६.५²; ५१.४; ५३.४; २१²; ५४.७; ५७.४; ६२.१; ४.२.४; ३.२; ५.३; ९; ११; ६.३; ११; ७.९; ८.४; ९.६; १७.१७; १८.७; २०.४; २१.४; ९²; २२.७; २३.१०; ३४.४; ३६.२; ३८.२; ३९.१; ५; ४०.१; ४३.१; २; ६; ५१.१; २²; ५५.४; ५८.९; ५.१.६; २.१०; ४.११; १७.३; २९.२; १३; ३०.१५; ३१.४; ३४.४; ३९.५; ४२.११; ४४.८; १४; १५; ४८.१; ५५.७; ५८.१; ७३.४; ८; ९; ७४.९; १०; ८३.१०²; ८५.५; ६; ६.१.१०; ७.६; ९.६; १०.२; १५.१; १२; १७; १९; १६.१४–१६; १८.१; २१.१; २; १०; २२.२; २३.३; ७; २४.५; ९; २५.१; २७.१²; २²; ७; २९.१; ३८.१; ४०.२; ४४.४; १४; ४५.६; १०; ११; १३; १६; २५; २८; ५१.१; ३; १०; ५३.१; ५४.२; ६४.१²; ७१.१; ४–६; ७३.२; ७.२.१०; ४.८; ९; ८.२; ३; १७.६; १८.३; १७; २०.२; ५; २१.२; २३.१; २९.२; ३०.२; ३३.५; ३५.२²; ३; ७²; ८; ९²; ११; १२; ३८.१; २; ४२.३; ४४.२; ५; ६०.९; ६१.६; ६३.१; २; ६६.१४; ६७.५; ६८.४; ७२.३; ७३.२; ७४.१; ७६.१; २; ७८.३; ८१.१; ८४.२; ८५.२; ८६.८; ८८.२; ९३.६; ९५.६; ९६.१; ९७.३; ९९.४; १०१.३²; १०४.१३; २०; २१; ८.२.१३; १६; १७; ३.३; १४²; १५; २०; ७.६; ७; १७²; १९; २२²; ९.१६; १५.१; ४; १७.७; २०.१९; २१.१; ९; २२.१३; २३.५; ७; १३; १६; २४.१; १६; २६; २५.१९; २६.१; २७.१२; ३०.३; ४०.३; ४१.१; २; ४३.२४; ४४.६; ९; ४५.१६; २८;३३; ४६.२७; ४७.७; ४८.३; ५२.१०; ६१.५; १२; ६२.१२; ६३.५; ८; ६४.६; ८; ९; ६५.५; ६६.७; ९; १०²; १३; ६९.१४; ७०.९²; ७५.७; ८०.१०; ८१.८; ८२.३; ८४.५; ९०.६; ९२.४; ५; ७; १२; ९३.१५; ९५.६; ९६.५; ६; १००.३; १०३.१०; ९.२.८; ३.१०; १५.८; १७.७; २१.७; ३८.१; ४५.४; ६१.७; २०; ६६.८; ८६.२१; ९२.५; ९७.३; १०१.८; १०७.८; १०८.११; ११०.१; ११२.१; १०.१.४; २.३; १०.६; ११; १२; १४²; १३.२; १४.२; १५.१३; १६.४; ११; १३; १७.२; २१.२; २५.४; २७.५; ६; ७²; १०; २९.४; ३०.७; १५; ३१.४; ७; ३२.८; ३५.१; ३८.५; ३९.१; ४०.११; ४१.१; ४८.७; ५२.३; ५४.३; ५६.१; ६१.२४; २७; ६५.१०; ६९.२; ७१.७²; ८; ११; ७२.४; ७६.२; ८१.४²; ८५.४७; ८६.३; १३; ८८.६; १०; १८; ९२.१४; ९४.८; ९५.१४; १५; १८; १०२.१०; १०३.११; १०४.१०; १०६.१; १०७.६; ११०.४; ११४.४;

ऊर्ध्वम् १.२४.७; ८५.१०; ८८.४; ३.८.८; ३१.१२; ६१.५; ४.६.२; १३.२; १४.२; ७.२.७; ७२.४; १०.३.२
ऊर्ध्वया १.१२७.१
ऊर्ध्वऽशोचिषम् ६.१५.२
ऊर्ध्वसानः १०.९९.७
ऊर्ध्वऽसानुः १.१५२.५
ऊर्ध्वा १.८८.३; ११९.२; १३४.१; १७१.३; ३.४.४; ५५.१४; ६१.३; ७.४३.२; ८.४५.१२; ९.८८.२; १०.६१.२०; १०५.९
ऊर्ध्वाऽइव ५.८०.५
ऊर्ध्वाः १.१४०.८; १८१.६; ३.५७.४; ५८.२; ७.७८.१; १०.९२.१५
ऊर्ध्वान् १.३६.१४; १७२.३
ऊर्ध्वाम् १.१४४.१; ७.६४.४; १०.२७.१३
ऊर्ध्वासः ७.३१.९; १०.११५.९[२]
ऊर्मयः १.४४.१२; ५२.७; १६८.२; ४.५८.६; ६.४४.२०; ६४.१; ७.९६.५; ८.१०३.११; ९.७.८; ३३.१; ६१.५; ८१.१; ८६.२; ९५.३; १०.६८.१
ऊर्मा ९.१२.३; २१.३; ३९.४; ८५.१०
ऊर्मिः २.१६.५; ३.३३.१३; ४.५८.१; ६.४७.१४; ८.१४.१०; ७५.९; ९.६४.११; ७८.२; ८०.५; ८६.४०; १०८.५; ११०.११; १०.१४८.५
ऊर्मिणम् ९.९८.६
ऊर्मिणा ९.६८.८; ७४.५; ७६.३; ८६.१३; २५; १०६.१०; १०७.१५
ऊर्मिऽभिः १.९५.१०; ३.३३.२; ४.५८.७; ६.६१.२; १०.६४.९
ऊर्मिम् १.९५.१०; ३.४७.१; ४.५७.२; ५८.११; ६.१७.१२; ४१.२; ७.४७.१; २; ४; ८.५९.३; ९.४४.१; ४९.१; ८६.८; ८८.५; ९६.७; ८; १९; १०.३०.२; ३; ७–९; १२३.२
ऊर्मीन् ४.१९.५
ऊर्मेःऽइव ९.५०.१

ऊर्मौ १.२७.६; ९.१४.१; ७२.७; ७३.२
ऊर्म्या १.१८४.२
ऊर्म्याः २.४.३; ८.९६.१
ऊर्म्यायाः ६.१०.४; ६५.२
ऊर्म्यासु ६.४८.६
ऊर्म्ये ५.६१.१७; १०.१२७.६
ऊर्वःऽइव ३.३०.१९
ऊर्वम् १.७२.८; २.३५.३; ३.३२.१६; ४.२.१७; २८.५; ५०.२; ५.२९.१२; ३०.४; ६.१७.१; ७.९०.४; १०.७४.४; १०८.८
ऊर्वस्य ८.६६.३
ऊर्वात् ४.१२.५; ५.४५.२; ६.१७.६
ऊर्वान् २.१३.७; ७.१६.७
ऊर्वे ३.१.१४; ७.७६.६; ९.८७.८
ऊर्वोः ८.७०.१०
ऊवध्यम् १.१६२.१०
ऊवुरित्यूवुः १.६१.८
ऊष ४.५१.४
ऊषतुः १०.४०.२
ऊषुः ३.७.१०
ऊष्मण्या १.१६२.१३
ऊहति ५.३४.३
ऊहथुः १.४७.९; ११२.१९; ११६.५; ८.३८.५
ऊहथुः १.११६.३; ४; २०; ११७.९; १४; १५; २०; १८२.७; ६.६२.३; ६; ६३.६; ७.६९.७; ७१.५; ८.२६.१५; १०.३९.४; ७; ६५.१२
ऊहसि ८.२१.१४
ऊहिरे २.३४.१२; ८.१९.१
ऊहिषे १.१२८.६
ऊहुः ४.२७.३
ऊहे ५.३.९
ऊहे १.१८१.४; १०.५२.३
ऊह्याते १.१२०.११
ऊह्याथे इति ४.५६.६

६.१७.२; १८.२; २४.१; ८.१०.५; १०.८९.५
ऋजु २.३.७; ४.१.१७; ५.४६.१; ६.५१.२; ७.६०.२; १०.६७.२
ऋजुऽअश्वः ४.६.९
ऋजुः २.२६.१; ९.९७.४३
ऋजुऽक्रतुः १.८१.७
ऋजुऽगाथ ५.४४.५
ऋजुना १.४१.५
ऋजुनीती १.९०.१
ऋजुम् ९.९७.१८
ऋजुऽमुष्काः ४.६.९
ऋजुऽमुष्कान् ४.२.२
ऋजुऽयताम् १.८९.२
ऋजुऽयते १.११६.२३; ५.१२.५; १०.१००.३
ऋजुऽयन्तम् १.१३६.५
ऋजुऽयमानः १०.८८.९
ऋजुऽयवः १.२०.४
ऋजुयाऽइव १.१८३.५
ऋजुऽवनिः ५.४१.१५
ऋजुऽहस्ता ५.४१.१५
ऋजूनसि ८.५२.२
ऋज्यते १.१४०.२
ऋज्यन्तः ६.३७.२; ३
ऋज्रऽअश्वः १.१००.१७; ११७.१८
ऋज्रऽअश्वम् १.११६.१६
ऋज्रऽअश्वस्य १.१००.१६
ऋज्रऽअश्वे १.११७.१७
ऋज्रः ९.९७.९; १०.२०.९
ऋज्रम् ८.२५.२२
ऋज्रा १.१७४.५; ४.१६.११; ८.१.३२; १०.२२.५
ऋज्राः ८.३४.१७
ऋज्रासः ७.१८.२३
ऋज्रे इति ६.६३.९
ऋज्रेभिः १.११७.१४
ऋज्रेषु ८.६८.१८
ऋज्रौ ८.६८.१५
ऋञ्जत ५.८७.५
ऋञ्जती १.१७२.२
ऋञ्जते १.६.९; ३७.३; १२२.१३; १४१.६; १४३.५; ७; २.१.८; २.५; ५.४८.५
ऋञ्जन् १.९५.७; ३.३१.१; ४.३८.७; ८
ऋञ्जन्ति ३.४३.६
ऋञ्जसानः १.५८.३; ४.२१.५
ऋञ्जसानम् १.९६.३
ऋञ्जसे ८.४.१७
ऋञ्जसे ४.८.१; ५.१३.६; ६.१५.१; ४; १०.७६.१; १४२.२
ऋञ्जे ३.४.७; ७.८; ४.२६.१
ऋणः ६.१२.५
ऋणऽकातिम् ८.६१.१२
ऋणऽचित् २.२३.१७
ऋणऽच्युतम् ६.६१.१
ऋणवेत् १.८४.१६
ऋणम् २.२४.१३; ४.३.१३; ८.३२.१६; ४७.१७
ऋणम्ऽचयस्य ५.३०.१२
ऋणम्ऽचये ५.३०.१४
ऋणऽयाः २.२३.११; १७; ४.२३.७; ९.११०.१; १०.८९.८
ऋणऽयावा १.८७.४
ऋणवः १.४८.१५; १३८.२
ऋणवः ७.८.३
ऋणऽवा १०.३४.१०
ऋणऽवानम् १.१६९.७
ऋणा २.२८.९; ४.२३.७; ९.४७.२
ऋणाऽइव १०.१२७.७
ऋणानि २.२७.४
ऋणुत ५.४५.६
ऋणोः १.३०.१४; १५; १७४.२; ९; ६.१८.५; २०.१२; ९.१०२.८
ऋणोति १.३५.९
ऋणोमि ८.२४.६
ऋण्वति १.५८.३; १२८.६[२]; १४४.५; ३.२.१; ११.२; ५.१६.२; ६.२.६
ऋण्वथः १.१३९.४; १५१.५
ऋण्वन् ७.२.१

ऋतवरी इत्यृतऽवरी ३.५४.४
ऋतवरी इत्यृतऽवरी १.१६०.१; ३.६.१०; ४.५६.२; १०.३६.२; ६६.६
ऋतऽवरीः ३.३३.५
ऋतऽवरीः ३.५६.५
ऋतवरीःऽइव ४.१८.६
ऋतऽवरीम् ५.८०.१
ऋतवसो इत्यृतऽवसो ८.१०१.५
ऋतऽवा १.७७.१; २; ५; १२२.९; २.३५.८; ३.१३.२; २०.४; ५३.८; ५४.१२; ४.२.१; ६.५; ७.७; ३८.७; ४२.४; ५.१.६; २५.१; ६.१२.१; १५.१३; ६८.५; ७३.१; ७.३.१; ७.४; ६१.२; ८.७५.३; ९.९६.१३; ९७.४८; ११०.११; १०.२.२; ६.२; ७.४; १६८.३
ऋतऽवाकेन ९.११३.२
ऋतऽवानः २.२४.७; २७.४; ३.५६.८; ५.६७.४; ७.३९.७; ४०.७; ६२.३; ६६.१३; ७६.४; ८७.३; १०.१५४.४
ऋतऽवानम् ३.२.१३; ४.१.२; ७.३; ८.२३.९; १०.१४०.६
ऋतऽवाना १.१३६.४; १५१.८
ऋतऽवाना ५.६५.२; ८.२३.३०; २५.१; ७; ८
ऋतऽवानौ १.१५१.४
ऋतऽवानौ ८.२५.४
ऋतऽवृधः १.१३.६; १४.७; ४४.१४; १४२.६; ५.४४.४; ६.१५.१८; ५०.१४; ५२.१०; ७.६६.१०; १३; ८२.१०; ८३.१०; ८.८९.१; ९.४२.५; १०२.६; १०.१६.११; ६५.७; ६६.१; १५४.४
ऋतऽवृधः ६.७५.१०
ऋतऽवृधा १.१०६.३; १५९.१; ५.६५.२; ९.९.३
ऋतऽवृधा १.४७.१; ३; ५; २.४१.४; ३.६२.१८; ६.५९.४; ७.६६.१९; ८.८७.५
ऋतऽवृधाम् १०.६५.३
ऋतऽवृधे ३.२.१
ऋतऽवृधौ १.२३.५
ऋतऽवृधौ १.२.८
ऋतऽज्ञे ८.१०३.८
ऋतऽसत् ४.४०.५
ऋतऽसापः १.१७९.२; ५.४१.६; ६.२१.११; ५०.२; ७.५६.१२; १०.६६.८; १५४.४
ऋतऽस्तुभम् १.११२.२०
ऋतऽस्पृशः ४.५०.३; ५.६७.४
ऋतऽस्पृशम् ८.७६.१२
ऋतऽस्पृशा १.२.८
ऋतस्य ५.६३.१
ऋतस्य १.१.८; २३.५; ४३.९; ४६.११; ६५.२[२]; ६७.४; ६८.३[२]; ७३.६; ७९.३[२]; ८४.४; १६; १०५.६; १२३.९; १३; १२४.३; १२८.२; १३२.३; १३६.२; १४१.१; १४२.७; १४३.७; १४४.२; १४७.१; १५६.३; ५; १६३.५; १६४.११; ३७; ४७; २.२३.३; १७; २८.५; ३४.१३; ३.१.११; २.८; ५.२; ६.६; ७.२; १०.२; १२.७; २७.११; ३१.१; ५; ५४.६; ५५.१२–१४; ६१.७; ६२.१३; १८; ४.१.१२; २.३; ३.४; ५.९; ७.७; १०.२; २१.३; २३.८[३]; ९; १०; ४२.४; ४४.३; ५१.८; ५७.२; ५.५.६; ७.३; १२.१; २; २१.४; ४१.१; ४५.८; ८०.४; ६.१३.२; १६.३५; १७.७; ४४.८; ४८.५; ४९.१५; ५१.१; ३; ९[२]; ५५.१; ७.७.६; ३६.१; ५; ३८.२; ४०.४; ४३.४; ४४.५; ५३.२; ६०.५; ६५.३; ६६.१२; ९५.६; ८.६.२[२]; ८; १०; १९; ७.२१; ८.२३; १२.३; १३–१५; १९.३५; २२.७; ३१.१३; ५२.९; ५९.४; ८३.३; ८६.५; ९५.५; १००.४; ५; ९.७.१; ८.३; १२.१; १३.९; ३२.४; ३३.२; ५; ३४.५; ३९.६; ४८.४; ६३.४; १४; २१; ६४.११; १७; २०; २२; ६६.१२; ६८.५; ७२.६; ७३.१; ६; ८; ९; ७४.४; ७५.२; ३; ७६.४; ७७.१; ८६.२५; ३२; ३३; ८९.२; ९५.२; ९७.३२; ३४; १०२.१; ७; ८; १०७.४; ११०.४; १११.२; १०.५.२; ४; ७; ८.३; ५; १३.३; ३०.११; ३१.२; ३५.८; ४३.९;

५९.८; ६१.१४; १९; ६५.७; ८; ६६.१३; ६८.४; ७०.२; ८०.६; ८५.२४; ८६.१०; ९२.४; १००.१०; ११०.२; ११; १११.२; ११८.७; १२३.२; ३; १२४.३; १३३.६; १७७.२

ऋतस्य ७.६४.२

ऋता १.४६.१४; ६७.४; १६१.९; ६.१५.१४; ६७.४; ९.९७.३७; १०.१०.४; १०६.५

ऋतात् १.३६.११; १३९.२; ८.१३.२६; १०.७३.५

ऋतानाम् १.१६५.१३; ४.२३.४

ऋतानि १.१७९.२; १०.१२२.६

ऋताय १.३४.१०; १२१.४; १३७.२; १५१.३; ६; १५३.३; ४.३.८; २३.१०[२]; ५.२०.४; ९.१७.८; ९७.२३; १०.८.४; ५

ऋतिऽसहः ८.४५.३५

ऋतिऽसहम् १.६४.१५; ६.१४.४; ८.६८.१; ८८.१

ऋतुः १.१६२.१९; २.१३.१; ५.४६.८

ऋतुऽथा १.१६२.१९; १६४.४४; १७०.५; २.३.७; ४३.१; ५.३२.१२; ६.९.३; १८.३; ६२.९; ८.१३.१९; ४४.८; ९.९७.१२; १०.२८.५; ४०.४; ८५.१६; ९८.४; ११०.१०; १३१.३

ऋतुना १.१५.१–४; ६;११; १२; २.३७.६

ऋतुऽपते १०.२.१

ऋतुऽपाः ३.२०.४; ५.१२.३; १०.९९.१०;

ऋतुऽपाः ३.४७.३

ऋतुऽपाभिः ४.३४.७

ऋतुऽभिः १.१५.९; १०; ८४.१८; २.३७.१–३; ३.४७.३; ४.३४.२; ५३.७; ५.३२.२; ६.५२.१०; ९.६६.३; १०.२.४; ७.६; १८.५

ऋतुम् ७.१०३.९

ऋतुऽशः १.१६२.४; १०.२.५; ५५.३; ९८.११

ऋतून् १.१५.५; ४९.३; ९५.३; २.३८.४; १०.२.१; ३; ११.१; ८५.१८

ऋतनाम् ५.१२.३

ऋते १.१८.७; १४१.११; १६४.८; १९०.२; २.१२.९; १६.२; २९.४; ४.३३.११; ५.४४.२; ६.७.१; ६७.८; ७.११.१; १६.६; ८.१.१२; २.३९; २७.१७; ९.६९.६; १०.८६.१२; ९९.२; ११२.९

ऋतेऽकर्मम् १०.५५.७

ऋतेऽजाः १.११३.१२; ६.३.१; ७.२०.६

ऋतेन १.२.८; २३.५; १३३.१; १५२.१; १८५.६; २.२७.८; ३.४.५; ५.३; ३१.९; २१; ५८.२; ४.३.९–१२; २३.९[२]; ४२.४; ५.१.७; १२.३; १५.२; ६२.१; ६३.७; ६८.४; ८०.१; ६.३९.४; ६८.२; ७.३४.८; ५६.१२; ७५.१; ८.८६.५; ९.८०.१; १०.१२.१; २; ६२.२; ३; ८५.१; १०८.८; ११; १०९.१; १२३.४; १२४.५; १३९.४

ऋतैः ९.७०.१

ऋतोः २.२८.५

ऋत्विक् २.५.७

ऋत्विजः १.६०.३; ८.५८.१; ९.११४.३; १०.२.१

ऋत्विजम् १.१.१; ४४.११; ४५.७; २.५.७; ३.१०.२; ५.२२.२; २६.७; ७.१६.६; ८.४४.६; १०.७.५; २१.७

ऋत्विजा ८.३८.१

ऋत्विजा १०.७०.७

ऋत्विजाम् १०.११४.९

ऋत्वियः १.१३५.३; १४३.१; ३.२९.१०; ४१.२; ५.७५.९; ८.१९.३१; ९.७२.४

ऋत्वियम् २.१.२; ८.४०.११; १०.९१.४; ६; १०; १००.२; १७९.१

ऋत्वियऽवतः ८.८.१३

ऋत्वियऽवती ८.१२.१०; ८०.७

ऋत्वियाः १.१९०.२

ऋत्वियाय ८.६३.११

ऋत्व्ये १०.१८३.२

ऋदून्तु ७.१०४.२४

ऋदुऽपे ८.७७.११

ऋदुऽवृधा ८.७७.११

ऋदूदरः २.३३.५

ऋदूदराः ३.५४.१०

ए

एकऽआयुः १.३१.५
एकऽईषम् १०.१३५.३
एकः १.७.९; ३२.१२; ३३.४; ५२.१४; ६१.१५; ६८.१; ७१.९; ८४.७; १००.७; १४३.४; १४५.३; १५४.३; ४; १६१.९[२]; १०[३]; १६२.१९; १६४.२; १०; ४४[२]; १६५.३; १७६.२; २.१३.३[२]; ६; २९.५; ३.१.१०; ३.११; ३०.४; ५; ११; ३१.४; ४६.२; ५१.४; ५५.६; ५६.२; ४.१७.५; ९; १९; ३०.५; ३२.७; ५.३०.४; ३२.३; ९; ६२.२; ८१.१; ५; ६.१८.२; ३; २२.१; ३०.१; ३१.१; ३४.२; ३६.४; ४५.१६; २०; ५९.५; ७.१९.१; २३.५; २६.३; ४; ९८.६; १०३.६[४]; १०४.३; ८.१.२७; २.४; ३१; ६.४१; १३.९; १४.१; १५.३; ११; १६.८; १७.१५; २४.१९; २५.१६; २९.१–७; ३६.७; ३७.४; ७; ३९.१०; ५८.२[२]; ६२.२; ७७.७; ९०.५; ९६.१९; १०.५.१; ३२.५; ४८.७; ५१.१; ८१.३; ८२.३; ८४.४; ९१.३; १०४.९; ११४.४; १२१.१; ३; ७; ८; १३८.६
एकःऽएकः ३.२९.१५; ५.६१.१
एकुकम् १०.५९.९
एकऽचक्रम् १.१६४.२
एकुऽज १०.८४.३
एकुऽजम् १.१६४.१५
एकुऽधूः ८.८०.१०
एकधेनुऽभिः ७.३८.५
एकऽपदी १.१६४.४१
एकुऽपुरस्य १०.३४.२
एकऽपात् २.३१.६; ६.५०.१४; ७.३५.१३; १०.६४.४; ६५.१३; ६६.११; ११७.८
एकम् १.९३.४; ९५.३[२]; ९६.५; ११०.३; ५; ११७.१८; १३१.२; १६१.२; १६४.६; ४६; ४८; १६५.६; ३.१.६; ५४.८; ५५.१–२२; ४.७.९; १९.१; ३५.२; ३६.४; ५८.४[३]; ५.३२.११; ६२.१; [illegible].११ ८५.६; ६.९.५; १७.८; ७.१८.११; १७; ३३.१०; ८.२०.१३; ५८.२; १००.५; १०१.६; ९.९.४; २१.३; ९७.५५; १०.१४.१६; २७.१६; ४८.७; ५५.४; ५६.१[२]; ८०.२; ८२.२; ६; ८५.१५; १६; १०९.५; ११४.५; १२९.२; ३; १३८.६; १४२.५
एकम्ऽएकम् १.२०.७; ८.७०.१४
एकम्ऽएका ५.५२.१७
एकया ८.२९.८; ६०.९; ७७.४; १०.६७.४
एकुऽराट् ८.३७.३
एकऽरूपाः १०.१६९.२
एकुऽवीरः १०.१०३.१
एकऽशतम् १०.१३०.१
एकस्मिन् ७.६७.८; ८.४५.३४
एकस्य १.१६४.४४. १६५.१०; २.१३.३; ९; ६.४५.५; ९.१०.७; १०.१०.३
एकस्याः १.११६.२१
एका १.३५.६; ३.७.२; ५६.२; ७.९५.२; ८.५८.२
एकाऽएका १.१२३.८
एकादश १.१३९.११[३]
एकादुशम् १०.८५.४५
एकादुशान् ८.३९.९
एकादुशासः ८.५७.२; ९.९२.४
एकादुशैः १.३४.११; ८.३५.३
एकाम् ३.२.९; ८.७२.७; १०.५.६
एकाम्ऽइव ३.७.४
एके ८.२९.१०; १०.११४.१०; १५४.१
एकेन २.१३.११; ३.१२.६
एकेऽभ्यः १०.१५४.१
एजत् १.१६४.३०; ३.५४.८; ४.१७.१०; १९.६; १०.८८.१५
एजति ५.७८.८; ८.६.२९; १०.३७.२
एजुति १.१०.२; ५.५९.२
एजतु ५.७८.७
एजथ ८.२०.४
एजात् १०.२७.५
एजान् ६.२५.७

६३.१–५; ६६.१४; ८०.२; १०३.२; ३; १०४.२१; ८.१२.१०; २३.२२; ७२.९; ८०.७; ९.३३.४; ३९.३; ४४.३; ६१.८; ७०.६; ७१.२[२]; ६; ७२.३; ८२.१; ८५.९; ८६.७; ३१; ९२.३; ९६.१; ६; १७; २२; ९७.१; ७; १३; १०१.१६; १०.३.१; ३; १७.१; २०.४–६; २७.१३; ३१.९; ३२.७; ३४.६; १०; ३५.८; ३७.२; ६१.२६; ८५.६; १९; ८८.१५; ९४.८; १०२.४; १०७.५[२]; ११७.८[२]; १६८.१[२]

एतु १.४०.३[२]; ९१.१६; १५४.३; १८६.१; २.३.९; ३३.१; ३.३०.६; ४.३२.१८; ५.१२.६; २२.२; २६.८; ४९.५; ६.१५.१२; १९.९[२]; ५४.५; ७.४.८; ९; १८.३; ३४.१; १३; ३५.८; ३६.१; ९; ४०.१; ४३.२; ६६.१; ८४.३; १०४.१०; ८.१९.२७; २४.२९; २७.३; ३१.११; ४६.२१; ६७.१५; १००.११; ९.३१.४; १०.१३.१; १७.५; ३०.१; ५७.४; ६२.११; ८७.११; १५; १००.४; १०३.८; ११०.८; १३४.५; १४९.४; १५२.२

एते १.५४.९; ८१.९; १०५.११; १२२.१३; १३५.६; १६५.१; १२; १९१.५; २.२८.४; ४.५८.६; ५.१२.५[२]; ३०.६; ४४.४; ५९.८; ६०.५; ७.७.६; १८.१५; १९.१०; २५.५; ७५.३; १०३.९; १०४.२०; ८.१.३०; ४३.५; ९.८.१; २१.१; ४; ७; २२.१–५; ४६.३; ६२.१; २२; ६३.४; १४; ६९.९; ८७.५; ८८.६; ९७.२०; १०१.१२; १०.१०.८; २८.१२; ७१.९; ७६.८; ९४.१–३; ९५.१; १२०.३; १८१.३

एते इति १.१४४.६; ३.५४.८; ७.९९.३

एतेन १.३१.१८; १७३.१३; ५.८३.६

एतेभिः ५.५२.१०

एतेभ्यः १०.१७.३

एतो इति ५.४५.५; ८.२४.१९; ८१.४; ९५.७

एतोः २.१५.५; ३८.३

एतौ १०.२७.२०; ८५.१८

एधः १.१५८.४

एधतुम् ८.८६.३

एधते ८.७४.४; १०.६.१; ६०.४

एधते १.४१.२; २.२५.५; ८.२७.१६; ४६.५; ८४.९; १०.६३.१३

एधन्ते १०.८५.२८

एधमानऽद्विट् ६.४७.१६

एधस्य १०.८६.१८

एधि १.९१.१५; ४.१.५; ५.९.७; १०.७; १६.५; १७.५; ६.१७.१४; ७.५४.२; ५५.१; १०.५६.१; ८४.२; ६; ८५.४४; १०३.४; १७३.१; २

एन १.१७३.९; ५.२.११; ९.९६.२; १०.१०८.३

एनः १.२४.९; १२५.७; १८९.१; २.१२.१०; २८.७; ३.७.१०; ५.३.७; ६.५१.७; ८; ७४.३; ७.१८.१८; ५२.२; ५८.५; ८६.३; १०.३६.९; ३७.१२; ७९.६; १२८.४; १३२.५

एनम् १.९.२; २४.१३; ३२.३; ८०.९; १२; ९४.२; ९६.६; १२३.१; १६२.३; ७; १६३.२[२]; २.१२.५; २२.१–३; ३.२.७; ९.५; ३२.१३; ३६.४; ५९.२; ४.२.९; १७.५; २३.३; २४.१०; ३८.५; ९; ५७.३; ५.४२.३; ६.२४.१०; ३८.२; ४; ४२.२; ५६.१; ७.१.६; २८.५; २९.५; ३०.५; ३३.१४; १०३.२; ८.१.१७; १९; २.३७; २३.९; ६६.७; ८०.४; ९.३४.६; १०९.२०; १०.१४.११; १६.१[२]; २; ४; १८.११; २८.२; ३२.८; ३४.४; ४४.३; ४५.१; ८; ४८.९; ७१.५; ७३.१०; ८७.५; ८; ११; १५; ८८.११; ९५.१४; १०२.५; १३०.२; १६१.१[२]; २; ३; १६८.२

एनसः ४.१२.५; ७.२०.१; ८९.५; ८.१८.१२; ४७.८; ६७.१७; १०.६३.८

एनसा १०.१३२.४

एनस्वन्तः ७.८८.६

एनस्वन्तम् ८.१८.१२

एना १.३०.३; १०५.१९; १६४.५; १७; १८;

४३; १७१.१; २.६.२; ९.६; ३४.१४; ३.३३.४; ४.३६.७; ५.१९.३; ५३.१२; ७३.४; ६.२०.१०; ४४.१७; ७.१६.१; ७१.४; ९३.७; ८.५.३९; २१.६; ९६.८; ९.६१.११; ९७.५२; ५३; १०.१४.२; ४; २३.७; २७.२१; ३१.८; ८२.५; ८५.२७; ११२.६; १२५.८; १४४.५[२]; १४८.३

एनांसि १.२४.१४; ४.१२.४

एनाः ८.९७.१४; ९.९७.२९; १०.१९.२[४]; ८; ३०.१४; १०८.५

एनान् १.१६१.५[२]; ५.५२.६; ७.१०३.३; १०.६१.२३; ८७.१८; ९३.२; ११०.३

एनाम् ८.६.१९

एनाम् १.१६४.२६; १०.७१.४

एनी १०.१२.३; ७५.७

एनी इति १.१४४.६

एनीः ५.८५.६; १०.२०.२; ८७.७

एनीम् ५.३३.६; १०.३.२

एने इति १.१४६.२; १०.८२.१

एनोः १.१३६.१; ५; ६.६९.८; ७.१०३.४

एन्यः ५.५३.७; ८.६९.१०

एभिः १.५३.४[२]; १६६.१४; ३.५०.१; ४.३.१५; १०.३; १६.१९; १७.११; ६.१६.१६; १९.१३; २५.१; ७.१.८; ९; २८.४; ६२.२; ८.४६.२६; १०.९३.१

एभिः १.१४.१; ३.६.९; ७.३३.३[२]; १०.३४.५; ५५.७

एभ्यः १.६९.४; ६.१९.१२

एभ्यः १.१३१.५; १३२.४; १४६.४; ५; ३.५३.१६; ४.५४.५; ६.४६.९; ६१.३; ६८.४; १०.३४.८; ६४.२; १०७.८; ११४.१०

एमं १.५८.४; ४.७.९; ६.३.४

एमंऽभिः ५.५९.२

एमि ७.८९.२; १०.३४.५

एमि १.१७१.१; ३.५४.९; ७.१८.२२; ८६.३; ८.४८.१०; १००.१; १०.१३.३; १७.१०; ६६.१३; ८६.१९; १२४.२[२]; ३

एमुषम् ८.७७.१०

एरिरे १.१२८.८[२]; २.२.३

एव १.१.३; ८.८–१०; ५१.६; ६१.९; १०; १६; ६२.१२; ७६.५; ७७.५; ९५.११; ९६.९; १०८.१३; ११३.१; १२४.६; १४०.७; १६१.२; १६४.१३; १६५.१२; १७३.८; १७८.४; १९०.८; २.२.९; १२.१; १३.८; १९.७; ८; २४.४; ३०.४; ३३.१५; ३.९.३; १७.२; ३६.३; ४.५.७; १६.२०; १७.२०; १९.१; २०.६; २१.१०; २८.५; ३०.१; ३३.६; ५०.६; ८; ५१.९; ५४.५[२]; ५.२.७; ६.१०; २५.९; २७.३; ३२.१२; ३३.७; ४४.६; ७८.७; ८; ८६.६; ६.३.२; ४.१; १७.३; १३; १९.२; २१.६; २३.१०; २५.९; २९.६[२]; ३८.५; ४८.१७; ५०.१५; ५४.१; २; ७.१८.२; २३.६; २४.६; २५.६; २६.४; ५; ३१.१२; ३३.३[२]; ४१.५; ४२.६; ४३.५; ८.२.३१; ९.३; ९; १०; १०.२; २४.१६; २३; ३३.१८; ३८.९; ४०.१२; ४२.२; ६; ४७.१७; ५३.८; ५४.२; ५८.२[२]; ६०.७; ९२.२८[३]; २९; ९.६.९; ६७.३०; ६८.१०; ७९.५; ८२.५; ९०.६; ९१.६; ९६.१२; ९७.१५; २१; २७; ३६; १०९.३; १०.७.६; १०.१३; १६.९; १८.५; ९; १९.३; २०.१०; २७.५; २८.६; ७; ३०.६; ४४.४; ६; ७[२]; ४९.११; ५१.४; ६०.८; ९; ६३.१७. ६४.१६; १७; ८२.३; ८३.२; ८५.४२; ८९.१७; ९०.२; ९४.१२; ९५.१६; ९९.१२; १००.१०; १०७.५; ६; १०८.९; १०९.३; ११३.४; ११५.७; १२०.९[२]; १२४.१; १२५.५; ८; १४४.६; १४५.४; १४९.५; १५४.१–४; १६१.२; १६६.३; १७३.२

एवऽथां ८.२४.१५

एवम् १०.१५१.३

एवऽया ५.४१.१६

एवऽयाः १.१५६.१

एवयामरुत् ५.८७.१–९

एवंऽयावः १.९०.५

एवऽयावः ७.१००.२
एवयावऽभिः १०.९२.९
एवऽयावरी ६.४८.१२
एवऽयाव्नः २.३४.११
एवऽवदस्य ५.४४.१०
एवाः ५.४१.५; १३
एवान् ६.५१.२
एवारै ८.४५.३८
एवासः १.१६६.४
एवैन १.१२८.३
एवैः १.६२.८; ६८.२; ७९.२; ९५.६; १००.२; ११; १८; ११७.१४; १५८.३; १८१.६; ३.३३.५; ५४.९; ५८.४; ४.२.१२; ३३.१; ५६.१; ५.४१.५; ७.६.६; ६२.२; १०४.७; ९; ८.१८.१३; ६८.४; ९७.३; १०३.१३; १०.६.६; ८.७; ६७.११; ७३.२
एवो इति ४.१२.६; १०.१२६.८
एषऽएष्या १०.१०२.११
एषः १.५६.१; १३९.७; १६२.३; १६५.१५; १६६.१५; १६७.११; १६८.१०; १७१.२; १७३.१३; १८४.५; २.४.२; १२.५; १४.१; २; ३६.५; ३.३१.१६; ४२.८; ४८.४; ५१.९; ४.२.५; १५.९; २५.६; ३५.४; ४५.१; ५.३१.१०; ३६.४; ४२.१५; १६; ५०.५; ६१.१९; ६.४१.३; ७३.३; ७.२०.९; २४.५; ६०.२; ६३.३; ६४.५; ६५.५; ६७.७; ६८.९; १००.३; ४; १०१.३; ८.१.३२; २.३१; ३४; १६.६; २४.३०; २९.६; ६६.१५^{2}; १०३.१२; ९.३.१–१०; १५.१–६; २७.१–६; २८.१–६; ३८.१; ४–६; ४२.२; ६२.११; १३; ६६.२९; ६७.२०; ७७.१; ८४.४; ८७.४; ७; ९६.१५; ९७.४६; ४७; ५६; १०८.५; ११०.११; १०.१६.८; ७१.५; ८६.२१; १३९.२; १४६.४^{2}; १६०.४; १६५.४; १६८.४
एषस्य २.३४.११; ७.४०.५; ८.२०.३
एषा १.४८.७; ८८.६; ११३.७; १२४.३; ६; ४.३.९; ५.८०.२–६; ६.६५.१; ७.७५.४; ७६.७; ८०.२; ९५.१; ८.२७.१८; ९.८७.८; १०.११.८; १४.२; १८.१०; ३१.६; ३४.२; ८५.२१; २९; १०९.३
एषाम् १.१६५.१३; १०.८५.२
एषाम् १.२४.७; ३७.३; ९; १३; १५; ३८.८; १२; ४१.३; ४८.४; ५४.९; ६१.१५; ६४.४; ६८.१; ८४.१६; ८५.३; ८७.३; ९४.१२; ९७.३; १२७.७; १३४.६; १५२.२; १६४.४४; १६५.१०; १६७.२; ७; १६८.३; १६९.६; १८५.८; १८६.९^{2}; २.१५.८; २७.८; ३.१३.३; ३१.३; ९; १०; ३९.४^{2}; ५४.५; ४.१.१४; २.४; २७.१; ३३.९; ४७.२; ५.१०.३; १६.४; २९.१; ३२.४; ४२.९; ५१.६; ५२.१५; ५३.१; ११; ५६.५; ५८.१; ७; ५९.२; ७; ६०.५; ६१.३; १४; ६६.३; ८७.२; ६.२५.३; ५; ५१.२; ८; ६६.२; ७५.१३; ७.२.२; ७.४; १८.११; १३; २१.४; ३३.८; ३४.१९; ३९.२; ५; ५६.२; ६०.१०; ८३.४; ७; १०३.५^{2}; ६; ८.७.१५; २८; १८.१; २; २०.११; १४^{2}; २८.४; ५; ३४.३; ३९.२; ४१.७; ४५.२; ४६.१८; ६९.१८; ८३.७; ९३.३३; ९.५२.४; ६४.२७; ७३.३; ७; ९१.४; १०.१८.४; ५; २७.२३; २८.३; ३४.५; ८; ४३.४; ५६.४^{2}; ६१.२३; ७१.१^{2}; २; १०; ७४.२; ३; ७५.२; ७७.१; ८७.४; ८८.८; ९३.५; ९; १३; १४; ९४.६; १०७.१; १२८.६; १२९.५; १३१.२; १७४.५; १९१.३
एषि १.१२३.१०; ८.९१.२; ९.५०.२; १०.८.४; ८६.२१
एषि १.५०.५; ७; ५२.१२; ५३.७; १६२.२१; ३.६१.६; ५.१.९; ७.३७.४; ८.९३.१; ९.८२.२; ८३.१; ९६.२३; ९७.१४^{2}; ५५; १०६.१४; १०.१.४; १४२.४
एषु १.९.३; ३.२.१०; ४१.४; ५.२३.४; ७.१.२२; ३४.१८

एषु १.६१.१६; ७७.५; ३.३०.१६; ४.३२.१२; ५.७.९; ७९.६; ६.६६.६; ८.६८.१८; १०.२७.६; ९३.१०; १४७.३
एषै ५.४१.५; ७; ८; ६६.३; ८६.४; १०.४८.९
एषे १.१८०.४
एषो इति १.४६.१
एष्टा १.१८४.२
एहिंऽमायासः १.३.९

ऐ

ऐक्षैताम् १०.१२१.६
ऐच्छः १०.१०८.५
ऐच्छाम १०.५१.३; ५३.१
ऐजन् १.६३.१
ऐट्ट ३.४८.३
ऐळ १०.९५.१८
ऐत् १०.११३.१
ऐत् ५.३०.९; १०.६१.८; ७२.८; ९; ९०.४
ऐत १०.१८.२
ऐत ४.३५.३
ऐतन १.११०.२; ३
ऐतन १.१६१.६
ऐतम् १०.१३.२
ऐधाऽइव १.१६६.१
ऐनोः ४.१६.७
ऐनोत् १.६६.५
ऐर्यैः ५.२.८
ऐरत् ४.४.६
ऐरत् २.१५.८; १९.६; ३.३१.१५; ५५.२०; ४.५६.३
ऐरत १०.७१.१
ऐरत ७.२३.१; ८.२०.४
ऐरतम् १.११८.६
ऐरम् ४.२६.३
ऐरयः २.१७.३; ८.८९.७
ऐरयत् २.१७.१; ८.६.१३; ७४.३
ऐरयत् १.७.३; ५१.११; २.१९.३; २०.७; ६.५६.३; ८.७६.३
ऐरयत ८.१९.२४
ऐरयतम् १.११२.५
ऐरयतम् १.११७.२२; २४; ६.७२.३; ७.८२.३; १०.३९.९
ऐरयन्त १०.१६९.३
ऐरयम् ४.४२.३
ऐरयेथाम् १.१५७.५
ऐरयेथाम् ६.६९.८
ऐषन्त १.१२६.५

ओ

ओ इति १.१०४.२; ११३.११; १३८.४; १३९.७; १६५.१४; १७७.५; १८२.१; २.३४.१५; ३.३३.९; ७.४०.१; ५९.५; ८.२.१९; ७.३३; २२.१; १०.१०.१; ११७.५; १७९.२
ओकः १.६६.२; १०४.५; १७३.११; २.१९.१; ३.५८.६; ४.१६.१५; ५.३०.१; ७६.४; ६.४१.१; ७.४.८; २५.४; ३२.४; ५६.२४; ८.३३.२; १०.११२.४; ११७.४
ओकसः १.३०.९; ७.५.६; ८.६९.१८
ओकसि ४.५०.८; ५.३३.४
ओकांसि १.४०.५; २.३८.५
ओकिऽवांसा ६.५९.३
ओक्यः ९.८६.४५
ओक्यम् १.१३२.५; ८.४९.३; ७२.१४; १०.४४.९
ओक्या ८.२५.१७
ओक्ये १.९१.१३; ३.४२.८
ओगणासः १०.८९.१५
ओचिषे ८.८२.२
ओजः १.३३.१२; ३९.१०; १०३.३; १२१.१०; १६०.५; १६५.१०; २.१७.२; २९.२; ३६.५; ३.२६.६; ३२.३; ९; ३६.४; ४७.३; ५३.१९; ६२.५; ४.७.१०; १७.३; १९.४; ४१.४; ५.३१.७; १३; ३२.१०; ३३.६; ५७.६; ६.१८.१५; १९.६; २६.७; ३६.२; ४६.७; ४७.२७; ३०; ७.५६.७; ८२.२; ६; ९१.४; ८.६.५; ४०.६; ५०.८; ९६.३; १७; ९८.१०; ९.९७.४१; १०.८.९;

४४.४; ५४.१; ८३.१; ४; ८४.२; ९५.११; ११६.६; १७०.३; १८०.३
ओजःऽदाः ८.३.२४
ओजःऽदातमः ८.९२.१७
ओजःऽभिः ७.५६.६
ओजसः १.५२.१२; १०२.८; ५.३२.९; ८.१२.२४; १०.७३.१०; १५३.२
ओजसा १.७.८; ९.१; ११.८; १९.४; ८; ३९.८; ५३.७; ५५.२; ५; ६; ५६.६; ८०.१; २; ११; ८५.४; १०; १०२.६; १२७.३; ४[२]; १३०.४; ७[२]; ९; १३२.५; १७५.४; १८७.१; १८८.४; २.१७.५; २२.२–४; २४.२; ४; २५.३; ४; ३.४५.५; ५१.१०; ४.३२.३; ५.५२.९; १४; ५५.२; ५६.४; ५९.७; ८१.३; ८४.३; ७.५८.२; ८२.३; ८.४.५; ६.१; १५; २६; ४१; ७.८; १२.४; २७; १७.९; ३२.१४; ३३.७; ८; ३६.३; ४०.५; १०; ५१.८; ६२.२; ८; ७६.१; ९; १०; ८८.५; ९२.६; ९३.२३; ९७.११; १४; ९९.३; ९.२.७; ५.३; ४; १५.४; २९.१; ३४.१; ३५.२; ३९.३; ५३.२; ६४.१८; ६५.१०; १४; १०१.५; १०६.७; १०८.६; १०.४९.७; ६५.२; ४; ७; ७५.१; ९६.१०; ९९.६; १०३.६; ११३.२; ६; १५३.३–५
ओजसे १.५७.५; ८.१२.२२; २३; ६१.२; ७५.१०
ओजस्वन्तम् ८.७६.५
ओजांसि १.८०.१५
ओजायमानः १.१४०.६
ओजायमानम् २.१२.११; ३.३२.११
ओजिष्ठ १.१२९.१०
ओजिष्ठः ६.३३.१; ८.९३.८; ९.६६.१६; ६७.१; १०१.९; १०.७३.१
ओजिष्ठम् ३.२१.५; ४.४१.४; ५.१०.१; ६.१९.६; ४६.५; ८.४.१०; ३४.१६; ९७.१०
ओजिष्ठया १.१६९.४
ओजिष्ठेन १.३३.११
ओजिष्ठेभिः ४.२०.१
ओजीयः २.३३.१०; १०.१२०.४
ओजीयान् ६.२०.३; ९.६६.१७
ओज्मानम् ६.४७.२७
ओणिम् १.६१.१४
ओण्योः ९.१६.१; ६५.११; १०१.१४
ओतवे १०.१३०.२
ओतवै १.१६४.५
ओतुम् ६.९.२; ३
ओदती १.४८.६
ओदतीनाम् ८.६९.२
ओदनम् ८.६९.१४; ७७.६; १०
ओपशः १०.८५.८
ओपशम् ८.१४.५; ९.७१.१
ओपशम्ऽइव १.१७३.६
ओमना ७.६९.४
ओमन्ऽवन्तम् १०.३९.९
ओमऽभिः ५.४३.१३
ओमात्राम् १०.५०.५
ओमानम् १.३४.६; ११८.७; ६.५०.७; ७.६८.५
ओमासः १.३.७
ओम्याऽवतीम् १.११२.२०
ओम्याऽवन्तम् १.११२.७
ओष १०.८७.१२; ११८.८
ओषः १.१७५.३
ओषतम् ७.१०४.१
ओषतात् ४.४.४
ओषति १.१३०.८[२]; ८.१२.९
ओषधयः १०.१७.१४; ९७.१७; २२
ओषधिः १.१६६.५
ओषधिम् १०.८५.३; १४५.१
ओषधीः १.९०.६; ९१.२२; ९८.२; १०३.५; १६३.७; ३.३४.१०; ५१.५; ५४.२१; ५५.२२; ४.३३.७; ५७.३; ५.४१.८; ११; ४२.१६; ४३.१३; ६२.३; ८३.४; ५; १०; ६.२१.९; ३९.५; ७.४.५; ३४.२३; २५; ३५.५; ५६.२५; १०१.५; ८.२७.२; ४३.७; ९; ५९.२; १०.५८.७; ६५.११;

औ

क

कलश १०.३२.९

कलशाः ३.३२.१५; ६.६९.६

कलशम् १.११७.१२; ४.२७.५; ९.६२.१९; ७४.८; ८६.११; ९७.४; ३३; १०६.७

कलशस्य १०.१६७.१

कलशा ६.६९.२

कलशाः ९.६५.१४

कलशान् ९.६०.३; ७५.३; ८१.२; ८६.१९; ८८.६; ९२.६; ९६.२२; १०६.१२; १०.१६७.३

कलशानाम् ४.३२.१९

कलशे ६.४७.६; ९.६३.३; १३; ६७.१५; ७२.१; ८५.५; ७; ८६.१६; २२; ९३.२; ९६.९; १४; २४; ९७.२२

कलशेषु ९.८.६; १२.५; १७.४; १८.७; ६७.१४; ६८.९; ८४.४; ८६.६; ९; ३५; ४७; ९६.२३

कलाम् ८.४७.१७

कलिम् १.११२.१५

कलेः १०.३९.८

कल्पय १०.१८.५

कल्पयतु १०.१८४.१

कल्पयन्तः ८.५८.१; १०.११४.६

कल्पयन्ति १०.११४.५

कल्पयस्व १०.१०.१२; १५.१४

कल्पयाति १०.२.४

कल्पयाति १०.२.३; ५२.४

कल्पयावहै १०.८६.२१

कल्पस्व १.१७०.२

कल्पेषु ९.९.७

कल्मलीकिनम् २.३३.८

कल्याण १.३१.९

कल्याणीः ३.५३.६

कल्याणीभिः १०.३०.५

कल्याण्यः ४.५८.८

कवऽअरिभ्यः १०.१०७.३

कवत्नवे ७.३२.९

कवन्धम् ५.८५.३; ८.७.१०; ९.७४.७

कवन्धिनः ५.५४.८

कवयः ५.५७.८; ५८.८; ७.५९.११

कवयः १.३१.१; १०३.१; १४६.४; १५९.४; १६३.१२; १६४.५; २.२४.७; ३.८.४; ३४.७; ५१.७; ५४.१०; ४.२.१२; ३६.७; ५.४५.४; ५२.१३; ७७.१; ७.५३.१; ७६.४; ८६.३; ८७.३; ९.७२.६; ७३.७; ९७.२९; ५७; १०.५.२; ६; ८८.१३; १०१.४; ११४.२; ५; ६; १२४.९; १२९.४; १५४.५; १७७.१; २

कवयः १.१८५.१; ३.५४.१७; ५.५८.३; ६.४९.६; ११; १०.५३.१०; ८८.१८

कवये ४.२.२०; ३.१६; २५.२; ५.१.१२; १५.१; ६.१५.११; २०.४; १०.४९.३

कवषम् ७.१८.१२

कवऽसखः ५.३४.३

कविः १.११.४; १२.६; ३१.२; ७१.१०; ७६.५; ७९.५; ९१.१४; ९५.४; ८; १४९.३; १५१.७; १६४.१६; १७४.७; १८८.१; २.२३.१७; ३.२.७; ३.४; ११; २३.१; २९.१२; ५४.६; ४.१५.३; १६.३; ११; २६.१; ५३.२; ५.१.६; ५.२; ११.३; ३१.१०; ४४.७; ४५.९; ८१.२; ६.७.७; ३२.३; ४९.४; ७.४.४; ९.३; १५.२; १८.२; ८; ८.८.११; ३९.१; ९; ४१.५; ४४.१२; २१; ६०.३; ५; ७५.४; १०२.१; ९.७.४; ९.१; १२.४; ८; १४.१; १८.२; २०.१; २५.३; २७.१; ४४.२; ४७.४; ५९.३; ६२.१४; ३०; ६४.३०; ६८.५; ७१.७; ७४.२; ७८.२; ८२.२; ८४.५; ८५.९; ८६.२०; २६; ९२.२; ९४.३; ९६.१७[२]; ९७.२; १०७.७; १८; १०९.१३; १०.२०.४; ६४.४; १६; ८७.२१; ९१.३; ९२.१२; १००.६; ११०.१; १२४.७

कविऽक्रतुः १.१.५; ६.१६.२३; ९.९.१; २५.५; ६२.१३

कविऽक्रतुम् ३.२.४; २७.१२; ५.११.४; ८.४४.७

कविक्रतो इति कविऽक्रतो ३.१४.७

कविऽच्छदा ३.१२.३
कविऽतमः ३.१४.१; ७.९.१
कविऽतमम् ५.४२.३; ६.१८.१४
कविऽतमस्य ५.८५.६
कविऽतरः ७.८६.७
कविऽत्वना ८.४०.३
कविऽत्वा १०.१२४.७
कविना ६.४९.१०; ९.३७.६
कविऽप्रशस्तः ५.१.८
कविऽभिः १.७६.५; ३.१.५; ८.९; ३१.१६; ६.३२.३; ९.७४.९; १०८.१२
कविम् १.१२.७; ११४.४; ११६.१४; १२८.८; २.२३.१; ३.२.१०; १९.१; २९.५; ४.२.१२; १६.९; ५.४.३; १४.५; ६.१.८; ७.१; १५.७; २६.३; ४९.४; ७.६.२; ८.४४.२६; १०२.५; १७; ९.६३.२०; ७२.६; ८६.२५; १०२.६; १०.८८.१४; ९९.९
कविम्ऽइव ८.८४.२
कविऽयन् ९.९४.१
कविऽयमानः १.१६४.१८
कविऽवृधः ८.६३.४
कविऽशस्तः १.१५२.२; ३.२१.४; २९.७
कविऽशस्ताः ६.५०.१४; १०.१४.४
कवी इति ८.८.२
कवी इति १.२.९; १३.८; १४२.८; १८८.७; ८.८.२३; ४०.३; १०.४०.६
कवी इति १.११७.२३; ८.८.५
कवीन् १.१६४.६; ३.३८.१
कवीनाम् २.२३.१; ३.१.२; ५.१; ३८.२; ५६.५; ५.४२.३; ६.१८.१४; ३२.२; ९.६४.१०; ६७.१३; ९६.६; १८; ९७.३२; १०.२२.१०; ११२.९
कवे १.१३.२; १३०.९; १७५.४; २.१.१३; ६.७; ३.२८.४; ४२.६; ५२.६; ५.२१.३; २६.३; ६.१६.३०; ५३.५; ७; ८.४४.३०; ४५.१४; १०२.१६; ९.२५.६; ५०.४; ६३.२७; ६४.२४; ६६.१; १०; ८६.११; २९; १००.५; १०.१४०.१
कवेः २.२८.१; ६.३९.१; ९.१०.८; १०.५.३
कव्यता १.९६.२
कव्यैः ९.९१.२; १०.१४.३; १५.९
कशःऽजुवम् १.११२.१४
कशऽप्लकौ ८.३३.१९
कशया १.१५७.४; १६२.१७; १६८.४; ५.८३.३
कशा १.२२.३; ८.३३.११
कशाः १.३७.३
कशाऽवती ८.६८.१८
कशाऽवन्ता ८.२५.२४
कशीकाऽइव १.१२६.६
कशुः ८.५.३७
कश्यप ९.११४.२
कस्मिन् १.७५.३; ४.१६.१७; ५.७४.२; १०.२२.१
कस्मै १.८४.१८; १२०.८; ५.५३.२; १२; १०.१२१.१–९
कस्य १.२४.१; ३९.१^{२}; ४२.४; १६५.२; १६९.५; ४.३.१३; २३.१; २५.३; ४३.१; ५.३८.४; ७०.४; ७४.३; ६.९.२; ७.१४.८; ८.६४.८; ८४.५; ७; ९३.२०; ९.२९.५; ७९.२; १०.४०.३^{२}; ६१.२१; १२९.१
का १.७६.१^{२}; ७७.१; १२०.१; २.२४.५; ४२.१; ३.५४.५; ४.५.१३; २०.९; २१.९; २४.१; ४३.४; ७.२९.३; ८.५८.१; १०.१०८.१^{२}; ३; १३०.३
काः ४.२३.३; ७.६०.९
काकम्बीरम् ६.४८.१७
काकुत् ६.४१.२
काकुदः १.८.७
काकुदम् ८.६९.१२
काचित्ऽकरम् १०.८६.१३
काटे १.१०६.६
काणुका ८.७७.४
काणे १०.१५५.१
काण्वम् ८.२.४०

काण्वस्य ८.१.८; ४.२०; ७.१९; ९.३; ९; १०.२
काण्वायनाः ८.५५.४
कानि १.१०५.७; ८.१०२.२०[२]
कानिषः ३.२८.५
कानीतस्य ८.४६.२४
कानीते ८.४६.२१
कार्पया १०.४०.३
काम् ७.८.३
कामः १.१७९.४; २.३८.६; ३.३०.१९; ५४.२; ४.४३.७; ४४.७; ५.४२.१५; ६१.१८; ७.२०.९; ९७.४; ८.७८.९; ९.९७.४६; १०.१०.७; १२९.४
कामऽकातयः ८.९२.१४
कामप्रेणऽइव १.१५८.२
कामम् १.१६.९; ३०.१५; ५३.३; ५४.९; ५७.५; ८५.११; १४३.६; १७८.१; २.२०.४; ३.१४.५; ३०.२०; ४९.१; ५०.१; ४; ४.२३.५; ५.३२.१२; ७४.५; ६.५.७; ४५.२१; ७.३२.२; ३९.६; ६२.३; ८.२.३९; १९.१८; २४.६; ६४.६; ७९.५; ९९.४; ९.८.१; १०.२९.५; ३४.६; ४२.६; ४३.२; ५४.५; ६१.६; ६६.१४; ९६.७; १०६.११
कामऽमूता १०.१०.११
कामयते ६.७५.६
कामयन्ते ५.४४.१४; १५
कामयाध्वे २.१४.८
कामयासे १०.१२४.५
कामये १०.१२५.५
कामस्य १.८६.८; ९.११३.११
कामाः ३.५५.३; ४.१६.१५; ९.११३.१०; ११; १०.२५.२; ४०.१२; ६४.२; ११६.८
कामान् १.८१.८; ५.४२.१०; ८.९८.७
कामाय ८.४३.१८; १०.९६.७; ९७.१८
कामासः ८.२१.६
कामिनः ५.५३.१६; ६.१६.८; ७.५९.३
कामिनम् ५.६१.७
कामी २.१४.१
कामे ३.४८.२; १०.१२८.२
कामेन ६.४९.८; ५८.३; ४; ७.१६.१०
काम्यः १०.२१.५
काम्यम् १.१८.६; २.२२.३; ३८.११; ४१.१४; ३.५८.१; ५.१९.४; ८.५०.१; ६६.६; ९.७२.२; ८५.४; ९७.२१; ९८.६; १००.१; १०.७६.६
काम्या १.६.२; ८.१०; ५.६१.१६; १०.२१.६
काम्याः ३.३१.१७
काम्यानि १०.९५.१०
काम्यैः १.६.८
कार्यमानः ३.९.२
कारः १०.५३.११
कारम् १.११२.१; १३१.५; ४.१.१४; ५.२९.८; ९.१४.१
कारवः १.११.६; २.४३.१; ६.४५.३३; ४६.१; ७.७२.४; ८२.४; ८.३.१८; ४६.३; ५४.१; ९२.१९; ३३; ९४.३; ९.१०.६; १७.६; २९.२; ९२.५; १०.६१.१२; ९२.७
कारवः ३.६.१
कारवे १.३१.९; ५३.६; २.२.९; ३४.७; ३.३३.९; १०.६१.२३
काराधुनीऽइव १.१८०.८
कारिणः ३.५४.१४; ८.२१.१२; ९.१६.५
कारिणम् ८.२.२९; ६६.१
कारिणाम्ऽइव ९.१०.२
कारिणे ९.९७.३८
कारिषत् ६.४८.१५
कारुः १.८३.६; १६५.१४; ७.६८.९; ९.११२.३; १०.७५.१
कारुऽधायः ६.२१.८
कारुऽधायाः ३.३२.१०; ६.२४.२; ४४.१२; १५
कारुम् १.३१.८; १०२.९
कारू इति ७.२.७; १०.११०.७
कारून् ४.१६.३; ५.३३.७
कारे १.१४१.१०; ३.४९.३; ८.२१.१२
कारो इति ३.३३.८; १०

कृणुतम् १.९३.१२; ८.७३.७
कृणुतम् १.१८२.३; २.३०.६; १०.३६.६; ३९.२
कृणुतात् २.३०.५
कृणुताम् २.५.७
कृणुते २.२५.१–५; ४.१७.१०; ५.६१.७; ८३.३; १०.२७.२४; ११७.२
कृणुते १.५५.८; १०; ११३.१५; ११५.५; ३.३०.१२; ४.७.११; १७.१०; २४.६; २५.६; ५३.३; ५.२.९; ८३.३; ८.४.६; ६२.६; ९.७१.१; २; ८; ७४.७; ७६.१; ८८.५; ९५.१; ९७.९; १०३.२; १०.४०.२; ४२.४; १०७.७; ११७.३; १६५.३
कृणुथ ८.६७.१७
कृणुथ ३.५३.१०; ६.२८.६[2]; ८.२७.१८
कृणुथः १०.३९.११; १४३.१
कृणुथः १.१८२.३
कृणुध्वम् ७.३२.८; ९
कृणुध्वम् १.७७.२; १२२.४; १८६.१०; ४.३.१; ५.४१.६; ६.४९.६; ७.३.१; ३१.१०; ३४.९; ३६.८; ३९.३; ५३.२; ८.७२.१; १०.६.५; ३४.१४; ६४.७; ७४.५; १०१.२[3]; ७; ८[2]
कृणुषे १.१२३.१०; ११; ६.६४.२
कृणुष्व १.१०.७; ४.४.१; ८.६४.१
कृणुष्व २.२.६; २६.२[2]; ४.४.५; ५.२८.३; ७.२५.४; ८.१९.२०; १०.६.६; १०.१४; ८५.२०; १४२.७
कृणुहि १.१८.१; १६५.९; ४.२.२०; ६.१७.३; २५.३; ४४.१८; ८.४८.६
कृणुहि १.१३.२; ३१.८; ३.६.६; ३०.६; ३१.२०; ४७.२; ४.४.१४; २२.९; ५.४२.९; ४३.५; ६.४४.९; ४८.४; ५३.१०; ७.१७.३; २५.२; ८.६१.१६; ९.११.५; १४.५; १०.५१.५; ११०.२; १३१.२
कृणोत ३.२९.९
कृणोत १.१६२.१८; ७.३४.१२; ८.३२.१७; १०.१२८.५
कृणोतन ८.१८.१८
कृणोतन १.१३.१२; १६१.२; ४.१५.१०; १०.१०१.५
कृणोति १.५५.५; ७७.१; ४.२०.९; २४.६; ५०.९; ६.४७.१५; ६०.१०; ६४.१; ७.१८.१८; १०२.२; ८.३२.११; १०.८७.८. ९७.२२; १६५.४
कृणोति १.१८.८; ४८.८; ९२.६; १०५.१५; १७३.११; ४.१७.१३; ५.७.४; ३१.१; ७५.४; ६.७५.२; ५; ७.८१.१; ९.३.५; ९५.२; १०.१७.१; ३४.८; ४८.१०; ११७.७; १६०.३
कृणोतु १.८४.३; १०२.९; १६२.२२; ४.३९.३; ६.४७.१२; ७५.१८; ८.४५.९; ९७.१३; १०.१६.६; ३५.२; ४२.११; ४३.११; ४४.११; १३१.६
कृणोमि १.१६२.१९; ४.४२.५
कृणोमि १.११६.१२; ३.३१.१९; ७.२२.७; ९९.७; १००.७; १०.३४.१२; १२५.५; ६
कृणोषि १.३१.७; ७४.४; ५.३.२; ६.१३.५; ४५.६; ७.८१.४; ९०.२; ८.२१.१४; ६२.५
कृणोषि ४.३२.२
कृण्महे ७.१६.४; १०.८४.४
कृण्वत १.७२.५; १००.७; ४.२४.३
कृण्वतः ८.३६.७; ३७.७; १०३.३
कृण्वती १.९२.४; ५.८०.२
कृण्वते २.३०.१; ८.७२.१५
कृण्वते १.१४०.७; १६१.५; ६.७५.७; ९.१०१.८
कृण्वन् १.६.३; ५५.६; ७०.४; १०५.१७; ४.१४.२; ७.१०१.१; ८.१४.८; ९६.२१; ९.६४.८; ७८.५; ८४.२; ८६.२६; ९०.४; ९६.१; ३; २२; ९७.१०; १४; १६; १०.८.२; १२.१; १०२.८; १११.३; १६८.१
कृण्वन्तः १.८८.४; ११७.२५; ७.१.१७; ३७.४; १०३.८; ९.६२.२; ३; ६३.५
कृण्वन्तम् २.२८.७; ५.२८.२; ८.३२.१०

कृण्वन्ति १.३८.७; ९; ४७.२; १२३.६; ३.५३.१४; ७.३३.७; ९.३१.१; ६४.२३
कृण्वन्तु ३.३७.२
कृण्वन्तु १.१६२.१०; १७०.४; ३.८.८; १०.१३७.६
कृण्वानः ३.५३.८; ४.३८.६; ५.४.६; ८.४३.७; ९.१४.५; ८६.२६; १०७.२६; १०.७३.७; ११३.१
कृण्वानाः ३.५८.६; ५.३.८; १०.१०९.६; १२२.७; १२४.७
कृण्वानासः १.७२.९; ३.३१.९
कृण्वाने १०.६१.६
कृण्वीत ४.२१.५; ८.२३.१९
कृण्वे १.१३८.२
कृण्वे ७.३६.२
कृण्वैते इति ६.२५.४
कृत ६.५८.३; ९.६९.५; १०.९७.२
कृतः १.५४.३; १०५.१६; १४१.८; ६.४९.८; ७.६२.१; ८.९३.८; ९.३.२; १०.९०.१२; १७६.४
कृतद्वसू इति कृतत्ऽवसू ८.३१.९
कृतऽध्वजः ७.८३.२
कृतऽब्रह्मा २.२५.१; ६.२०.३; ७.७०.६
कृतम् १.२४.९; ३४.८; ८५.६; ११२.२४; ११७.८; १३२.१²; २.२२.४; ३.७.१०; २९.१; ४.१०.७; ५.६०.१; ६४.६; ७३.४; ६.१८.१३; ५१.८; ५८.४; ६०.४; ७४.३; ७.८४.३²; ८.४.३; ७; ८.१३; १७; ९.५; १९.१०; ४५.३२; ५७.३; ९.७१.६; ९७.५८; १०.४०.१३; ४२.९; ४३.५; १०२.२; १३५.६
कृतम् १.१७.७; १८२.४; ६.५९.८; ७.२.७; ६७.५; ८.१८.१६; १०.२४.६; ३९.२; १४३.५
कृतस्य ७.११.४
कृता १.२८.२; ३.१.२०; ३०.२; ६.६१.१३; ८.१०.३; ७७.९; १०१.१३; १०.९७.५
कृताः ३.३५.७; १०.९०.१५
कृताःऽइव २.३५.५

कृतात् १०.६३.८
कृतान् १.१६१.४; १०.५३.६
कृतानि १.२४.१४; २५.११; १००.९; ११७.४; १२८.७; २.११.६; १२.४; २१.३; ३.३८.९; ५.३०.३; ४२.६; ७.६.१; १८.१४; ६१.६; ९८.५; ८.३२.१; ६३.६; ९.४७.२; १०.३४.६; ११२.८
कृतिः १.१६८.३
कृते ५.१७.१; ७.५७.५; १०.९६.९; १०१.३
कृतेन १०.४८.३
कृतेभिः ८.१६.६; १०.१११.१
कृत्तिः ८.९०.६
कृत्नवे २.१३.१०
कृत्नुः १.९२.१०; ८.७९.१
कृत्नुम् ८.१६.३
कृत्नो इति ६.१८.१५
कृत्या १०.८५.२८; २९
कृत्रिमा १.५५.६; ८.६७.२०
कृत्रिमाणि २.१५.८; ७.२१.३
कृत्वः ३.१८.४; ५४.१
कृत्वने ८.२४.२५; १०.१४४.३
कृत्वऽसु ९.६५.२३
कृत्वी १.१६१.३; १०.१५.१२; १७.२; १०९.७; १५९.४; १७४.४
कृत्व्यः ६.२.८; ९.७६.१; ७७.५; ८४.५; १०१.२
कृत्व्यम् १०.४९.७; १४४.२
कृत्व्याःऽइव ९.४६.१
कृत्व्यान् १.१२१.७
कृत्व्यानाम् ८.२५.२३
कृत्व्ये १.५४.६; ८.५.२६; ८.२१; ५०.९
कृध १०.९७.९
कृधः १.११२.८; ५.७४.५
कृधः १०.३९.८
कृधि १.१०.११; ३६.१४; २.९.५²; १७.७; ८; ३.१५.३; १८.५; ४.१२.४; ६.४७.१०; ५१.१३; ७.१६.६; ८.२६.२५; ५३.६; ६७.१२; ९६.८; ९७.८; ९.२३.३;

६१.२८; ८४.१; ९७.२७; १०४.६; १०.४२.७; ९३.९
कृधि १.१४.७; ४२.६; ५५.७; ९४.९; १०२.४; १०६.५; ११४.२; १२७.११; १३८.२[2]; २.२.७; २३.७; ३०.१०; ४१.१६; ३.१.१९; ४.२; १६.५; ४.१.३[2]; ३१.१५; ५.१८.५; ५१.१४; ६.५.६; २३.७; ४६.६; ७.२५.५; २७.५; ३२.२५; ४२.५; ७७.४; ८.१९.१२; ३२.९; ३६.६; ५३.४; ६०.१४; ६१.१३; ६८.१२; ७५.२; ११; ८०.४–६; ९०.४; ९१.६; ९३.१०; ९.४.१–१०; ६४.१४; ७८.५; ११३.८–११; १०.२२.१५; ३८.२; ८५.४५; ९६.११; ११२.१०; १३३.४; १३४.२; १४२.१; १४७.५; १५१.२;३; १६६.१; १६७.१; १७१.४; १८६.२
कृधुऽकर्णीः १०.२७.५
कृधुना ४.५.१४
कृध्वम् ७.३४.१५
कृन्तत् ८.४५.३०
कृन्तत्रम् १०.८६.२०
कृन्तत्रात् १०.२७.२३
कृपण्न्त १०.७४.३
कृपणे १०.९९.९
कृपण्यति ८.३९.४
कृपते १.११३.१०
कृपऽनीळम् १०.२०.३
कृपन्त ९.९९.४
कृपम् ८.३.१२
कृपमाणम् १.११६.१४; ११९.८
कृपऽयतः ८.४६.१६
कृपयन् १०.९८.७
कृपा १.१२७.१; १२८.२; ६.२.६; १५.५; ७.३.९; ८.२३.५; ८; ९.६४.२८
कृपीटम् १०.२८.८
कृपे ८.४.२
कृशनऽवतः १.१२६.४
कृशनिनः ७.१८.२३
कृशनेभिः १०.६८.११
कृशनैः १.३५.४
कृशम् ६.२८.६; ८.७५.८; १०.४०.८
कृशस्य २.१२.६; ८.५९.३; १०.३९.३
कृशानुः ४.२७.३
कृशानुम् १.११२.२१; १०.६४.८
कृशानोः १.१५५.२; ९.७७.२
कृशाय १०.११७.३
कृशे ८.५४.२
कृषतु ४.५७.४
कृषन् १०.११७.७
कृषन्तु ४.५७.८
कृषस्व १०.३४.१३
कृषिम् १०.३४.१३
कृषे ८.३.२०; ३२.३
कृषे १०.४९.७; ५०.५; ६
कृष्टयः १.४.६; ३६.१९; ५२.११; ३.४९.१; ४.३०.२; ५.१९.३; ७.३१.९; ८.५.३८; ६.४; ७४.१०; ७५.१०; १०३.३; ९.६९.७; ८६.३७; १०.५०.५; ६०.४; ११९.६
कृष्टिऽओजसा ७.८२.९
कृष्टिऽप्राः ४.३८.९
कृष्टिऽभिः १.१००.१०
कृष्टिषु १.७४.२; १०२.७; २.२.१०; ३.५३.१६; ६.४६.७; ८.९२.१८
कृष्टिहाऽइव ९.७१.२
कृष्टीः १.७.८; १६०.५; १८९.३; ३.४३.७; ५९.१; ४.१७.६; ७; २१.२; ३८.१०; ६.१८.३; ३१.१; ७.१९.१; ८५.३; ८.२४.१९; ६२.२; १०.१७८.३
कृष्टीनाम् १.५९.५; १७७.१; ४.१७.५; ५.१.६; ६.१८.२; ४५.१६; ७.५.५; ६.१; २६.५; ८.१३.९; ३२.१९; ६८.७
कृष्टेः ४.४२.१; २
कृष्णऽअध्वा २.४.६; ६.१०.४
कृष्णाः ८.८५.३
कृष्णः १.७९.२; ४.१७.१४; ८.९६.१३; १०.१६.६; २०.९
कृष्णऽगर्भाः १.१०१.१

कृष्णऽजंहसः १.१४१.७
कृष्णऽपविः ७.८.२
कृष्णऽप्रुतौ १.१४०.३
कृष्णम् १.५८.४; ७३.७; ९२.५; ११५.५; १४०.५; १६४.४७; ३.५५.११; ४.७.९; ६.९.१; ७.३.२; ८.९६.१४; १०.१२७.७
कृष्णया ८.७३.१८
कृष्णयामम् ६.६.१
कृष्णऽयोनीः २.२०.७
कृष्णऽवर्तनिम् ८.२३.१९
कृष्णऽव्यथिः २.४.७
कृष्णऽसीतासः १.१४०.४
कृष्णस्य ८.८५.४
कृष्णा १.३५.४; ११३.२; ४.३.९; १६.१३; ६.६०.१०; ८.४३.६; ९.६६.२४; १०.२१.३; ६१.४; ८९.२
कृष्णाः १०.९४.५
कृष्णाः ६.४७.२१
कृष्णात् १.१२३.१; ९
कृष्णान् ३.३१.२१; ८.४१.१०
कृष्णाम् १.११३.१४; १३०.८; ९.४१.१; १०.३.२
कृष्णाय १०.३१.११
कृष्णासः १.१४१.८
कृष्णासु १.६२.९; ३.१५.३; ८.९३.१३
कृष्णियाय १.११६.२३; ११७.७
कृष्णीः ७.७१.१
कृष्णे इति ३.३१.१७; ४.४८.३
कृष्णेन १.३५.२; ९
कृष्णेभिः १.६२.८
कृष्व १.१०.९; ६.१८.१५; ७.२२.४
कृष्व १.५४.९; २.२३.१४; ३.५२.५; ६.२१.९; १०.४४.४
के १.८७.१; ९४.९; ११०.२; ३.४५.१; ५.२.५; १२.४^{४}; ५२.१२; ६१.१; ६.५२.१५; ६७.१०; ७.५६.१; १०३.८; ८.४५.४^{२}; ७७.१^{२}; ९.११०.६; १०.१९.७; २०.८; ५०.३^{३}; ५४.३; ९०.१०
केतः १.२४.१२
केतम् १.३३.१; २.३८.५; ४.२६.२; ७.१८.२५; ९.२१.६; १०.६.७; ९५.५
केतवः १.२४.७; ५०.१; ३; १९१.४; ७.७८.१; ८.१२.७; ४३.५; ९.७०.३; ८६.५; ६; १०.७८.७; ९१.५; १११.७
केतवे १.१६६.१; १०.३७.१
केतऽवेदाः १.१०४.३
केतऽसापः ५.३८.३
केतस्य १०.१३६.६
केताः १.५५.७
केतान् १.१४६.३
केतुः १.२७.१२; ९६.६; १०३.१; ११३.१९; १२४.११; १२७.६; ३.१.१७; १०.४; ११.३; ५५.२; ६१.३; ५.११.३; ७.६३.२; ६७.२; ७६.२; ९.८६.७; १०.४५.६; ८५.१९; ८९.१२; ९२.१; ९६.४; १५६.५; १५९.२
केतुना १.३.१२; ३६.१४; १८७.६; ५.४४.८; ६०.८; ६६.४; ६.७.६; १०.८.१; ३७.९
केतुम् १.६.३; ६०.१; ७१.२; ९२.१; ११३.१५; १२४.५; ३.२.१४; ३.३; ८.८; २९.५; ३४.४; ४.७.४; १४.२; ५.७.४; ११.२; ३४.९; ६.२.३; ७.२; ५; ३९.३; ४९.२; ७.५.५; ६.२; ९.१; ३०.३; ३४.६; ८.४४.१०; ९६.४; ९.६४.८; १०.१.५; २.६; ८८.१२; १२२.४; १३९.२
केतुऽमत् ६.४७.३१
केतुऽमन्तम् ८.५८.३
केतू इति २.११.६
केतेन ८.६०.१८
केतेभिः ३.६०.७
केन १.७६.१; ८७.२; १६५.२; १०.१५.६
केऽनिपानाम् १०.४४.४
केनो इति ८.६६.९
केपयः १०.४४.६
केभिः ८.१०३.१३
केवटे ६.५४.७
केवलऽअघः १०.११७.६
केवलऽआदी १०.११७.६

क्रतून् ९.७२.५
क्रतूनाम् ४.३१.५
क्रतोः ४.१०.२
क्रतौ १०.९५.३
क्रत्वः ७.८९.३; ८.७८.७
क्रत्वा १.३९.१; ६५.५; ६९.१; ७३.२; ८१.४; १२८.४[2]; ५; १३८.३[2]; १४१.६; १४३.२; १४५.२; १६५.७; १९०.३; ३.२.३; ६.५; ९.६; ४.१.१; ५.७; १२.१; २१.१०; २८.३; ३३.९; ५.१०.२; १७.४; २९.५; ७; ८७.२; ६.२.८; ५.३; १२.४; १६.२६; १७.६; ४८.४; ६८.९; ७.४.५; २१.६; २८.२; ६१.२; ६२.१; ७६.१; ८.१९.२९; ३३.६; ६१.४; ६६.४; १०; ८८.४; ९७.१०; १०२.८; ९.४.५; ६; १६.२; ४; ८६.१३; १०२.८; १०.२९.७; ६१.१; ८३.५; ८४.६; १४४.६[2]
क्रत्वाऽमघासः ५.३३.९
क्रत्वे १.१११.२; १३५.१; ४.३७.२; ५.४३.५; ६.४०.२; ७.२५.४; ९.३६.३; १००.५; १०९.२; १०; १०.५७.४
क्रदः ९.९७.१८; २८
क्रन् ७.५.७
क्रन्त १.१४१.३
क्रन्तः ४.२.१४
क्रन्द २.४२.३; ५.८३.७
क्रन्दत् १.३६.८; १७३.३
क्रन्दत् १०.४४.८; ९५.१३
क्रन्दति १.१००.१३
क्रन्दत्ऽइष्टये १०.१००.२
क्रन्दतु ५.५८.६
क्रन्दन् ३.२६.३; ९.३८.६; ४२.४; ९६.२२; ९७.३३
क्रन्दनुः ७.४२.१
क्रन्दन्ति १०.९४.२
क्रन्दय ६.४७.३०
क्रन्दसि १०.३८.१
क्रन्दसी इति २.१२.८; ६.२५.४; १०.१२१.६
क्रमणाय ६.७०.३

क्रमणे इति १.१५५.५
क्रमते १.१४४.१
क्रमस्व ४.१८.११; ८.१.४; ८१.७; १००.१२
क्रमाम ६.४९.१५
क्रमिष्ट १.१५५.४
क्रमिष्ट ८.६३.९
क्रमिष्टम् १.१८२.३
क्रमीः १.५१.६
क्रमुः ७.३२.२७
क्रवणस्य ५.४४.९
क्रविषः १.१६२.९; १०
क्रविषा १०.८७.१६
क्रविष्णुः १०.८७.५
क्रव्यऽअत् १०.१६.१०; ८७.५
क्रव्यऽअदः १०.८७.२; १९
क्रव्यऽअदम् १०.१६.९; १६२.२
क्रव्यऽअदे ७.१०४.२
क्रव्यऽवाहनः १०.१६.११
क्राणस्य १.१३२.२
क्राणा १.५८.३; १३९.१; ५.७.८; १०.२; ९.८६.१९; १०२.१; १०.६१.१
क्राणाः १.१३४.२[2]; १०.९२.६
क्राणाय १०.१३२.२
क्राणासः १.१३४.२
क्राम १०.१६४.१
क्रामेम १.१०५.६; ५.५३.११
क्रियते ९.७०.८; १०.११२.९
क्रियन्ते ३.४१.३; ८.९०.३
क्रियमाणम् ६.५२.२; ७.३५.१४
क्रियमाणस्य १०.५५.७
क्रियमाणा ५.२९.१५
क्रियाम १०.३२.९
क्रियास्म ६.२३.६
क्रिविः ५.४४.४; ८.८७.१; ९.९.६
क्रिविःऽदती १.१६६.६
क्रिविम् १.३०.१; २.१७.६; २२.२; ८.२०.२४; २२.१२; ५१.८
क्रीळति ९.६६.२९; १०.३४.८
क्रीळथ ५.५०.३

४.२४.४; ३८.५ ५.१.१०; ३२.१०; ३६.६; ६.१.५; ७.२८.४; ८.१६.९; ९.८९.६
क्षितिः १.६५.३; १५१.४; ४.५.१५
क्षितिऽभ्यः ३.१३.४; ६.६१.३; १०.८९.११
क्षितिषु १.७३.४; २.२.३; ७.८८.७
क्षितीः ३.३.९; १४.४; ५.३७.४; ६.६५.१; ७.६५.२; ७५.४; ७९.१; ८.६.२६
क्षितीनाम् १.७.९; ५९.१; ७२.७; १७६.३; १७७.३; ३.२०.४; ३४.२; ५.७.१; ३५.२; ६.३२.४; ४६.७; ७.९८.१; ८.६७.१३; १०.७८.१; १८७.१
क्षिप २.३०.५
क्षिपः ३.२३.३; ५.४३.४; ९.८.४; १४.७; १५.८; ४६.६; ६१.७; ७९.४; ८०.४; ५; ८५.७; ८६.२७; ९७.१२
क्षिपणिम् ४.४०.४
क्षिपणोः ४.५८.६
क्षिपत् ४.२७.३; १०.१८२.१–३
क्षिपाभिः ९.९७.५७
क्षिप्ता १.१२९.८
क्षिप्रऽइषवे ७.४६.१
क्षिप्रऽधन्वा ९.९०.३
क्षिप्राऽइव ४.८.८
क्षिप्रेण २.२४.८
क्षियतः १.१२६.१
क्षियन्तः ४.२५.८; ७.८८.७; ८.८३.६
क्षियन्तम् १.११७.५; २.११.५; १२.११; ३.३०.८; ३९.५; ४.१७.१३; १०.६८.८
क्षियन्ति ७.७४.६; १०.५१.२; १२५.४
क्षीयते २.९.५
क्षीयन्ते १.६२.१२
क्षीयन्ते ६.४५.३
क्षीरऽपाकम् ८.७७.१०
क्षीरम् १.१६४.७; ९.६७.३२; १०.८७.१६
क्षीरेण १.१०४.३
क्षीरैः ८.२.९
क्षु १०.६१.१२
क्षुद्मम्ऽइव १.१२९.६
क्षुद्राऽइव ८.४९.४
क्षुधः ८.६६.१४; १०.४३.३
क्षुधम् ८.६०.२०; १०.४२.१०; ४३.१०; ४४.१०; ११७.१
क्षुधे ७.१.१९
क्षुध्यत्ऽभ्यः १.१०४.७
क्षुभा ५.४१.१३
क्षुऽमत् ९.८६.१८
क्षुऽमतः २.१.१०; १०.११६.२
क्षुऽमति ४.२.१८
क्षुऽमती १०.११.३
क्षुऽमतीः १०.२.६
क्षुऽमन्तः १.३०.१३; १०.३१.५
क्षुऽमन्तम् २.४.८; ९.५; ८.८१.१; ८८.२; १०.३८.२
क्षुम्पम्ऽइव १.८४.८
क्षुरम् ८.४.१६; १०.२८.९
क्षुराः १.१६६.१०
क्षे ४.३.६
क्षेति ३.५५.४; ७; ५.३७.४; ७.३२.९; ८.८४.९; १०.४०.११
क्षेति १.६४.१३; ८३.३; ९४.२; २.२७.१३; ३.५५.२१; ४.१.९; ५०.८; ५.६१.१९; ८.३९.९; ९.१२.३; ७२.३; १०.९१.२; १२४.८; १३६.५
क्षेत्रऽजेषे १.३३.१५
क्षेत्रम् १.१००.१८; ३.३१.१५; ५.४५.९; ६.४७.२०; ९.८५.४; ९१.६; १०.३३.६
क्षेत्रम्ऽइव १.११०.५
क्षेत्रऽवित् ९.७०.९
क्षेत्रवित्ऽतरः १०.२५.८
क्षेत्रऽविदम् १०.३२.७
क्षेत्रऽविदा १०.३२.७
क्षेत्रऽसाता ७.१९.३
क्षेत्रऽसाधसः ३.८.७
क्षेत्रऽसाधसम् ८.३१.१४
क्षेत्रऽसाम् ४.३८.१
क्षेत्रस्य १.११२.२२; ४.५७.१–३; ७.३५.१०; १०.६६.१३

क्षेत्राणि ६.६१.१४
क्षेत्रात् १.११९.७; ५.२.३; ४
क्षेत्राय ७.१००.४
क्षेत्रे ५.६२.७
क्षेपयत् ५.९.७
क्षेमोः १०.५१.६
क्षेमः १.६७.१; १०.२०.६
क्षेमऽकामासः १०.९४.१२
क्षेमम् १.६६.२; १०.१२४.७
क्षेमऽयन्तः ४.३३.१०; ५.४७.४
क्षेमऽयन्तम् ३.७.२
क्षेमस्य १.१००.७; ७.८२.४; ८.३७.५
क्षेमासः ८.१९.८
क्षेमे ५.३७.५; ७.५४.३; ८६.८; १०.२७.४; ८९.१०
क्षेमेण १.५५.४; ७.८२.५
क्षेमेभिः ८.८४.९
क्षेम्या १०.२८.५
क्षेषत् ६.३.१
क्षेषि ७.१८.२
क्षेषि ६.४.४; १०.५१.५
क्षेष्यन्तः २.४.३
क्षैतः ९.९७.३
क्षैतऽवत् ६.२.१
क्षैत्रऽपत्येषु १.११२.१३
क्षैत्राय ८.७१.१२
क्षोः ९.९७.२२
क्षोणयः १०.२२.९
क्षोणस्य १.११७.८
क्षोणी इति १.१८०.५; ८.७.२२; ५२.१०; ९९.६
क्षोणीः १.५४.१
क्षोणीः १.१७३.७; ८.३.१०; १३.१७
क्षोणीःऽइव १.५७.४
क्षोणीभिः २.३४.१३; १०.९५.९
क्षोणीभ्याम् २.१६.३
क्षोदः १.६५.३[२]; ६६.५; ९२.१२; १८०.४; २.२५.३; ६.१७.१२; ८.२५.१५; १०.५६.७; ६१.२
क्षोदन्ति ७.५८.१
क्षोदन्ते ५.५८.६
क्षोदसः १.१८२.५
क्षोदसा १.११२.१२; ५.५३.७; ७.९५.१
क्षोभणः १०.१०३.१
क्ष्णोत्रेणऽइव २.३९.७
क्ष्णौमि १०.२३.२
क्ष्मः १.१००.१५
क्ष्मया १.५५.६; ५.८४.३; ७.४६.३; १०.६१.७; ८९.३
क्ष्विङ्काः १०.८७.७

ख

खजऽकृत् ६.१८.२; ७.२०.३
खजऽकृत् ८.१.७
खजम्ऽकरः १.१०२.६
खदिरस्य ३.५३.१९
खनमानः १.१७९.६
खनामि १०.९७.२०
खनामि १०.१४५.१
खनिता १०.९७.२०
खनित्रिमाः ७.४९.२
खनित्रैः १.१७९.६
खम् ४.११.२; १०.१५६.३
खरऽज्रुः १०.१०६.७
खरमज्रा १०.१०६.७
खर्गलाऽइव ७.१०४.१७
खलु १०.३४.१४
खले १०.४८.७
खाताः ४.५०.३
खादःऽअर्णाः ५.४५.२
खादति १.१५८.४
खादथ १.६४.७
खादयः १.१६६.९; ५.५४.११; ७.५६.१३
खादिः १. १६८.३
खादिनः २.३४.२
खादिनम् ६.१६.४०
खादिषु ५.५३.४; १०.३८.१
खादिऽहस्तम् ५.५८.२

खानि २.१५.३; ४.२८.१; ५.३२.१; ७.८२.३
खाम् २.२८.५; ६.३६.४
खार्यः ४.३२.१७
खिदत् ४.२८.२
खिदति ४.२५.७
खिद्रम् ५.८४.१
खिद्वः ६.२२.४
खिल्याः १०.१४२.३
खिल्ये ६.२८.२
खुदत १०.१०१.१२
खृगलाऽइव २.३९.४
खे ८.७७.३; ९१.७[३]
खेदया ८.७२.८; ७७.३
खेदाम् १०.११६.४
खेलस्य १.११६.१५
ख्यः १.८१.९; ६.१५.१५
ख्यः १.४.३; ६.४८.१९; ८.६५.९
ख्यत् १०.५३.२
ख्यत् ७.३६.७; ८.७९.२
ख्यत ८.४७.११
ख्यतम् ५.६५.६; ८.२२.१४; ७३.१५
ख्यन् ३.३१.१२
ख्यन् १.१६२.१; ७.९३.८; १०.१०.२
ख्यम् ७.८६.२

ग

गङ्गे १०.७५.५
गच्छ ६.७५.१६
गच्छ १०.१६.३[२]; ८५.२६; १५५.१; ३
गच्छत १०.१५.११
गच्छतम् १.३४.१०; ५.७५.३; ८.८.१; ८५.१; ६
गच्छतम् १.३४.७; ४७.३; १३५.७[२]; ४.४६.५; ४९.३; ५.७५.७; ७८.१; ६.६०.९; १४; ८.३५.४–६; १०; ७३.१४
गच्छतात् १०.१५४.१–५
गच्छताम् १.२१.४; २२.१; १०.१६.५
गच्छति ९.१८.७; १०.८६.१२
गच्छति १.१.४; १६.८; १८.८; ४१.६; ८३.१; १२५.५; २.२५.४; ८.६४.८; ९.७.७; १५.६; ८६.१२; १०.१४.१३; ८६.१०
गच्छतु ९.६३.२२; ९७.६; १०.१६.३; ९
गच्छते ९.९३.२
गच्छथ ५.५५.७
गच्छथ १.१६१.११; ६.५२.८
गच्छथः १.२२.४; ११२.१८; ११७.२; १५१.७; ४.४३.३; ७.६९.२; ७४.१; ८२.७; ८.९.६; १०.४१.२; ३
गच्छथः ४.४५.४; ५.७४.३; ८.३५.७–९; १३–१५; १०.४०.३[२]
गच्छध्वम् १०.१९१.२
गच्छन् ४.३८.४; ५.४५.९; ९.१५.१; २५.५; ३८.१; ४; ६१.२५; ९०.१
गच्छन्तः ९.८.२; ६३.६
गच्छन्ति १.१४५.४
गच्छन्ति १.८५.११; १४५.३; १०.११७.१; १६८.२
गच्छन्तु ९.८१.४; १०१.४
गच्छसि ४.३१.५
गच्छसि ८.९३.६; ९.२०.७; ६७.१९
गच्छस्व १०.१४.८[२]
गच्छाः ६.३५.३
गच्छात् १०.१०८.३
गच्छाति १०.१६.२
गच्छाति ७.३३.१४
गच्छाथ ८.७.३०
गच्छान् ८.७९.५
गच्छान् १०.१०.१०
गणः १.८७.४[२]; ३.३५.९; ५.६१.१३; ७.५६.७; १०.१३७.५
गणऽपतिम् २.२३.१
गणऽपते १०.११२.९
गणम् १.१४.३; ३८.१५; ६४.१२; ४.३५.३; ५.४४.१२; ५२.१३; १४; ५३.१०; ५६.१; ५८.१;२; ६.१६.२४; ५६.५; ८.९४.१२; ९.३२.३; १०.३६.७; ७७.१
गणम्ऽगणम् ३.२६.६; ५.५३.११
गणश्रिऽभिः ५.६०.८

गणऽश्रियः ८.२३.४
गणऽश्रियः १.६४.९
गणस्य ५.१.३; १०.३४.१२
गणाः ५.७९.५
गणानाम् २.२३.१
गणाय ७.५८.१
गणे ६.४०.१; ८.४६.३१
गणेन १.२३.७; ११७.३; ३.३२.२; ४.५०.५; ७.९.५; ९.९६.१७; १०.१०३.३
गणेषु १०.११२.९
गणैः १.६.८
गण्या ३.७.५
गत १.३.७; १०६.२; २.४१.१३; ५.५१.२; ६.५२.७; ७.५९.१०; ८.२०.२; १०; ९.५.११; १०.१५.४; ३५.११; ७७.४
गतऽअंसुम् १०.१८.८
गतः ७.५८.३
गतम् १.१०५.४; ११९.४; २.३७.५
गतम् १.२.४; ४६.१३; ४७.७; ९; ११२.१–२३; १३५.४[२]; ३.१२.१; ५८.४; ९; ४.४६.५; ५.५.७; ७१.३; ७३.१; ७४.६; ६.५९.१०; ६०.८; १५; ७.७०.१; ७३.४; ७४.३; ८२.८; ८३.३; ९४.७; ८.५.१३; १६; ३०; ८.६; १०.५; २२.५; १०;१२; २६.८; ९; ३५.२२–२४; ३८.४–७; ७३.१०; ८७.१; ६; १०.६१.४
गतिम् ५.६४.३
गत्वाय ८.१००.८
गत्वी ४.४१.५; १०.१०१.९
गध्र ८.२०.१६
गध्रि ८.९८.४
गध्यम् ४.१६.११; १६
गध्यस्य ६.१०.६; २६.२
गध्या ४.३८.४
गन् ७.५०.१
गनिंग्मतम् १०.४१.१
गनीगन्ति ६.७५.३
गन्त १.३८.२; ३९.७; ९; ५.८७.९; ८.२७.५
गन्त ६.४९.११
गन्त १.३.८; ५.४३.१०; ८.२०.१
गन्तन २.३६.३; ८.५४.३
गन्तन २.३४.५; ६; ५.५७.१. ७.४३.४; ५९.५; ८.७.११; २७
गन्तम् ५.४३.८; ८.८७.४
गन्तम् १.१३५.५; १३७.१; ३; १५१.७; २.३९.३; ५.७१.१; ६.६३.२; ७.६८.२; ८.८.७; १७; १९; ९.१
गन्तवे १.४६.७
गन्तवै १०.९५.१४
गन्ता १.८६.३; २.२३.१३; ४१.२; ४.२९.४; ५.३०.१; ६.२३.४; ४४.१५; ८.७१.५
गन्तारः ३.२६.६
गन्तारम् १.९.९
गन्तारा १.१७.२; ८.५.५; १३.१०; २२.३
गन्तु १.१७५.२; १८६.६; ५.४३.८; ११; १३; ७.१८.४; ८.६३.४
गन्तोः १.८९.९; ३.५४.१८
गन्धः १.१६२.१०
गन्धर्वः १.१६३.२; ९.८३.४; ८५.१२; १०.१०.४; ८५.४०; ४१; १२३.४; ७; १३९.५; ६; १७७.२
गन्धर्वम् ८.१.११; ७७.५; ९.८६.३६; १०.१३९.४
गन्धर्वस्य १.२२.१४
गन्धर्वाः ९.११३.३
गन्धर्वाणाम् १०.१३६.६
गन्धर्वान् ३.३८.६
गन्धर्वाय १०.८५.४१
गन्धर्वीः १०.११.२
गन्धारीणाम्ऽइव १.१२६.७
गन्म २.२८.७; ६.६१.१४
गन्वहि ८.६९.७
गभस्तिऽपूतः ९.८६.३४
गभस्तिऽपूतम् २.१४.८
गभस्तिम् १.५४.४
गभस्ती इति ६.१९.३; ७.३७.३
गभस्तौ १.६२.१२; २.१८.८; ६.२०.९; १०.४४.२; ६१.३; ७३.८

गर्भं ९.८२.४

गर्भः १.७०.$२^{४}$; ९५.४; १५२.३; १६४.९; २.१.१४; १०.३; ३.१.१२; ५.३; २९.११; ३१.३; ५.२.२; ४५.३; ७८.७; ६.१५.१; ४७.२८; ७.९.३; ८.१२.११; ९.६८.५; ९७.४१; १०.१.२; ८.२; २७.१४; ३०.८; ४५.६; ७९.४; १६८.४

गर्भःऽइव ३.२९.२

गर्भऽत्वम् १.६.४

गर्भऽधिम् १.३०.४

गर्भम् १.९५.२; १३०.३; १५६.३; १५७.५; १६४.३३; ५२; १७३.३; १८५.२; २.१८.२; ३५.१३; ३.१.६; १०; १३; २.१०; २७.९; ३१.२; ७; ४६.५; ५७.३; ४.७.९; १९.५; ५.४१.१०; ४७.४; ५८.७; ८३.१; ७; ६.४८.५; ५२.१६; ६६.३; ६७.४; ७.४.५; १०१.१; १०२.२; ८.६.२०; ९.१९.५; ७४.५; ७७.४; ८३.३; १०२.६; १०.२१.८; २७.१६; ४६.५; ६८.७; ८२.५; ६; ९१.६; १२१.७; १६२.१; २; १८३.३; १८४.१; $२^{३}$; ३

गर्भऽरसा १.१६४.८

गर्भाः १०.७३.२

गर्भिणीषु ३.२९.२

गर्भे १.६५.२; १४८.५; ४.२७.१; ६.१६.३५; ८.४३.९; ८३.८; १०.१०.५; ५३.११; १७७.२

गर्भेभ्यः १.१४६.५

गर्हसे ४.३.५

गल्दया ८.१.२०

गवयस्य ४.२१.८

गवा ५.३०.७

गवाम् १.१०.७; ३१.१२; ३३.१; ८१.७; ९३.२; १०१.४; १२२.७; १२४.५; ११; १६४.३; २.२३.१८; ३.३१.४; ४.१.१९; ३२.१८; ५१.८; ५२.२; ३; ५; ५.३०.४; ११-१३; ४५.२; ५६.५; ८६.३; ६.६५.५; ७२.४; ७.७६.६; ७७.२; ९८.६; १०२.२; १०३.२; १०; १०४.१०; ८.४.२०; ३६.५; ४६.२२; ५१.२; ६१.६; ९.६५.१७; ६६.२९; ७२.४; ७७.४; ८१.१; १०.४८.९; ४९.१०; ८७.१८; १०२.५; ९; १०८.३; ९; १६६.१

गवाम्ऽइव १.१३०.३; ५.५९.३; ६.२४.४

गवि १.११९.६; ४.५८.४; ६.४६.१४; ५६.३; १०.९४.९; १०६.१०; ११६.४

गविष्ठिरः ५.१.१२

गविष्ठिरम् १०.१५०.५

गवे १.४३.२; ६; ५.३३.४; ६.४५.२२; ८.५.२०; ३०.४; ४७.१२; ६८.१३; ९२.२५; ९.११.३; ७; ६१.१५; ६२.३

गव्यता ३.३१.९; ४.१.१५; ६.४६.१०

गव्यते ६.४५.२६

गव्यन् ३.३३.११; ९.८७.७; ९६.१

गव्यन्तः १.३३.१; ४.१७.१६; ७.३२.२३; ८३.१; १०.१३१.३; १६०.५

गव्यन्तम् ८.२.३५

गव्यन्ता १.१३१.३

गव्यम् १.७२.८; १२६.३; १४०.१३; ३.३२.१६; ४.२.१७; ५८.१०; ५.२९.१२; ३४.८; ५२.१७; ६१.५; ६.१७.१; ७.९०.४; ९२.३; ८.२१.१०; ९.१०८.६

गव्ययम् १०.४८.४

गव्यऽया ८.९३.१७

गव्ययी ९.७०.७

गव्यऽयुः ९.३६.६; ९८.३

गव्यवः १.१५१.१; ३.३३.१२; ७.१८.१४

गव्यस्य १.१३१.३; ५.३०.१५; ८.६६.३

गव्या ६.४४.१२; ७.६७.९

गव्या ५.७९.७; ७.१८.७; ८.१.१७; ९.१४.६; ६४.४; ८७.५

गव्यानि ८.३४.१४; ९.८.६; २२.७; ६२.२३

गव्युः १.५१.१४; ३.३१.८; ४.२३.१०; ३१.१४; ६.४१.२; ७.३१.३; ८.५३.८; ७८.९; ९.२७.४; ९७.१५

गव्यूतिः ९.७४.३; १०.१४.२; ६०.६

गव्यूतिम् ३.६२.१६; ५.६६.३; ७.६२.५; ६५.४; ७७.४; ८.५.६; ९.७८.५; ८५.८

गव्यूतीः १.२५.१६
गव्ये ८.१३.२२; ९.१०१.१६
गव्येभिः ६.६०.१४; ८.७३.१४; १५
गव्यो इति ८.४६.१०
गर्हनम् १.१३२.६; १०.१२९.१
गहि १.४.२; ३; ६.९; १४.२; १६.४; ५; १९.१–९; २३.१; २३; ३०.२२; ४९.१; ८४.१; १३९.६[2]; १४२.१३[2]; २.६.६; ४१.१; २; ३.१.१९; ३१.१८; ३७.११[2]; ४०.८; ९; ४२.१; २; ४४.१; ४.३२.१; ५; ५.५.९; २६.४; ५१.१; ३; ६.२२.११; ४१.१; ५४.७; ७.३२.१; ८.१.९; १६; ३.१७; ४.२; ३; १०; १३.१३; १४; १८.४; २१.४; २४.७; २६.२०; ३२.६; ३४.६; १२; ४६.९; ४९.७; ५०.७; ६०.४; ६५.९; ६६.८; १२; ८२.२; ४; ९५.८; ९७.५; ९९.१; ९.६५.५; ७२.९; १०.९.९; १४.५; ३८.५; १५०.१[2]; १६७.२
गाः १.१०.८; ३२.१२; ३३.३; १०; ६१.१०; ६२.२; ३; ८३.५; ८४.१६; ९१.२२; ९२.२; ९३.४; १०१.५; १०३.५; ११८.२; १२६.५; १७४.४; २.१२.३; १४.३; १९.३; २१.५; २४.३; १४; ३४.१; ३६.१; ३.३०.१०; २१; ३१.२१; ३९.५; ४४.५; ५०.३; ४.१.१५; १७.१०; ११; ३२.२२; ५.१४.४; २९.३; ४५.७; ८; ६२.३; ६.१७.३; ५; ६; २३.४; २७.८; ३५.२; ३९.५; ४३.३; ४७.१४; २४; ५४.५; ६; ६०.२[2]; ७५.२; ७.३६.१; ८.२.३९; ३.१९; १४.८; ६३.३; ९६.१७; ९.१४.५; ४२.१; ६४.३; १३; ७१.७; ७२.३; ७८.१; ८२.१; ३; ८६.२६; ८७.७; ८; ८९.३; ९०.४; ९१.६; ९५.१; ९६.८; १६; ९७.१३; ३९; १०७.२६; १०८.६; १०.८.८; १९.६; ४८.२; ६७.३; ४; ६; ८; ६८.३–५; १०; ११; ८९.७; १०२.८; १५६.२; १६०.३
गाः १.६७.३; ३.५३.२; ४.३.१३; १६.९; ७.६२.२; १०.१.२; ५६.३; १०८.९
गाःऽइव ३.४५.३; ८.२०.१९; ४१.१; ९.११२.३; १०.१२७.८
गाङ्ग्यः ६.४५.३१
गात् ७.३.९
गात् १.३८.५; १०४.५; १६४.४; १६७.५; २.३३.१४; ३८.८; ११; ३.३१.१; ६; २१; ५.४५.१; २; ७.६७.८; ६९.४; ८.५.३९; १०.५.६; १८.४
गात ८.२.३८
गात ८.२०.२२; १०.१९.१; ७८.८
गातन ५.५५.९
गातवे ३.३.१
गातुः १.१३६.२; ३.४.४; ५४.१८; ५.३२.१०; ९.१६.१५; १०.२०.४; ६; ३०.१; ६१.२५
गातुऽभिः १.१००.४
गातुम् १.७१.२; ७२.९; ८०.६; ९५.१०; ९६.४; ११२.१६; १५१.२; ६; १७३.१३; २.२०.५; २१.५; ३.१.२; ३१.९; १५; ४.४.६; १८.१०; ५१.१; ५५.४; ५.३०.७; ६५.४; ८७.८; ६.६.१; २२.५; ३०.३; ७.१३.३; ४७.४; ६३.५; ८.४५.३०; ९.६९.७; ८५.४; ९६.१०; ९७.१८; १०.१४.२; ४९.९; ७६.३; ९९.८; १०४.८; १२२.२
गातुऽमत्या ७.५४.३
गातुऽय ८.१६.१२
गातुऽयन् १.५२.८
गातुयन्तिऽइव १.१६९.५
गातुऽवित् १.५१.३; ३.६२.१३; ८.६६.१४; ९.४६.५; ६५.१३; ९२.३
गातुवित्ऽतमः ८.१०३.१; ९.४४.६; १०४.५; १०६.६; १०७.७
गातुवित्ऽतमाः ८.१९.१६; ९.१०१.१०
गातुवित्ऽतरा ८.२५.९
गातुऽविदम् १.१०५.१५
गात्रा १.१६२.१८; ८.१७.५
गात्राणाम् १.१६२.१९
गात्राणि १.१६२.२०; ९.८३.१
गात्रात् १.१६२.११

गात्रेऽगात्रे ८.४८.९
गाथऽपतिम् १.४३.४
गाथम् १.१६७.६; ९.११.४
गाथया ८.३२.१; ९८.९; ९.९९.४; १०.८५.६
गाथऽश्रवसम् ८.२.३८
गाथान्यः १.१९०.१
गाथान्यम् ८.९२.२
गाथाभिः ८.७१.१४
गाथिनः १.७.१
गाधम् १.६१.११; ५.४७.७; ६.२४.८; ४८.९; ७.६०.७; १०.१०६.९; ११३.१०
गाधानि ७.१८.५
गाधेषु ८.७०.८
गानि ४.१८.३
गान्धर्वीम् १०.८०.६
गाम् १.३३.१५; ११०.८; ११६.२२; ११७.२०; १५१.४; १६१.७; १०; १६४.९; ३.३४.९; ६०.२; ४.३३.४; ३६.४; ५७.१; ५.५२.१६; ६.४५.७; ४६.२; ६२.७; ७.४४.३; ८.१.२; ४.२१; १४.३; ७४.१०; ७८.२; ८१.३; ९७.२; १०१.१५; १६; ९.९.९; ९४.५; १०.४२.२; ५९.१०; ६५.११; ६७.५; ९७.४; १०७.७; ११२.८; ११९.१; १४६.४; १५५.५; १६५.५
गाम् १०.१२८.४
गाम १०.५७.१
गाम्ऽइव ८.६५.३; १०.७९.६
गाय १.३८.१४; ६.१६.२२; ८.२०.१९; ३३.४
गाय ६.४०.१; ४५.२२; ८.४६.१४
गायत् १.१६७.६; १७३.१
गायत १.४.१०; ५.१; ४; २१.२; ३७.१; ४; ५.६८.१; ६.४५.४; ७.३१.१; १०२.१; ८.१५.१; ३२.१३; १७; २७; ४५.२१; ८९.१; ९२.१; ९८.१; १०१.५; १०३.८; ९.११.१; १३.२; ६०.१; ६५.७; ८६.४४; ९७.४; १०४.१; १०५.१
गायति ८.९२.२५; १०.७१.११
गायत्रम् १.२७.४; ३८.१४; १२०.६; १६४.२३; २.४३.१; ८.१.८; २.१४; ३८.१०; १०.७१.११
गायत्रऽवर्तनिम् ८.३८.६
गायत्रऽवेपसम् ८.१.१०
गायत्रऽवेपसे १.१४२.१२
गायत्रस्य १.७९.७; १६४.२५
गायत्राः ८.१.७
गायत्रिणः १.१०.१
गायत्री १०.१४.१६; १३०.४
गायत्रे १.१६४.२३
गायत्रेण १.१२.११; १६४.२४; १८८.११; ९.६०.१
गायत्रेषु १.२१.२
गायत्रैः ८.१६.९
गायन्तः ८.६१.८; ६६.१
गायन्ति १.१०.१
गायसि २.४३.२; ८.१९.२२
गायिषे ७.९६.१
गाये ८.४६.१७
गारीत् ५.४०.७
गार्ष्टयः १०.१११.२
गार्हऽपत्यानि ६.१५.१९
गार्हऽपत्याय १०.८५.२७; ३६
गार्हऽपत्येन १.१५.१२
गावः १.२३.१८; २५.१६; ३२.११; ३८.२; ६६.५^{२}; ७१.१; ९०.८; ९१.१३; ९२.१; ४; ९५.६; १३५.८; १५३.४; १५४.६ १६३.८; १६४.७; १६८.२; १७३.१; १८६.७; १८७.११; १९१.४; २.१२.७; ३.३६.५; ५३.१४; ५६.२; ४.२३.९; ४१.८; ४२.१०; ५.३०.१०; ३३.१०; ४७.४; ५३.१६; ५६.४; ६.२८.१; ४; ५^{४}; ४०.२; ४१.१; ४५.२८; ६४.३; ६७.११; ७.९.४; १८.१; १०; २३.४; ३५.१२; ७५.७; ७९.२; ८.४.१८; ९.१९; २०.२१; ४१.६; ४६.३०; ४८.५; ६९.६; ७२.१२; ९३.१२; ९६.५; ९.१२.२; २४.२;

२६.२; ३१.५; ३२.५; ३३.४; ४१.१; ४९.२; ६२.५; ६६.१२; ६८.१; ७१.४; ७२.६; ८४.५; ९३.३; ९४.२; ९७.९; २२; ३४; ३५; ९९.३; १०१.८; १०.४.२; १५.१; २७.८; ३२.४; ३४.१३; ६१.२१; ८५.१३; ८९.१४; ९०.१०; ९५.६; ९७.८; १०८.५; ११; १७२.१

गावः ६.२८.६; १०.१००.१०

गावःऽइव ८.४३.१७; १०.१४६.३; १४९.४

गावा ५.२७.१

गावाऽइव ३.३३.१

गावौ ३.५३.१७; ६.२७.७; १०.२७.२०; ८५.११

गासि ५.२५.१; ८.२७.२

गासिषत् ८.८१.५

गाहते १.१२७.४

गाहते ९.३.६; ७.२; ६७.१४; २०; ८६.८; २६; ४०; ९९.२; ७

गाहमानः १०.१०३.७

गाहसे ९.११०.२

गाहात् ९.११०.८

गाहेमहि २.७.३

गिरः १.३.२; ५.८; ६.६; ९; ९.४; १०.९;१२; ११.१; १४.१; २५.१८; २६.५; ३७.१०; ४५.५; ५३.१; ५७.४; ५९.४; ६१.४; ६४.१; ७७.४; ७९.१०; ८२.१; ८४.८; ९३.९; ११८.१०; १२१.१; १२२.१४; १५१.७; ८; १७६.२; १७८.३; १८६.७; २.६.१; २७.१; ३५.१; ३९.७; ३.३.३; १०.६; २०.२; २४.४; २९.१०; ३१.१३; ३९.७; ४०.८; ४२.३; ५१.१; २; ६; ५२.३; ४.३२.१६; ४१.८; ५.१०.४; ११.५; १३.३; २७.३; ३९.४; ५[2]; ४१.१२; १४; ४३.१०; ६१.१७; ६५.१; ६.१६.१६; ३७; ३४.१; ३६.३; ३८.३; ४; ४४.५; ४५.२३; २५; २८; ४७.१४; ५२.९; ६९.२; ४; ७.३.८; ५.५; १०.३; १५.६; १८.२; ३; २२.५; ३२.५; ३१.५; ४५.४; ४६.१; ६८.१; ९४.२; ९९.७; १००.७; ८.२.३०; ३.३; १५; ६.११; ८.२२; १३.६; ७; १६; १८; ३२.२३; ३३.१३; ३५.६; ४३.१; ४४.१९; २२;२५; ५२.८; ५७.४; ७१.१०; ८४.३; ६; ७; ८५.९; ९२.१९; २१; २७; ९५.१; ६; ९६.१०; १०२.१३; १०३.१; ९.२.७; ६.९; २०.५; २५.५; ३४.६; ४०.५; ४३.२; ६१.१४; २३; ६३.१०; ८५.११; ९६.७; ११४.२; १०.२०.१०; २९.३; ५; ३३.६; ६१.२५; ६४.१२; ६५.१४; ६६.१०; ६९.३; ८९.४; ९१.१२; ९६.१; १०४.१; ७; १४८.३; १६०.२

गिरम् ३.६२.८; ५.१२.१; १५.१; ४२.१३; ७.५.१; ८.७.९; ९५.५

गिरयः १.६१.१४; ६३.१; ६४.७; ५.४१.११; ६.२४.८; ६६.११; ८.७.३४; १०.५९.३

गिरा १.३८.१३; ४६.१३; ७८.१; २; ७९.५; १३९.९[2]; १५१.१; २.१.११; २.१; ५; ६.६; २४.१; ३०.११; ३.२७.२; ५३.२; ४.८.१; ३२.९; ५.१७.३; १८.३; २०.३; ४४.१; ५२.१३; ५३.१६; ६८.१; ८७.३; ६.१५.१; ७; ७.३२.२०; ३६.४; ९४.११; ८.१.१८; २०; ११.७; १९.१३; २१; २०.१९; २०; २३.२; ९; २६.१५; २७.५; ३१.१४; ४०.४; ७; ४१.२; ४६.१४; १७; ६९.४; १४; ७४.११; ९३.९; ९.१०.४; १४.२; २९.२; ६२.१५; ६७.९; ७१.३; ६; ८६.३९; ४६; १०.२२.१; ६४.३; ४; १०१.३; ११८.३; १३८.२; १४०.६

गिराऽगिरा ६.४८.१

गिराम् १.१०.३; ३.३१.१८; ६.२४.१

गिराऽवृधम् ९.२६.६

गिरिः १.३७.७; ६५.३; ४.२०.६; ८.७.५; ५०.२; ९८.४

गिरिऽक्षिते १.१५४.३

गिरिऽजाः ५.८७.१

गिरिऽभ्यः १.१०९.६; ७.९५.२; ८.७७.६

गिरिऽभ्रजः १०.६८.१

गिरिम् १.५६.२; ४.१७.३; ५.५४.५; ५६.४;

गुहत्ऽअवद्यम् २.१९.५
गुहम् १.६७.३
गुहमानः ४.१.११
गुहा १.६.५; २३.१४; ६५.१; ६७.२; ४; १२३.७; १३०.३; १४१.३; १६४.४५; १६७.३; २.४.९; ११.५; १२.४; २४.६; ३.१.९[२]; ५.१०; ३९.६; ५६.२; ४.५.८; ९; १२; ७.६; १८.५; २१.७; ५.२.१; ८.३; ११.६; १५.५; ८.६.८; ८.२३; १४.८; ९.६.९; १०.९; ६८.५; १०२.२; १०.५.२; २२.१; १०; ३९.९; ४५.२; ४६.२; ५४.५; ६१.१३; ६७.४; ६८.७; ७१.१; ७९.२; ८५.१६; १००.७; १२४.२; १४८.२; १८१.२
गुहा १.६७.३
गुहाऽइव ३.१.१४
गुह्यम् १.८६.१०; २.११.५; ३.३९.६; ५५.१५; ४.५.१०; ५८.१; ५.३.२; ३; ९.८७.३; ९६.१६; १०.५५.१; २; ७९.३; १४८.२
गुह्यमानम् ४.५८.४
गुह्या ३.३८.३; ५.५.१०; ७.८७.४; ८.४१.५
गुह्याः २.३२.२; ७.१०३.८
गुह्यानि १.७२.६; ९.९५.२; १०.५३.१०
गुह्याम् १०.५३.३
गुह्येन १.१६३.३
गुह्येषु ३.५४.५; १०.११४.२
गुङ्वी ७.८०.२
गूळ्हम् १.११७.४; २.११.५; ३.३९.६; ५.४०.६; ७.७६.४; १०.७२.७; १२९.३; १४८.२
गूळ्हा ६.४८.१५
गूळ्हे इति ८.९६.१६
गूर्त १.१७३.२
गूर्तऽतमाः १.१६७.१
गूर्तऽमनाः ६.६३.४
गूर्तयः १.५६.२; ८.५०.५
गूर्तये १०.६१.१५
गूर्तवचःऽतमः १०.६१.२
गूर्तऽवचाः १०.६१.१
गूर्तऽवसुः १०.१३२.१
गूर्तऽश्रवसम् १.६१.५
गूर्तऽश्रवाः १.१२२.१०
गूर्ताः ४.१९.८
गूर्तिऽभिः ९.१०५.१
गृधय ८.१९.१
गृहः ७.१००.६; १०.२७.२४
गूहत १.८६.१०
गूहताम् २.४०.२
गूहते १०.२७.२४
गूहथः ५.६३.४
गूहन्ति १०.१०८.४
गूहन्तीः ४.५१.९
गूहमाना ७.१०४.१७
गृणतः ३.६१.१; ४.१७.५; ५.३३.७; ६.२३.४; २४.२; ४९.११; ७.१२.२; ९.४३.६; १०.२२.१५; ११५.५; ९; १४८.४
गृणताम् ६.४४.१३; ४५.१७; १०.८९.१६
गृणते १.४४.६; ५८.९; ९४.९; ११३.१७; २.४.९; ३.३०.१५; ५९.५; ४.११.२; २४.१; ६.४.८; ६.७; ११.३; ३१.४; ३९.१; ५; ४०.१; ४९.७; ६२.५; ११; ६५.६; ६६.९; ७.३.१०; ४.१०; ३६.९; ७७.४; ९.६९.१०; ८९.६; १०.३०.१२; ४९.१; ८७.११
गृणत्ऽभ्यः ६.८.५
गृणत्ऽसु ५.८६.६[२]; ८.१३.१२
गृणन्तु ८.३.७
गृणन्तः १.९.९; १५२.५; १७७.५; ३.१७.४; ४.१०.४; १६.३; २९.५; ५.८.४; ६.२५.९; ३३.५; ६८.८; ७.५३.१; ६०.१; ७८.२; ८.३.१३; ५.२७; २७.१३; ९.२९.२; १०.८९.१७; १०४.४; १२२.८
गृणन्तम् १.५८.८; ९; ३.२०.४; ४.२९.४; ५.७५.८; ६.२६.४; ७.५७.२
गृणन्ति १.१४.२; ४८.११; ४.३४.१०;

गोः १.२८.९; ५३.२; ६१.१२; ८४.१५; १२१.२[२]; ७; ९; १५८.२; १६३.७; १८०.३; ५; १८१.८; २.१४.१०; ३.१.२३; ५.११; ६.११; ७.११; १५.७; २२.५; ३०.१०; ३८.७; ३९.६; ५५.१; ८; ४.१.१६; ३.९; ५.३; १०; २२.४; ८; २३.६; २८.५; ४४.१; ५.४१.१८; ४५.६; ७.१८.२२; ८.३२.५; ५२.५; ९.६५.२५; ७१.५; ७९.४; ९१.३; १०१.११; १०.१२.३; ९६.११; १००.१२; १११.३

गोऽकामाः १०.१०८.१०

गोऽघ्नम् १.११४.१०

गोऽजाः ४.४०.५

गोऽजाताः ६.५०.११; ७.३५.१४; १०.५३.५

गोऽजित् ९.५९.१; ७८.४

गोऽजितः ३.३१.२०

गोऽजिता १.१०२.६

गोऽजिते २.२१.१

गोऽजीरया ९.११०.३

गोतम १.७९.१०

गोतमः १.६२.१३; ७८.२; ८८.५; १८३.५

गोतमस्य १.११६.९

गोतमाः १.७८.१; ४.३२.९; १२; ८.८८.४

गोतमात् ४.४.११

गोतमाय १.८५.११

गोतमासः १.६०.५; ६१.१६; ८८.४

गोतमेभिः १.६३.९; ७७.५; ९२.७

गोत्रऽभित् ६.१७.२

गोत्रऽभिदम् २.२३.३; १०.१०३.६

गोत्रम् १.५१.३; २.२३.१८; ८.५०.१०; ९.८६.२३

गोत्रस्य ८.६३.५; १०.१२०.८

गोत्रा २.१७.१; ३.३०.२१; ४३.७; ४.१६.८; ६.६५.५; १०.४८.२

गोत्राणि ३.३९.४; १०.१०३.७

गोऽदत्र ८.२१.१६

गोऽदत्रे ८.९२.११

गोऽदाः १.४.२; ३.३०.२१; ४.२२.१०; ५.४२.८; ८.४५.१९

गोऽदुहः ८.५२.४

गोऽदुहे १.४.१

गोधा ८.६९.९; १०.२८.१०

गोधाः १०.२८.११

गोऽधायसम् १०.६७.७

गोऽधुक् १.१६४.२६

गोनाम् १.६९.२; १२६.२; २.३०.५; ४.२०.८; ५.३.३; ६.७; २७.२; ७.१६.७; ८.५.३७; ६.४७; ७८.१; ९.७४.८; ८७.३; ९; ९७.३१; ४३; १०.८.९; ४७.१; ८०.५; १०८.८

गोऽन्योघाः ९.९७.१०

गोऽपतिः १.१०१.४; ३.३१.२१; ४.२४.१; ३०.२२; ६.२८.३; ७.९८.६; ८.१४.२; ६२.७; १०.१०८.३

गोऽपतिम् ७.१८.४; ८.६९.४; ९.३५.५; ९७.३४; १०.४७.१; ६७.८; १६६.१

गोपती इति गोऽपती ९.१९.२

गोऽपते ८.२१.३

गोऽपते ३.३०.२१; ६.४५.२१

गोऽपतौ १०.१९.३

गोपम् १०.६१.१०

गोपऽयत्यम् ८.२५.१३

गोऽपरीणसा ८.४५.२४; १०.६२.१०

गोपर्वनः ८.७४.११

गोपा ७.९१.२; ८.२५.१; १०.४०.१२

गोपा ५.६२.९; ७.६४.२

गोपाः १.२२.१८; ९४.५; ९६.४; १०१.११; १६३.५; १६४.२१; २.९.२; ६; २३.६; २७.४; ३.१०.२; १५.२; ३१.१४; ५५.१०; ४.१६.१७; ५.२.५; ११.१; १२.४; ३१.१; ६.७.७; ९.३; ५१.१५; ७.१३.३; ५१.२; ५२.२; ५६.१८; ६०.२; ८.२८.३; ३१.१३; ४८.९; ९.७३.८; १०.७.७; ८.५; १७.३; १९.४; ५; २३.६; २५.७; ४८.१०; ६९.५; ११८.७; १२८.६; १३९.१

गोपाःऽइव ८.४१.४

गोपाजिह्वस्य ३.३८.९

गोपान् ६.५१.३

घ

घृणा १.५२.६; १४१.४; ४.४३.६; ५.७३.५; ९.१०७.२०

घृणात् १.१३३.६

घृणिऽइव २.३३.६

घृणिऽवान् १०.१७६.३

घृणे ६.१५.५

घृणैः ६.१६.३८

घृणेन १०.३७.१०

घृतऽअन्नः ७.३.१

घृतऽअन्नौ ६.६७.८

घृतऽआसुतिः १.१५६.१

घृतऽआहवन १.१२.५; ४५.५

घृतऽआहवनम् ८.७४.५

घृतऽकेशम् ८.६०.२

घृतऽदुहः ९.८९.५

घृतऽनिर्निक् १०.१२२.२

घृतऽनिर्निक् २.३५.४; ३.१७.१; २७.५

घृतऽनिर्निजः ४.३७.२

घृतऽपदी १०.७०.८

घृतऽपृचा ६.७०.४

घृतऽपृष्ठः १.१६४.१; ५.३७.१

घृतऽपृष्ठम् १.१३.५; ५.४.३; १४.५; ७.२.४; १०.३०.८; १२२.४

घृतऽपृष्ठाः १.१४.६

घृतऽप्रतीकः ३.१.१८; ५.११.१

घृतऽप्रतीकम् १.१४३.७; १०.२१.७

घृतऽप्रतीका १०.११४.३

घृतऽप्रतीकाम् ७.८५.१

घृतऽप्रयाः ३.४३.३

घृतऽप्रसत्तः ५.१५.१

घृतऽप्रुषः ६.४४.२०; ८.५९.४; १०.७८.४

घृतऽप्रुषम् १.४५.१; ७.४७.१

घृतऽप्रुषा २.३.२

घृतऽप्वः १०.१७.१०

घृतम् १.८५.३; ८७.२; ११०.६; १२५.५; १३४.६; १३५.७; १६८.८; २.३.११[२]; ५.६; ३५.११; १४; ३.२.१; २६.७; ४.१.६; १०.६; ५८.४; ५.५.१; १२.१; ८६.६; ६.१०.२; ७०.२; ७.४१.७; ८०.३; ९५.२; ८.६.११; ७.१९; १२.४; १३; ३९.३; १०२.२१; ९.३१.५; ४९.३; ६२.९; ६७.११; १२; ७४.४; ८२.२; ८६.३७; १०.१२.३; ३०.१३; ५१.८; ६९.२[२]; ८२.१; ९१.१५; ९६.१; ९९.४; १५४.१

घृतम्ऽइव ४.५७.२

घृतऽयोनिम् ३.४.२; ५.८.६

घृतयोनी इति घृतऽयोनी ५.६८.२

घृतऽवत् १.२२.१४; ६४.६; ३.५.६; ३१.११; ५९.१; ७.४७.३; १०.१४.१४; ६४.९; ६५.८

घृतऽवती ६.११.५

घृतवती इति घृतऽवती ६.७०.१

घृतवत्ऽभिः २.२६.४; ७.३.७

घृतऽवन्तः ३.२१.२; १०.२९.६

घृतऽवन्तम् १.३४.१०; १४२.२; ३.५.७; ६.१५.१६; ९.८२.१; १०.४५.९; ९१.४; १४८.५

घृतऽवन्ति ९.९६.१३

घृतऽवर्तनिः ७.६९.१

घृतऽवृधा ६.७०.४

घृतऽश्चुतः ३.२१.३; ७.९६.५; ८.५९.४; ५; ९.७४.६; ७७.१; १०.१८.१२

घृतऽश्चुतम् २.११.७; ८.८.१५; १६; ५१.१०; ५४.१

घृतऽश्चुता ५.१४.३

घृतऽश्रियम् ५.८.३

घृतऽश्रिया ६.७०.४

घृतऽश्रीः १.१२८.४; १०.६५.२

घृतऽस्नाः ४.६.९; ८.४६.२८

घृतऽस्नुः ५.७७.३; ९.८६.४५; १०.१२२.६

घृतऽस्नुना ६.५२.८

घृतऽस्नुवः १.१६.२

घृतऽस्नुवा ३.६.६

घृतस्नू इति घृतऽस्नू ३.४१.९; ४.२.३

घृतस्नू इति घृतऽस्नू १.१५३.१; १०.१२.४

घृतऽस्नूः २.२७.१

घृतस्नो इति घृतऽस्नो ५.२६.२

घृतस्य १.१२५.४; १२७.१; ३.१.७; ८;

घ्नन्तु ७.१०४.१७
घ्रंसम् १.११६.८; ५.४४.७; ७.६९.४
घ्रंसे ५.३४.३

च

च १.२.५–७; ७.४; ८.५; १०; १०.४^{२}; ५; १२.१०; १३.१; ६; १४.१; १५.९; १७.६; १८.५; २०.५^{२}; २२.१३; २३.२०^{२}; २१; २२; २४.१^{२}; २^{२}; २५.११; १९; २०^{२}; २६.५; ८; २७.३^{२}; २८.३; ३१.७; ९; १२; १७; ३२.१३^{३}; १४^{२}; १५; ३३.७; ३४.३; १२; ३५.२; ११^{२}; ३७.६^{२}; ४०.६; ४२.९; ४७.१०; ४८.३; ५०.११; ५१.८; ५४.८; ११^{२}; ५७.५; ६०.२; ६१.४; १४^{२}; ६२.३; ७०.२–४; ७१.८; ७२.६^{२}; ७३.७^{३}; ८; १०; ७४.१; ६; ७६.४^{२}; ७७.२; ४; ८०.१३; १४; ८४.२^{२}; ५; २०; ८६.४; ८८.४; ९१.६; ९२.१३^{२}; ९३.५; ९४.५; १४; ९६.१^{२}; २; ७^{६}; ९७.२; ३; १००.१; १५; १८; १०१.६^{२}; १०२.१^{२}; ७; १०; १०३.२; ७; १०९.६; ११२.६; २३; २४; ११३.१०; ११४.२^{२}; ६; १०^{३}; ११५.१; ११६.११; १८^{२}; ११७.१०^{२}; १८; १२०.४^{२}; ९^{२}; १२; १२३.१२^{२}; १३; १२४.१२; १३^{२}; १२५.४^{४}; १२७.८; १२८.५; १२९.१; १३२.४^{२}; १३५.४; ७^{२}; १३६.२; ७; १३९.३; ८^{२}; १४०.६; १२^{२}; १३; १४१.११; १३^{२}; १५३.४; १५५.१; ६; १५६.१; ४; १५७.५^{२}; १५९.३^{२}; १६०.२; ३; १६२.६; १२; १४^{३}; १६३.१३; १६४.११; १९; २२; ३१^{२}; ५१^{२}; १६५.१२; १६६.३; १६७.१०; १६८.३^{२}; १६९.४; १७४.१; ३; १७८.२; ३; १८०.२; १८३.३; १८४.२; ५; १८५.१०; १८६.३; ११^{२}; १८८.५^{२}; १८९.२; १९०.३; ४; ७; १९१.८; २.१.२^{२}; १५^{३}; १६^{२}; २.१२; १३^{२}; ५.७; ६.८^{२}; ७.२; ११.३; १४; १३.६^{२}; ७^{३}; ८^{२}; १३^{२}; १४.४; १५.२; ९; १९.१; २; ६; २०.३^{२}; ४; ७; २३.३; १९; २४.२; १४; १६; २५.२^{२}; २७.१०^{२}; १२; २९.२^{३}; ३; ३१.५; ३२.३; ३३.१३^{२}; ३५.६; ८; ३६.४; ४१.११; १९; ४२.१; ४३.१^{२}; ३.१.१०^{२}; १५^{२}; २.१; ३.४; ६–८; ६.३; ९; ९.९^{२}; १२.८; १४.४; १५.३^{२}; १७.५^{२}; १९.३; २०.३; ५^{३}; २२.३; २५.४; ३०.१८; २०; ३१.१९; २१; ३४.८; ३७.१; ७; ४०.८; ९; ४२.७; ४३.४; ४६.२^{२}; ५०.४; ५२.२; ३^{२}; ५३.३–५; २०^{२}; ५४.११; ५५.११^{२}; १२^{२}; १९; २१; ५७–५; ५८.७; ६०.४; ६; ६२.९; १४; ४.१.१७; २.२; ३^{२}; ११^{३}; ९.५; १६.१९; १७.११; १८.४; १९.८; २०.२; २२.१; ३; ४; २६.१; ७; २८.५; २९.३; ३०.१९; ३२.१६^{२}; ३४.६; १०; ३५.२; ३६.१; ३७.६; ३८.५^{२}; ४१.६; ४२.३; ४७.२; ३; ४९.१; ३; ५०.१०; ५१.११^{२}; ५३.७; ५४.३^{२}; ५.३.५; ४.४; ७.१; ९.६; १०.३; ६^{२}; ७; ११.५; १५.४; १६.५; २५.३; २६.१; २७.२^{३}; २८.२; २९.६; ३०.३; ३३.५^{२}; ६; ३७.३; ३८.३^{२}; ४०.७; ४१.१४; १५; ४३.१०; ४४.३^{२}; १२; ४८.३; ४९.१; २; ५०.२; ५१.६; १४^{२}; ५२.३; ४; ५५.८^{२}; ६०.७; ६२.८; ६४.४; ५^{२}; ६; ६५.६; ६६.६; ६८.२^{२}; ७२.३^{२}; ७७.२; ७८.५; ६^{२}; ८२.९; ८३.९; ८७.२; ६.१.९; ११; ८.७^{२}; ९.१^{२}; १०.५^{३}; १५.८^{२}; १६.२; ३; १७; २२^{२}; २३; १७.१४^{२}; १८.८–१०; २१.९; २२.८; २४.५^{२}; ७; १०; २५.१; २८.२; ३^{२}; २९.६; ३१.१; ५; ३२.४; ३३.३; ५; ३४.१^{३}; ५; ३६.२; ३७.४; ३८.३^{२}; ४; ५; ४३.२; ४४.१७; ४५.४; ४६.७; ८; ९^{२}; १२; ४७.२; १०; २१; ४८.१; ८; १०; १३^{२}; ४९.५; १३; १५; ५०.१; ६; ११; ५१.२^{२}; ५२.१४; १५; ५४.३;

५६.५; ६^{२}; ५७.५; ६०.१२; ६१.१४;
६३.८^{३}; ९; ६४.६; ६५.५; ६६.२;
६८.४^{३}; ५; ६९.१; ८; ७०.५; ६^{२};
७१.२^{२}; ७२.१; ७५.५; ११^{२}; १९; ७.३.७;
१०; ४.१; ५^{३}; १०; ७.५; १५.८; ११;
१२^{२}; १६.५; ६; ९^{२}; १७.४; १८.६; १०;
११^{२}; १४; १९^{३}; १९.४; ५^{२}; १०^{२};
२०.१०; २१.१०; २२.९^{२}; २४.१^{२};
२५.३; ३०.४; ३१.५; ६; ३२.६; २४;
३३.६; ३६.२; ५; ७; ४०.२^{३}; ६; ४२.२;
४५.१^{२}; ५०.२; ४; ५१.३^{३}; ५२.३;
५५.६^{२}; ५९.१; ६^{२}; ६०.२^{२}; ६२.२;
६४.४; ६५.२^{२}; ६६.९; ११; १३; १७;
१८; ६७.१०; ६८.१; ६९.८; ७२.३; ४;
७३.२; ७७.५^{२}; ७८.५; ८१.२; ८३.१^{२};
६^{२}; ८६.१; ८८.३; ८९.५; ९१.२^{३};
९२.३; ९६.३; ९७.१; १०; ९८.७;
९९.५^{२}; १०१.६; १०४.१०; ११^{२};
१२^{२}; २५; ८.१.१; ३; ६; १४; २२^{२};
२.४; २९; ३०^{२}; ३३; ४.११; ५.१२;
६.१२; १८; २८; ११.१०^{४}; १३.२५;
१४.९; १५.३; ५; ८; १६.२; १२^{३};
१८.१५^{२}; १९.२३^{२}; २०.१८; २१.६;
१२; २३.३; २४.१२; २०; २९; २५.२;
२७.२; ३०.२^{२}; ३१.१^{२}; ५; ३३.१३;
३४.१५; १६; ३५.१–९; १०^{६}; ११^{६};
१२^{५}; १३–२१; ३७.५^{२}; ३९.४^{२}; ५; ९^{२};
४१.२; ४५.२५; ४७.४; ९; १२^{२}; १४^{२};
१६^{२}; १८; ४८.२; ५३.१; ४^{२}; ६०.७;
११; ६१.१; ८; १७^{३}; ६२.११^{२}; ६३.२;
६; ६८.४; ६९.७; ७१.१५; ७४.१०;
७८.१; ८; ७९.५; ८०.१०; ८१.९; ८२.१;
४; ८३.२; ८९.६; ९१.६; ९३.२; ४; १०;
१३; १७; ९४.८; ९७.१; १०; १३; १४;
१००.२; १०२.१६; ९.१.१०; ४.१^{२};
२; १९.२; २३.७; ३२.६^{२}; ४७.२; ५५.१;
५८.४; ६१.९; ६३.२; ६५.१०; ६६.१९;
६७.२१; २५; ७०.३^{२}; ७२.८; ७४.५^{२};
७८.५^{२}; ७९.१; ८१.२; ८६.९^{२}; २९^{२};
४२^{२}; ८९.१; ९५.३^{३}; ५; ९७.१८^{२};
४२; ४३; ४४^{३}; ५४; ९८.१०; १२;
९९.३; १००.३; ५; ९^{२}; १०६.३;
१०७.२४; २५; १०९.२; ५; ११०.९;
१११.३; ११३.१०^{३}; ११^{२}; ११४.४;
१०.३.७; ४.७^{२}; ५.७^{३}; ७.७; ८.६; ९.३;
६–८; १०.४; १३; ११.२; ८; १४.३^{२};
७; ९; ११^{२}; १४; १५.३^{२}; १३^{४}; १६–३^{२};
६; ७; ११; १७.६^{२}; ११^{२}; १३; १९.७;
२०.८; २२.६^{२}; १५; २३.७^{२}; २५.११;
२६.४^{२}; ६^{२}; २७.१०; २०; २२; २९.५;
७; ३०.५; ६; १२^{३}; ३२.९; ३४.५; ११;
३६.२^{२}; ३७.२^{२}; ४; ९^{२}; ३८.४; ३९.१०;
४०.९; ४८.३; ४९.२^{३}; ४; ८; ५०.१; ४;
५; ७^{२}; ५१.८^{४}; ९; ५२.६^{२}; ५४.३^{२};
५; ५७.३; ४; ५८.१२^{२}; ६१.१६; २२;
२३; २४^{२}; ६२.१०; ६३.८; ६४.१४;
१६; ६७.३; ७४.३^{२}; ७७.८; ८२.७;
८३.३; ८४.७; ८५.१७; ४१^{२}; ८६.२०^{२};
८७.३; ८८.१५; १७; ९०.२; ३;
७; ८; १०; १३^{२}; ९१.३^{२}; ५; ६^{३}; १०^{२};
९२.३; ७; ९३.९; १५^{२}; ९७.१; १०;
१५; २०; २१^{२}; १००.६; १०१.३;
१०४.८^{२}; १०७.४. ८; १०८.३; ९–११;
१०९.३; ११०.१–३; ११३.९^{२}; ११४.५;
६^{२}; ११५.१; ९^{२}; ११६.७; ९; १२०.२^{२};
७; ८; ९^{२}; १२१.५; ९; १२४.५; १२६.२;
१३३.५; १३६.५; १३८.१; १३९.२;
१४१.३; ५; ६; १४२.८; १४६.५;
१४८.१; १५७.१^{२}; २^{३}; १५८.४^{२};
१५९.६; १६१.५; १६४.५; १६५.३^{२};
१६७.४; १७३.५^{२}; १७४.५; १७७.३^{२};
१८१.१^{३}; २; ३; १८७.४; १८९.१;
१९०.१^{२}; ३^{२}

चकनन्त १.१६९.४

चकमानः ५.३६.१

चकमानाय १०.११७.२

चकुर १.१६५.८

चकुरम् ४.४२.६

चकर्त १०.६७.६; ७९.६
चकर्तिथ १.५७.६
चकर्थ १.६९.४; ११३.९; १३१.५; २.१३.११; ४.३०.८; ३२.११; ५.२९.१३; ३१.६; ३३.४; ८.१००.६; १०.५४.४; १०४.९; ११२.५; ११६.३
चकर्थ १.५९.५; १०३.७; १६५.७; ३.१.१; ३०.१७; ५.३१.२; ७.९८.३; १०.७३.७; ८; ७९.६
चक्रानः ३.५.२; ५.३.१०; २७.३; ६.३६.५; ७.२७.१; १०.६४.१६; १२३.८; १४८.३
चक्राना ६.६८.३
चक्रानाः २.३१.७; ४.१६.१५; ६.२९.१; १०.७७.८
चकार १.२४.८; ३२.१; ८०.१; १६४.२९; ३२; २.२४.५; ३.३१.२; ४.१६.१६; ६.२१.४; ७३.२; ७.६.४; ५; २६.३; ८७.१; ९८.५; ८.७०.३; ९६.२; १०.८६.३
चकार १.११६.१६; १९१.१०–१३; २.१५.२–९; ३.३४.७; ४.१६.४; ५.३२.७; ४५.७; ६.२१.३; २७.१; २; ३९.३; ७.६.३; १८.१७; ८८.४; १००.४. ८.२.३४; ९.९७.४१; १०.६८.१०
चकृपन्त ४.१.१४
चकृम १.३१.१८; १७९.५; १८५.८; २.५.८; २७.१४; ४.२.१४; ३.२; १२.४; १७.१८; ५४.३; ५.८५.७; ७.३१.२; ८६.५; ९३.७; ८.४६.२५; १०.१०.४; ३७.१२; ७०.८
चकृम १.७६.३; १०१.८; ९; १६२.७; १७१.४; ३.१.२; ५२.७; ५८.२; ८.६१.८; १०.१२.५; १५.४; १००.७
चकृऽवांसः १.१६१.४; ५.४३.३
चकृऽवांसम् ६.१७.१३
चकृऽवान् ५.२९.१४; १०.१३८.३
चकृषे १.५२.१२; ४.३५.७; ६.२३.६; ८.६३.८; ७७.७; ९.८८.१
चकृषे १.५२.१४; ११३. ९; ५.३०.४; १०.८.६
चक्रे १.२५.१९; ११७.२३; ३.३.३; १०; ६२.५; ८.६४.८; १०.४०.७
चक्र १.८९.९; १६५.११
चक्र ४.३६.४; ७.५६.२३
चक्रतुः १.१५९.२
चक्रथुः १.९२.१७; १०८.५; १६४.१९; ४.५७.५; ६.५९.१ ७.८२.५
चक्रथुः १.९३.६; ११६.९; २२; ११७.१३; १७; २१; ११८.६; १८२.५; ६.७२.१; ७.९९.४; १०.३९.७; ९
चक्रदुः ९.६४.३; १०७.२२
चक्रदत् ८.७.२६; ९.७.३; ७४.१; ८६.३१
चक्रन् १०.९५.१२; १३
चक्रम् १.३०.१९; १२१.१३; १३०.९; १५५.६; १६४.२; ११; १४; ४८; १७४.५; १७५.४; २.११.२०; ४.१.३; १६.१२; १७.१४; २८.२; ३०.४; ३१.४; ५.२९.१०; ३१.११; ३६.३; ७३.३; ६.३१.३; ५४.३; ५६.३; ७.६३.२; ८.५.३४; ६.३८; २२.४; १०.६१.१६; ७३.९; ८५.१५; १६; ९३.९
चक्रमन्त २.१९.२
चक्रमन्त ४.२२.६
चक्रमाणा ६.६२.२
चक्रमाणाः १०.१२३.३
चक्रमाथे इति ६.६९.५
चक्रम्ऽआसजः ५.३४.६
चक्रम्ऽइव २.५.३; ३.६१.३
चक्रमुः १०.७५.१
चक्रमुः १०.५६.५
चक्रमे १.२२.१७; १८; ५.४७.३; ८७.४; ७.१००.३; ४; ८.२९.७; १०.११७.८
चक्रये १.९.२
चक्रवाकाऽइव २.३९.३
चक्रस्य ८.६३.८
चक्रा १.३४.९; १६६.९; १८०.४; ८.५.२९; १०.१०.७; ८; ८९.२; ११७.५
चक्राऽइव ४.३०.२
चक्राणः १.७२.१; ८.१४.५; ९.४४.४

चक्षुष्मते १०.१८.१
चक्षूंषिऽइव ५.१.४
चक्षे १०.७९.५
चक्षोः १०.९०.१३
चक्ष्व ७.१०४.२५^{२}; १०.१६४.१
चख्यथुः ७.७०.४
चख्वांसम् २.१४.४
चङ्क्रमत ८.५५.४
चचक्ष ५.२.८; १०.३२.६
चचरा १०.१०६.८
चच्छद्यात् १०.७३.९
चच्छन्द ७.६३.३
चतन्तम् १.६५.१; १०.४६.२
चतसृऽभिः ८.६०.९
चतस्रः १.६२.६; १६४.४२; १८२.६; ५.३५.२; ७.३५.८; ८.१००.१०; ९.७४.६; ८९.५; १०.१९.८; ५१.९; ५८.४; ९५.१६; १२८.१
चतिनम् ६.१९.४
चतुःऽअक्षः १.३१.१३
चतुःऽअक्षौ १०.१४.१०; ११
चतुःऽअङ्गः १०.९२.११
चतुःऽअनीकः ५.४८.५
चतुःऽअश्रिः १.१५२.२
चतुःऽअश्रिम् ४.२२.२
चतुःऽकपर्दा १०.११४.३
चतुःऽत्रिंशत् १.१६२.१८
चतुःऽत्रिंशता १०.५५.३
चतुःऽदश १०.११४.७
चतुःऽधा ४.३५.२; ३
चतुःऽपत् १.४९.३; ९४.५; १२४.१; १०.९७.२०
चतुःऽपदः ६.७१.२; १०.१२१.३
चतुःऽपदा १.१६४.२४
चतुःऽपदी १.१६४.४१
चतुःऽपदीम् १०.१३.३
चतुःऽपदे १.११४.१; १२१.३; १५७.३; ३.६२.१४; ५.८१.२; ६.७४.१; ७.५४.१; ९.६९.७; १०.३७.११; ८५.४३; ४४; १६५.१
चतुःऽपात् ४.५१.५; १०.२७.१०; ९९.१०; ११७.८
चतुःऽपादः ८.२७.१२
चतुःऽभिः १.१५५.६; २.१८.४
चतुःऽभृष्टिम् १०.५८.३
चतुःऽयुगः २.१८.१
चतुःऽयुजः ८.६.४८
चतुःऽवयम् १.११०.३; ४.३६.४
चतुःऽशतम् ८.५५.३
चतुःऽशृङ्गः ४.५८.२
चतुःऽसमुद्रम् १०.४७.२
चतुःऽसहस्रम् ५.३०.१५
चतुरः १.२०.६; ४१.९; १६१.२; ४; ४.३३.५; ६; ३५.४; ९.३३.६; १०.११४.६
चतुर्णाम् ८.७४.१३
चत्ता १०.१५५.२
चत्तार्थ १.१३२.६
चत्तो इति १०.१५५.२
चत्वारः १.१२२.१५; ५.४७.४; ७.१८.२३; ८.७४.१४
चत्वारि १.१६४.४५; ४.५८.३; ५.३०.१२; १४; ८.२.४१; ९.७०.१; १०.५४.४
चत्वारिंशत् १.१२६.४
चत्वारिंशता २.१८.५
चत्वारिंश्याम् २.१२.११
चन १.१८.७; २४.६; ५५.१; ५; ७४.७; ८१.५; ८४.२०; १००.१५; १०५.३; ११३.८; १३६.१; १३९.२; ५^{२}; १५०.२; १५२.२; १५५.५; १६६.१२; १९१.७; २.१६.२; ३; २३.५; २४.१२; २८.६; ३.३०.१; ३६.४; ४.१८.८^{२}; ९; ३०.३; ३१.९; ५.३४.५; ७; ४१.१३; ४२.६; ८२.२; ६.३.२; २०.४; २६.७; ४७.१; ३; ४८.१७; ५४.९; ५९.४; ६९.८; ७५.१६;

७.१८.९; ३२.१; १३; १९; ५९.३; ८२.७; ८३.२; ८६.६; १०४.३; ८.१.५; २.१४; १९.६; २३.१५; २४.१५; २८.४; ४७.७; ५१.७; ५२.७; ५५.५; ६४.२; ६६.१३; ६८.१९; ७८.१०; ९१.३[२]; ९.६१.२७; ६९.६; ११४.४; १०.३३.९; ३९.११; ४८.५; ४९.५; १०; ५६.४; ५९.८–१०; ६२.९; ८५.३; ८६.११; ९५.१; ११२.९; ११९.६; ७; १२८.४; १२९.२; १५२.१; १६८.३; १८५.२

चनः १.३.६; २६.१०; १०७.३; २.३१.६; ३५.१; ६.४.२; १०.६; ४९.१४; ७.३८.३; ८.१९.११; ३२.६; १०.११६.८

चनःऽहितः ३.२.२; ७; ११.२; ९.७५.१; ४

चनस्यतम् १.३.१

चनिश्चदत् ५.४३.४

चनिष्टम् ७.७०.४

चनिष्ठत् ८.७४.११

चनिष्ठम् ५.७७.४

चनिष्ठया ९.९.२

चनिष्ठा ७.५७.४; ७०.२; ५; ८.७४.८

चनिष्ठाः ७.२०.८

चनिस्कुदत् ८.६९.९

चन्द्र ६.६.७

चन्द्र ५.१०.४

चन्द्रऽअग्राः ५. ४१.१४; ६.४९.८

चन्द्रः १.१५०.३; ८.४.९

चन्द्रऽनिर्निक् १०.१०६.८

चन्द्रऽबुध्नः १.५२.३

चन्द्रम् ३.३.५; ३१.१५; ४.२.१३; ६.६.७; ८.६५.११; १०.८५.३१; १०७.७

चन्द्रमसः १.८४.१५

चन्द्रमसा १०.६४.३

चन्द्रमाः १.२४.१०; १०५.१; १०.८५.१९; ९०.१३

चन्द्रमाःऽइव ८.८२.८

चन्द्रमःऽइव २.२.४

चन्द्रऽरथः १.१४१.१२

चन्द्रऽरथम् ३.३.५

चन्द्रऽरथा ३.६१.२

चन्द्रऽरथाः ६.६५.२

चन्द्रऽवत् ५.५७.७

चन्द्रऽवता ३.३०.२०; ५०.४

चन्द्रऽवर्णाः १.१६५.१२

चन्द्रा १.१५७.१; ४.२३.९; ९.९७.५०

चन्द्राऽइव ३.६१.७

चन्द्राः ७.३९.७; ४०.७; ६२.३; ९.६६.२५; १०.१२१.९

चन्द्राणि ५.४२.३; ९.६९.१०

चन्द्रान् ८.२०.२०

चन्द्राभिः ६.६.७

चन्द्रासः ३.४०.४

चन्द्रेण १.४८.९; १३५.४; ४.४८.१–४

चमसः ४.३५.४; १०.१६.८; १०१.८

चमसम् १.२०.६; ११०.३; १६१.१; २; ५; ४.३५.२; ३; ५; ३६.४; १०.१६.८; ६८.८

चमसा ४.३३.५

चमसाः १.५४.९

चमसान् १.१६१.४; ९; ३.६०.२; ४.३३.६

चमसान्ऽइव १०.२५.४

चमसे १०.९६.९

चमसेषु ८.८२.७

चमू इति ५.५१.४; ८.४.४; ७६.१०; ९.४६.३; १०७.१८; १०.२४.१

चमूषु ३.४८.४; ८.८२.७; ८; ९.२०.६; ६२.१६; ६३.२; ९२.२; ९३.३; ९७.२१; ३७; ४६; ९९.६; ८

चमूऽसत् ९.९६.१९

चमूऽसदः १.१४.४; ५४.९; ९.८.२; ७८.२; १०.४३.४

चम्रिषः १.५६.१

चम्रीषः १.१००.१२

चम्वः ८.२.८

चम्वा ३.५५.२०

चम्विऽइव १०.९१.१५

चम्वोः १.२८.९; १६४.३३; ४.१८.३; ६.५७.२; ९.३६.१; ६९.५; ७१.१; ७२.५;

चषालम् १.१६२.६
चषालऽवन्तः ३.८.१०
चष्टे १.१०८.१; ७.२८.४; ६०.३; ६१.१; ८.१९.१६; १०.३०.२
चष्टे १.२४.१२; ९८.१; १६४.४४; १९०.७; ३.५५.९; ५९.१; ५.१९.१; ६.२६.२; ५१.२; ७.३४.१०; ८.२५.१६; ६२.६; ९.३८.५; १०.५.१; ३४.१३; ५५.३; ९२.६; ११४.४; १३९.२; ३
चस्कन्द १०.१७.११
चाकन् १.३३.१४; १७४.५; २.११.३; १०.२९.१; ९५.४; १४८.१; ४
चाकन् १.१४८.२; १०.१३२.४
चाकन १.५१.८; १२०.१०
चाकनः १.५१.१२; ८.५२.४; ६२.४
चाकनत् १०.९१.१२
चाकनत् ८.३१.१; १०.१४७.४
चाकनन्त ५.३१.१३[२]
चाकनाम २.११.१३
चाकन्तु १.१२२.१४
चाकन्धि १०.१४७.३
चाकन्यात् १०.३१.४
चाकशीति १.१६४.२०
चाकशीमि ४.५८.५; ९
चाक्लृप्रे १०.१३०.६
चाक्लृप्रे १०.१३०.५
चाक्षमः २.२४.९
चातयते ४.१७.९
चातयस्व ५.४.६
चातयस्व २.३३.२; ७.१.७
चातयामसि १०.१५५.१
चायमानः ७.१८.८
चायमानः ६.२७.८
चायमानाः १०.९४.१४
चायमानाय ६.२७.५
चायवः ३.२४.४
चारथे ८.४६.३१
चारवः ५.५९.३; ९.७७.३; १०.९४.१०
चारीत् ७.२५.१
चारु १.२४.१; २; ५५.४; ६१.७; ७२.२, १८७.६; २.२७.८; ३५.११; ३.५.६; ३२.१; ५४.१६; १७; ५६.४; ४.२.१९; ५.७; १०; ५.३.३; ४३.३; ४८.५; ७.९८.२; ९.३४.५; ७२.७; ८६.२१; ९६.१६; ९७.२४; १०९.१४; १०.३२.४; ९६.१
चारुः १.९४.१३; ९५.५; १३७.२; २.२.८; ३.४९.३; ४.६.६; ४९.२; ५.३३.५; ६.८.१; ७.२२.२; ८.१.२६; ९.१७.८; ६१.९; १०९.१३; १०.१.२; ३१.४; ५६.१; १००.६
चारुणः ८.५.१४; ९.७०.२; ४; १०८.४; ११०.४
चारुऽतमः ५.१.९
चारुऽतमम् १.६२.६
चारुऽःवम् १०.७०.९
चारुऽप्रतीकः २.८.२
चारुम् १.१९.१; ५८.६; ७२.१०; ३.५२.५; ५.७१.१; ७.८४.३; ८.६४.१२; ९.३०.६; ४४.४; ४८.१; १०२.६; १०.२१.७; ३९.२; ९१.१४; १४४.५; १६०.३
चारूणि ९.७०.१
चारोः ३.५०.२; ५.३३.७; ७.२९.१; ६५.४
चार्षेण १०.९७.१३
चास्कम्भ १०.१११.५
चिकाय १०.८९.३
चिकाय १०.११४.९
चिकित् ८.५१.३; ९७.१४; १०२.२; १०.३.१
चिकितः १.९१.१
चिकितान् ५.६६.१
चिकितानः ३.१८.२
चिकितुः ८.५६.५
चिकितुः ३.५३.२४; ७.११.३
चिकितुषः १.७३.१; ८; १६४.६; ७.८६.३
चिकितुषा ६.६१.१३
चिकितुषी १०.१२५.३

चिकितुषे ४.१६.२; ५.४१.११; ६.४१.४; ६६.१; ७.१०४.१२; ८.१०१.१५
चिकिते ७.२३.२
चिकिते १.५१.७; ७१.७; २.४.५; २७.११; ३.५३.२३; ४.२३.२
चिकित्रिरे १.१६६.१३; १०.९२.४; १०
चिकित्रे १.१८६.९
चिकित्रे १०.३.४; ३०.६; ९१.४; ५
चिकित्वः १.७०.३; २.६.८; ३.१७.५; २५.१; २९.१६; ५.२.७; ३.७; ९; १२.२; ६.५.३; १०.४.४
चिकित्वना ८.६०.१८
चिकित्वांसः ७.६०.७
चिकित्वांसम् ४.७.५
चिकित्वान् १.२५.११; ६८.३; ७०.१; ७१.५; ७; ७२.४; ७७.५; १२५.१; १४५.१; १६९.१; ३.७.३; ९; १७.२; २९.३; ८; ४४.२; ४.३.८; ५.१२; ८.४; १२.१; २९.२; ५.२.५; ६.५२.१२; ८.६.२९; ४४.९; १०.१२.२; ५३.१; ९८.२; ५; ९९.१; ११०.१
चिकित्वित् ४.५२.४
चिकित्वित्ऽमनसम् ५.२२.३; ८.९५.५
चिकित्स १.९१.२३; ६.४७.२०
चिकित्सत् ४.१६.१०
चिकित्सन्ती १.१२३.१
चिकित्सामः ८.९१.३
चिकिद्धि ५.२२.४
चिकिद्धि २.४३.३; ४.४.११; ५.१.१०; १२.२; ८.३९.३; १०.२८.४
चिकीषते ८.७८.६^{2}
चिकेत ९.१०२.४; १०.२६.२
चिकेत १.६७.४; ५.३३.१; ६५.१; १०.५५.६
चिकेत १.३५.७; ९५.४; १००.१६; १५२.३; १६४.१६; ४८; २.४.६; १४.१०; ५.१९.१; २७.१; ७.५६.४; ६१.१; ८.२.१४; १७; ९.७; ३९.५; १०.५१.४; ५९.३; ७९.४
चिकेतत् १.३५.६; ६९.५; ५.३६.१; ६.९.३; ६२.९
चिकेतत् १.१५२.२
चिकेतति १.४३.३; ८२.४; ८.२६.१४; १०.३८.३; १४७.४
चिकेतति ५.७३.६; ६.५९.५; ८.१.३१
चिकेतथः ८.९.४
चिकेतम् १०.२८.५
चिकेतसि १.१३१.६
चिकेथे इति ५.६६.४
चिक्यतुः ८.२५.९
चिक्युः १.१६४.३८
चिक्युः १.१६४.३८; १०.११४.२; १२४.९
चिक्रदः ९.९०.४
चिक्रदत् ८.५१.४
चिक्षिपः १०.१६.१
चिच्चिकः १०.१४६.२
चिच्युषे ४.३०.२२
चित् १.४.५; ६.५^{2}; ८.९; १०.९^{2}; २४.४; ८–१०; २५.१; २६.६; २७.८; २८.५; २९.१; ३०.४; ३१.२; ६; १३; १४; ३२.८; ३३.५; १५; ३४.१; ३७.११; १३; १५; ३८.७; ९; ३९.४; ६; ४०.८; ४१.१; ९; ४२.४; ४८.१४; ४९.१; ३; ५१.३; ६; ९; ५२.७; १०; ५३.१; ५४.५^{2}; ५५.१; ५८.१; ५९.५; ६०.२; ६१.६; ८; ६२.९; ६३.१; ५; ६४.३; ६८.४; ७०.२; ७१.२; ७२.३; ८०.११; १४; ८१.२; ८४.९; ८५.४; १०; ८६.५; ८७.१; २; ९४.७^{2}; ९; १००.८; ९^{2}; १०१.४; १०४.२; १०५.७; १०७.१; ११०.२; ३; ११६.३; २२^{2}; ११७.७; १२०.२; ६; १२१.१०; १२४.१२; १२५.७; १२७.३^{2}; ४^{3}; १२९.१–५; १०^{4}; १३२.४^{2}; १३३.२; १३५.९^{2}; १३६.१; १३८.३; १४०.११; १४८.३; १५०.२; १५२.३; १५६.१–३; १५८.२; १६४.६; १६५.१०; १६७.२; ७; ९; १६८.४; १६९.१^{2}; ३; ५; १७३.५^{2}; ७; ८; ११^{2}; १२; १७६.४;

१७८.२; १७९.२^{२}; ४; १८०.७^{२}; ८; १८२.३; १८४.१; १८५.८; ९; १८७.७; १९१.१०–१२; **२**.१०.३; ११.२; ७; १२.८; १३^{२}; १५; १५.९; २०.५; २३.२; ११; २४.५; २६.४; २७.३; ५; ११^{२}; १४; ३०.४; ८; ३३.१२; ३८.२^{२}; ३^{३}; ४२.१; **३**.१.२; ९; १३; ६.२; ७; १०; ७.१०^{२}; ९.७; ३०.२; ५; ७; ३१.९; १२; १६; ३२.१६; ३५.२; १०; ३६.६; ३९.२; ३; ८; ४५.१; २; ५३.२२^{३}; ५४.४; ५६.४; ७^{२}; ५७.१; ५८.४; ५; **४**.२.७; १८^{२}; ३.४; १०; १४; ६.१; ७; ७.९; १०; ८.३; १०.५^{२}; ७; ११.१; ६; १२.४^{२}; ५; ६; १६.३; ५; ६; १६; १७; २०; १८.१; ८^{२}; २०.९; २२.१; २३.७; २८.५; २९.१; ३०.९; ३१.२; ८; ३२.२; ३; १३; ४३.४; ४५.६; **५**.२.५; ७; १०; ७.२^{२}; ४; ६; १०; १०.४; १८.२; २०.१; २५.२^{२}; २९.४; १२^{२}; १४; ३०.४^{२}; ५; ८; १५; ३१.२; ७; १०^{२}; ११; ३२.२–५; ६^{२}; ८; ९; ३३.४^{२}; ३८.४; ३९.३; ४१.१३; १७^{२}; ४४.१०; ४९.१; ५२.१२; ५४.३; ५५.३; ५६.१; २; ४; ५८.७; ६०.२^{३}; ३^{२}; ६५.४; ६७.४; ७०.१; ७४.४; ८; १०; ७५.७; ७८.४; ७९.१; ५^{२}; ८४.३; ८६.१; ५; **६**.१.४; २.९; ३.३; ४; ४.३; १०.४; ११.३; १५.१^{२}; १७.९^{२}; १८.८; ११; १९.२; ४; १२; २२.४; ६; २३.३; २४.७; ८^{२}; २७.४; २८.५; ६^{२}; ३०.३^{२}; ३१.२; ३५.५; ३७.१; ३; ३८.२; ३९.३; ४४.१५; ४५.२^{२}; ९; ४७.१३; ४८.२१; ४९.११; १३; ५१.८; ५३.३^{२}; ६२.९; ११; ६४.६; ६५.१; ४; ६६.१; ५^{२}; ७; ६७.३; ५; १०; ७१.५; ७३.२; **७**.१.२; २२; ४.२^{२}; ८; ७.१; ८.५; ११.३; १८.१; ५; १७^{२}; १८; २०; १९.९; २०.१; ४–६; २१.७; ८; २२.८; २३.४; २७.३; ४; २८.१; ३; ३२.१; ५^{२}; ३४.२;

३७.५; ७; ३८.३; ४१.२^{३}; ४५.२; ४८.३; ५३.१; ५६.१५; २०^{२}; २३; ५७.१; ५; ५८.२; ६; ५९.७; ६०.६^{२}; ७; ९; १०^{२}; ६७.२; ६८.८^{२}; ६९.२; ७०.२; ५; ८५.३; ८६.१; ३; ८; ८७.७; ८८.५. ९०.४; ९३.६; ९४.११; ९५.४; ९७.६; १०; ९८.७; ९९.४; १०३.८; १०४.७; **८**.१.१; ३; ७; १२; २.३५; ३९; ४.१२; १८; २१; ५.१६; २५; ३०; ३७; ६.६; ७.१५; ३४^{२}; ८.६; ७; ११.४; ७; १५.६; १६.८; १८.५; १२; १३; २२; १९.१५; ३५; २०.१; ५; १८; २१; २२; २१.१; ६; १६; २२.११; १३; १६; २४.३; १०; ११; २५.९^{२}; १५; २६.५; २७.९; १८^{३}; ३१.१५; ३२.११; १२; ३३.१४; १७; १८; ४०.१; २; १०; ११; ४५.११; १३; १४; १९; ३२; ४६.११; १६; २१; २५; २७; ५१.९; ५३.४; ६०.७; ६१.३; ४; १२; ६२.३; ५; ११; ६४.५; ६५.७; ६६.४; ५; ८; १२^{२}; ६७.१७; ६८.६; १०; ६९.१७; ७०.७; ७३.२; ५; ७७.११; ७९.४; ८०.४; ८३.९; ८६.४; ५; ८९.४; ९२.१०; २७; २९; ९३.१०; ११; ९६.२; ९८.८; १००.५; १०२.१४; २०; १०३.५; १३^{२}; **९**.६.९; १०.८; २९.५; ४७.१; ६६.१७^{३}; ६७.३०; ७२.१; ७३.९; ७९.२; ८७.३; ९१.४; ९७.२७; ३८; ५२^{२}; १०४.६; १०५.६; १०७.२; ११०.५; ६; **१०**.५.३; ८.१; ८; ९; १०.१^{२}; ३; ७; ११.३; १२.५; १५.६; २२.५; २३.२; ४; २५.३; २७.१२; २०; २८.६; ९; १०; ३१.२; ३४.८^{२}; ३९.३^{६}; १३; ४१.२; ४२.६; ४५.६; ५०.२; ६१.१८; २१; ६४.१३; ६७.११; ६९.९; १०; ११^{२}; ७३.१–३; ६; ७६.२; ५^{४}; ७७.६; ९१.१२; ९२.८^{२}; ९३.७; ८; ९४.२; ९६.१०^{२}; १०२.११; १११.२; ४; ५^{२}; ११२.१०; ११५.६; ११७.२;

४; ९[४]; १२०.४; १२१.८; १२६.८; १२७.५; १३१.२; ७; १३२.३; १३३.१; १४३.१; २; १४४.६; १४७.१; १५०.१; १५४.१–४; १७१.४; १७६.४; १७८.३
चितः १.११२.१७; १५८.४
चितन् ४.३७.७
चितन्त्या १.१२९.७
चितयत् २.३४.७
चितयत् १.१८०.८; २.२.५
चितयत्ऽभिः ५.४१.७
चितयन् ५.१५.५
चितयन्त २.३४.२; ४.५१.३; १०.९५.३
चितयन्तः १.३३.६; ९४.४; १३१.२; ५.१९.२; ६.१.२
चितयन्तम् २.२.४; ६.६.७; ७.६०.६
चितयन्ते १.१७१.५; ५.५९.२
चितयन्त्या ६.१५.५
चितयेम ४.३६.९
चितयेम २.२.१०
चितानाः ९.१०१.११
चितासः ७.१८.१०
चिते १०.१४३.४
चित्तः ९.६५.१२
चित्तऽगर्भासु ५.४४.५
चित्तम् १.१६३.११; १७०.१; ५.७.९; १०.१०३.१२; १२८.६; १६६.४; १९१.३
चित्तानि ७.५९.८
चित्तिः १.६७.५; १०.८५.७
चित्तिऽभिः ३.२.३; ३.३; ५.४४.१०; ८.४४.१९; ५९.३
चित्तिऽभिः १.१६४.२९
चित्तिम् २.२१.६; ४.२.११
चित्ती ८.७९.४
चित्र ८.४६.२०
चित्र ४.३२.२; ५.३९.१; ६.६.७; ४६.२; ५; ७.२०.७; ८.२१.१७; ९७.१५
चित्रऽआयुः ६.४९.७
चित्रऽऊतयः १०.१४०.३
चित्रः ८.२१.१८
चित्रः १.४८.११; ६६.३; ८८.२; ९४.५; ११३.१; १६६.४; १७२.१[२]; २.८.४; ३.२९.६; ४.३१.१; ६.४.६; ४८.९; ७.३.६; ९.८६.३४; १०.१.२; १००.१२; ११५.१
चित्रऽक्षत्र ६.६.७
चित्रऽतमः १.१०८.१; ६.३८.१
चित्रऽतमम् ४.२३.६; ६.६.७; ९.६८;१०
चित्रऽतमा ४.१.६
चित्रऽदृशीकम् ६.४७.५
चित्रऽध्रजतिः ६.३.५
चित्रऽबर्हिषम् १.२३.१३; १४
चित्रऽभानवः १.६४.७; ८५.११
चित्रऽभानुः १.३५.४; २.१०.२; ७.९.३
चित्रऽभानुम् ७.१२.१; ८.४४.६
चित्रभानो इति चित्रऽभानो ५.२६.२
चित्रभानो इति चित्रऽभानो १.३.४; २७.६; १०.५१.३; ६९.११
चित्रम् १.९.५; ३४.१०; ३७.३; ४४.१; ७१.१; ९२.५; १३; ११०.९; ११३.१५; २०; ११५.१; १३९.८; १४२.४; १४८.१; २.१३.१३; १४.१२; २३.१५; ३४.१०; ३.२.१५; ३०.१३; ६१.६; ४.७.१; ६; २३.२; ३२.२; ३६.९; ५.३.३; ५.३; १३.६; ६३.४; ८२.३; ६.६.७; १०.५; ६५.२; ६६.९; ७.४५.४; ६१.५; ६८.५; ७४.२; ७५.२; ८१.५; ८.१३.५; २१.१; ४६.२७; ६७.३; ८१.१; ९.४.१०; १९.१; ६१.१६; १०.२.६; २१.४; ३६.१३; ३७.१०; ४७.१–८; ९९.१; १०६.९; १०७.१०; ११२.९
चित्रऽमघा ७.७५.५; ७७.३; ८.५८.३
चित्रऽमघे १.४८.१०
चित्रऽमहसम् १०.१२२.१
चित्रया २.१७.८; ८.६६.८; १४
चित्रऽयामम् ३.२.१३
चित्रऽरथम् १०.१.५

चेतयति १.३.१२
चेतयते ९.८६.४२
चेतयध्वम् ३.५३.११
चेतयन्ती १०.११०.८
चेतयेथाम् ८.९.१०
चेतसा ५.७३.६; ९.१६.४; २०.३; ८३.२; ८६.४२; १०.४६.८
चेतारः ७.६०.५
चेतिं १.९३.४; ४.१६.१४
चेति १.९२.१२; ११९.४; ३.१२.९; ४.३७.४; ४३.६; ५५.४
चेतिष्ठ ८.४६.२०
चेतिष्ठः १.६५.५; ५.२७.१
चेतिष्ठम् १.१२८.८; ७.१६.१; १०.२१.७
चेतुना ५.६५.३; ९.८१.३
चेत्ता १.२२.५
चेत्तारम् १०.१२८.९
चेत्यः ६.१.५
चेत्या १०.८९.१४
चेदयः ८.५.३९
चेरवे ८.६१.७
चैद्यः ८.५.३७
चैद्यस्य ८.५.३८
चो इति ५.२९.१३; ६.६६.३
चोद १.४८.२; ७.९६.२
चोदः ५.६१.३
चोदः १.१४३.६
चोदत् ७.२७.३
चोदत १.१६८.४; ५.५६.७
चोदते ९.६९.२
चोदऽप्रवृद्धः १.१७४.६
चोदम् २.१३.९
चोदय ६.४७.१०; ७.७७.४
चोदय १.९.५; ६; १०२.१०; ६.४८.९; ५३.३; ७५.१३; ७.३२.१५; ८.२३.२८; २४.२५; ९.८.३; ५०.१; ६५.१२; ७५.५; ८५.२; ११०.७; १०.१४१.५; ६
चोदयः १.१७५.३
चोदयः ६.२६.३; ९.१७.५; १०.२२.१०
चोदयत् १०.८०.२; १२३.१
चोदयत १०.१०१.१२
चोदयत १.१८८.८
चोदयतम् १०.३९.२
चोदयत्ऽमति ५.८.६
चोदयत्ऽमते ८.४६.१९[२]
चोदयन् १.८०.५; ८.९९.४; १०.१०२.१२
चोदयन्ता १.११७.३
चोदयन्ती ७.७९.५
चोदयाते ८.२४.१३
चोदयामि १०.१२०.५
चोदयासि १.९४.१५
चोदयासे ६.४६.१३; १०.२९.८
चोदयित्री १.३.११; ७.८१.६
चोदस्व १.१०४.७; ८.७५.६
चोदामि ३.४२.८; ८.६८.७
चोदितः ९.७२.५
चोदिता १.५१.८; २.१२.६; ८.८८.६; १०.२४.३; ४९.१; १३३.१
चोदितारा ५.४३.९
चोदिष्ठेन ८.१०२.३
चोदीः १.६३.४
चोदेथाम् ७.७४.२
चोदौ २.३०.६
चोष्कूयते ६.४७.१६
चोष्कूयमाणः १.३३.३
चोष्कूयसे ८.६.४१
च्यवतानः ५.३३.९
च्यवनः २.२१.३; ६.१८.२; ८.३३.६; १०.६९.५; ६
च्यवनम् ८.९६.४
च्यवना २.१२.४
च्यवन्त १.४८.२
च्यवन्ते १.१६७.८; १०.१२४.४
च्यवम् १.१६५.१०
च्यवय १०.४२.२; १०१.१२
च्यवयति ४.१७.५; ७.१९.१
च्यवयतु १०.१७.३

च्यवयथ १.१६८.६
च्यवयन् ३.३०.४
च्यवयन्ति १.३७.११; ६४.३; ५.५६.४
च्यवयन्ते ६.३१.२
च्यवयसि ३.४३.७
च्यवयसि ८.९२.७
च्यवयामः ४.१७.१६
च्यवयामसि ४.३२.१८
च्यवानः १०.५९.१; ६१.२; ११५.६
च्यवानम् १.११७.१३; ११८.६; ५.७५.५; ७.७१.५; १०.३९.४
च्यवाना ६.६२.७
च्यवानात् १.११६.१०; ५.७४.५
च्यवानाय ७.६८.६
च्योष्ठाः १०.१७३.२
च्यौत्नः १०.५०.४
च्यौत्ना ६.४७.२; ८.२.३३
च्यौत्नानि १.१७३.४; ४.३१.९; ७.१९.५; ८.७७.९
च्यौत्नाय ६.१८.८
च्यौत्नेन १०.४९.११
च्यौत्नैः ८.१६.६

छ

छदयत् ६.४९.५; १०.३१.४
छदयति ३.९.७
छदयथः ८.१.६
छदयन्ति ५.७९.५
छदयाथ १.१६५.१२
छदिः १०.८५.१०
छन्त्सत् १.१३२.६; १०.३२.३
छन्त्सि १.१६३.४
छन्दः १.९२.६; ८.७.३६; ५२.१; १०.८५.८; १३०.३
छन्दः ६.११.३
छन्दःऽस्तुभः ५.५२.१२
छन्दयसे ८.५०.५
छन्दयाते १०.२७.८
छन्दसाम् १०.११४.९
छन्दस्याम् ९.११३.६
छन्दांसि १०.१४.१६; ९०.९; ११४.५; ६
छन्दुः १.५५.४
छन्द्यम् ८.१०१.५
छर्दिः १.४८.१५; ११४.५; ४.५३.१; ६.१५.३; ४६.९; १२; ६७.२; ७.७४.५; ८.५.१२; ९.१; १५; १८.२१; २७.४; २०; ६७.६; ७१.१४; ८५.५; १०.३५.१२
छर्दिःऽपौ ८.९.११
छर्दिषः ६.६७.११
छागः १.१६२.३
छादयासि ६.७५.१८
छायया ५.४४.६
छाया १०.१२१.२
छाया इव १.७३.८
छायाम् २.३३.६
छायाम्ऽइव ६.१६.३८
छिद्रा १.१६२.२०
छिन्धि १.१३३.२
छुबुकात् १०.१६३.१
छेदि २.२८.५
छेद्य १.१०९.३

ज

जंहः ६.१२.२
जक्षतः १.३३.७
जक्षीयात् १०.२८.१
जगत् १.४८.८; ८०.१४; ११३.४; १५७.१; १६४.२३; १८९.१; २.२७.४; ४.५३.३; ६.४७.२९; ४९.६; ८.४०.४; १०.२५.६; ३७.४; ५८.१०; ८८.४; १७३.४
जगतः १.३५.१; ८९.५; १०१.५; ११५.१; १५९.३; ४.१३.३; ५३.६; ६.२२.९; ३०.५; ४९.६; ५०.७; ७.२७.३; ३२.२२; ६०.२; ६६.१५; १०१.२; ६; १०.६३.८; १०२.१२; १२१.३
जगता १.१६४.२५

जगताम् २.३१.५; १०.७५.२
जगति १.१६४.२३
जगती १०.१३०.५
जगतीषु १.१५७.५; ६.७२.४
जगत्ऽपौ ८.९.११
जगन्थ १०.१०८.७; १८०.२
जगन्म ४.१६.१८
जगन्वांसः ८.४५.१९
जगन्वांसा ५.६४.१
जगन्वान् १.११७.१५; ३.३८.६; ७.८८.२; १०.१०.१
जगाम ७.८८.५; ८९.३
जगम्यात् १.५८.९; ६०.५; ६१.१६; ६२.१३; ६३.९; ६४.१५; १०४.२; ५.३३.५; ६.५०.८; ८.८०.१०; ९.९३.५
जगम्याम् १.११६.२५
जगम्युः १.१७९.१; २
जगाम १०.५८.१–१२; १७९.२
जगाम १.१४५.१; १७९.६; ५.३१.१२; ७.१८.९; ८.४.११; १००.१०; १०.२८.१; ११४.१
जगायात् १०.२८.१
जगार ४.१८.८
जगार १०.२७.१३; २८.९; ३१.१०; ५५.५
जगुरिः १०.१०८.१
जगृधुः २.२३.१६
जगृभथुः ६.७२.४
जगृभुः ५.२.५
जगृभ्म १.१३९.१०; १०.४७.१
जगृभ्यात् ५.४२.२; १०.३१.२
जगृभ्रिरे ४.७.२
जगृभ्रे १.१४८.३; ७.४.३
जगृभ्रे ५.३२.११; ७.१८.८; १०.६१.८
जगृभ्वान् ४.२३.४
जगृहे १०.१२.५
जग्धम् १.१४०.२
जग्ध्वाय १०.१४६.५
जग्मतुः १०.४०.१४
जग्मथुः ८.७३.४; १०.२२.६
जग्मयः १.८५.८; ८९.७
जग्मये ६.४२.१; ८.४६.१७
जग्मिः २.२३.११; ७.२०.१; ८.९३.२२
जग्मिरे ६.१९.५; १०.५.२
जग्मी इति १०.१०६.८
जग्मुः ३.१.१३; ६.३४.१; १०.६.६; १३१.२
जग्मुः १.३२.२; ३.३६.६; ६०.१; ४.३३.६; ४१.८; ५.४१.४; ५६.२; ६.२४.६; ८.२४.११; १०.१११.८; १०
जग्मुषः ७.३९.३
जग्मुषी १.११९.५
जग्मुषीः १.१२२.१४
जग्मे १.१६४.८
जग्म्यातम् ६.५०.१०
जग्रभ ८.६.१०
जग्रभ १०.१८.१४
जग्रसानाः १०.९४.६
जग्रसानान् ४.१७.१; १०.१११.९
जग्रसीत ५.४१.१७
जग्राह १०.१६१.१
जघनत् ९.२३.७
जघना १.२८.२
जघनान् ६.७५.१३
जघने ५.६१.३
जघन्थ १.५२.१५; ८०.२; २.१५.९; ३०.४; ७.२१.६
जघन्थ १.८०.४; ३.३०.८; ६.३१.४; ७.१८.२०; ८.६.१४; ९६.१७; १०.७३.६; ७; १११.६
जघन्वान् १.३२.११; ५२.८; ५९.६; ८०.१०; १७४.६; २.१४.७; ३.३२.६; ३६.८; ४.१७.१; १८.७; १९.८; ४२.७; ५.३२.२; ७.२३.३; १०.८.८; २७.३; ११३.२
जघान १.८४.१३; २.१२.१०; ११; १४.२–५; ४.१८.९; ५.२९.८; ८५.१; ६.१७.९; ९.२३.७; १०९.१४; १०.२३.५; ८९.७
जघान १.३२.७; ५१.९; २.१५.१; ३.३३.७; ५.३२.३; ४; ६; ६.४४.१४; ७.१८.१७; २०.३; २१.४; ३३.३; १०.८९.२

जनऽपानम् ९.११०.५
जनऽभक्षः २.२१.३
जनम् १.३१.१७; ४०.७; ४४.६; ४५.१; ९; १०; ४९.२; १६६.८; २.२३.४; ३०.११; ३.५३.१२; ४.९.१; ५.१३.३; ६५.६; ८०.२; ६.१६.६; १९.१२; २१.४; ३४.४; ४९.१; ५२.१२; ७.३६.२; ८.५.३३; ६.४८; ४४.९; ९.६३.२४; ७१.८; ८०.५; ८४.१; ३; १०.५३.६; ६०.१; ६३.९; १८०.३
जनमाने ८.९९.३
जनम्ऽजनम् ५.१५.४; १०.९१.२
जनम्ऽसहः २.२१.३
जनय ९.९६.१२; ९७.३६; १०.५३.६
जनय १.११३.१९; ७.४१.३; ८.१३.७
जनयः १.६२.१०; ७१.१; ८५.१; १८६.७; ४.५.५; १९.५; ५.६१.३; १०.१८.७; ४०.१०; ४३.१; ११०.५; १२४.७
जनयः १०.५५.२
जनयत् ६.५२.१६; १०.४५.८
जनयत् १.७१.८; १०.६७.१
जनयत १.९५.४; ३.२९.५; ९.९५.१
जनयतम् १.१८५.३
जनयतु १०.८५.४३
जनयथ १०.९.३
जनयथ ५.५८.४
जनयन् १.३२.४; १४०.८; ३.२.१२; ३४.४; ४.२१.५; ६.३०.५; ७.५.६; ७; ९.३.१०; २५.५; ४२.१[२]; ६६.४; ७८.१; ८६.२०; ३३; ९७.४०; १०६.१२; १०७.१८; २६; १०८.१२; ११३.६; १०.३.२; ८.४; ५५.८; ८१.२; ३
जनयन् १०.६६.९
जनयन्त ३.३१.२; ४९.१; ७.२२.९; १०.८७.१३
जनयन्त १.९५.२; १४१.२; ३.२.३; ५.४९.३; ६.७.१; २; ७.१.१; ३१.११; १०.६६.२; ९१.६
जनयन्तः १.८५.२; ७.७५.३; ९.७३.२; १०.६५.११
जनयन्त्वा ७.९९.४
जनयन्तीः १०.१२१.७; ८
जनयस्व ६.१८.१५
जनयामि १.१०९.२
जनये ७.२६.१; १०.९१.१४
जनऽयोपनः १०.८६.२२
जनऽराज्ञः १.५३.९
जनऽश्रियम् ६.५५.६
जनसी इति २.२.४
जनस्य १.७०.१; ३.४३.५; ५.११.१; ६.२२.९; ३८.१; ८.१९.१५; २१.११; ९.३५.५; ९१.२; १०.९२.३; १५९.६; १७४.५
जना १.१३१.३; ९.८६.४२
जनाः १.७४.५; ८९.१०; १०२.५; ६; २.२४.१०; ३.२.५; ५९.८; ४.३८.९; ६.११.४; ५१.११; ७.६३.४; ८.१.३; ५.३८; ४०.७; ४३.२९. ४६.३२; ७४.६; १०.४२.४; ४५.६; ५३.५; ८९.८; १४०.६
जनाः ५.३१.१२; १०.५३.४
जनात् १०.८५.३१
जनान् १.३५.५; ३७.१२; ५०.३; ६; ५९.१; ६४.१३; १२०.११; १३२.५; १४०.१२; १७३.८; २.२.१०; २०.२; ३.४६.२; ५९.१. ५.३३.२; ६.१०.५; २०.१; ४६.४; ४९.१५; ६७.१; ३; ६८.५; ७.१८.११; ५५.७; ८.१९.१४; ३२.२२; ६०.१६; ९.९२.३; १०.१४.१२; ६०.३
जनानाम् १.२५.१४; ६६.२; ७५.३; ४; ८१.९; १७७.१; १९१.४; ३.१८.१; २३.३; ३०.१; ४.४.९; ९.५; १६.१७; ५.१.१; २.६; १६.२; ६६.४; ६.१.५; ७.१; ३६.४; ४४.९; ४५.९; ७.१६.२; ७; ४९.३; ५६.२४; ६१.५; ६३.२; ७४.६; ७५.४; ७९.१; ८३.३; ८.१.४; ५.१३; १५.१०; १९.३३; २४.४; ४५.२८; ५४.७; ६४.३; ८१.७; १०३.६; ९.५२.४;

जमदग्निऽदत्ता ३.५३.१५
जमदग्निऽवत् ७.९६.३; ९.९७.५१
जम्भथ १.२९.७; २.२३.९
जम्भयतम् १.१८२.४
जम्भयन् १.१९१.८
जम्भयन्तः ७.३८.७
जम्भेऽसुतम् ८.९१.२
जम्भासः ८.६०.१४
जम्भिषत् १०.८६.४
जम्भे १.३७.५
जम्भेभिः ७.७.२
जम्भैः १.१४३.५; १४८.४; ४.७.१०; ७.३.४; १०.८७.३; ११३.८
जय ६.३५.२; ८.८९.४
जय ६.७५.१; ८.१५.६; १२; ७५.१२
जयत् १०.४३.५
जयत १०.१०३.१३
जयत १०.१०३.२
जयतः १०.३४.७; ३८.२
जयतम् ८.३५.११
जयतम् १.१०८.१३
जयताम् १०.१०३.९; १०
जयताम्ऽइव १.२३.११; २८.५
जयति ४.२१.४
जयति १.३६.४; ४.५०.९; ६.७५.५; ७.३२.९; ९.८६.४०
जयतु ६.४७.२६
जयन् ४.१७.१०; ५.३१.६; ६.७३.२; ९.८५.४[२]; १०.१०३.४
जयन्तम् १.९१.२१; ५.४४.१; ६.७५.१८; १०.४६.५; १०३.६; १२०.४; १६७.२
जयन्ताम् १०.८७.१९
जयन्ति ८.१६.५
जयन्ती १.११६.१७; १२३.२; १०.१५९.५
जयन्तीनाम् १०.१०३.६
जयन्तु ६.४७.३१; १०.१०३.११
जयसि ९.८३.५
जयाः १.८०.३

जयाति ५.३७.५; १०.४२.९; ५२.५
जयाथ १०.१०१.७
जयासमसि ४.५७.१
जयामि १०.४८.१
जयाव १.१७९.३
जयासि ६.३५.२; ८.९६.७
जयुषा १.११७.१६; ६.६२.७; १०.३९.१२
जयेथे इति ६.६९.८
जयेम १.८.३; १२३.५; ८.२१.१२; ६८.९; ९२.११; ९.६१.२३; ८५.८
जयेम १.१०२.४; २.४०.५; ४.२०.३; ५.२.११; ४.१; ६.८.६; ७५.२[२]; ७.८२.१; ९८.४; १०.१८.९; ४२.१०; ४३.१०; ४४.१०; १०२.११; १२८.१
जरणा १.१२१.६
जरणा ४.३३.३
जरणाऽइव १०.४०.३
जरणाः १.१४१.७
जरणाम् ७.३०.४; १०.३७.६; ३९.८
जरणिऽप्राः १०.१००.१२
जरण्यया १.११९.७
जरण्युः १०.६१.२३
जरतः १०.३४.३; ८०.३
जरतम् ७.६७.१०; ६९.८
जरत्ऽअष्टिः १०.८५.३६
जरत्ऽअष्टिम् ७,३७.७
जरताम् ४.४.८
जरतीभिः ९.११२.२
जरते ६.६५.४
जरते १.५९.७; १२७.१०; १८१.९; ७.६८.९; ७८.२; १०.४५.१; ६९.१
जरतोःऽइव ८.७३.११
जरत्ऽविषस् ५.८.२
जरध्यै ७.६७.१
जरन्त १०.३१.७
जरन्तम् १.११७.१३
जरन्ता १.१६१.७
जरन्ति ६.२४.७

जर्हृषाणः १.५२.२; ७.२१.४; १०.१६.७; १०२.४
जलाषः २.३३.७; ७.३५.६
जलाषऽभेषजः ८.२९.५
जलाषऽभेषजम् १.४३.४
जल्गुलः १.२८.१–४
जल्पिः ८.४८.१४
जल्प्या १०.८२.७
जल्हवः ८.६१.११
जवनी १.५१.२
जवसा १.११८.११; ४.१७.३; २२.६; ५.७८.४; ८.८९.४
जवसा ४.२७.१
जवसे ३.५०.२
जवांसि ४.२१.८
जविनीभिः २.१५.६
जविष्ठम् ६.९.५
जविष्ठा ४.२.३
जवीयसा ८.७३.२; १०.३९.१२
जवीयान् १.११७.२; ११८.१; १८१.३; १८३.१; ९.९७.२८; १०.११२.२
जवे १.११२.२१
जवेते इति ३.३३.१
जवेन १०.१११.९
जवेषु १०.७१.८
जसमानम् १.११२.६
जसमानाय ७.६८.८
जसुः १०.३३.२
जसुम् १०.६८.६
जसुरये १.११६.२२; ६.१३.५
जसुरिम् ४.३८.५; ५.६१.७
जस्यत १.१९१.७
जस्वने ६.४४.११
जहस् ९.१४.४
जहति ४.१८.११
जहतीः ७.५.३
जहतीषु १०.९५.८
जहतुः १०.६१.६
जहा ८.४५.३७
जहाति ९.६४.२०; ७१.२; १०.१८.५
जहाति १.९५.७
जहातु ३.५३.२१
जहाम १०.५३.८
जहामि १०.१२४.२
जहामि १०.१२४.४
जहि १.१३१.७; ३.३०.६; १६[२]; ४७.२; ४.३.१४; २२.९; ५.३.७; ६.१६.२९; १७.३; २५.३; ४४.११; १७[२]; ५१.१४; ७.२५.३; १०४.२२; २४; ८.४५.४०; ५३.४; ९.८.७; ६१.२६; ६३.२८; ७८.५; ७९.३; ८५.२; ८६.४८
जहि १.२९.७; ३६.१६; ४२.२; ९४.९; १३३.३; १७६.३; ४; २.३०.४; ६.५३.४; ७.१८.१८; १०४.१९; ८.१७.९; ६१.१३; ६४.१; ९.४.३; १३.८; ६१.२८; ६७.२१; ८५.२; १०.८३.३; ८७.७; १५२.३; ४
जहितः ८.५.२२
जहितस्य १.११६.१०
जहिता ४.३०.१९
जहुः २.२४.७; ७.१८.१५
जहुः ७.६८.७; १०.७१.८
जहृषाणेन १.१०१.२
जह्नावीम् १.११६.१९
जह्नाव्याम् ३.५८.६
जाः १.१४३.८; ६.४७.२१; ९.७१.९; ९३.१
जाःपतिः ७.३८.६
जाःपतिम् १.१८५.८
जाःपत्यम् ५.२८.३; १०.८५.२३
जागर १०.१४९.५
जागरूके इति ३.५४.७
जागार ५.४४.१४[२]
जागार ५.४४.१५[२]; १०.१४४.५
जागृतम् १.२१.६; ७.१०४.२५
जागृवत्ऽभिः ३.२९.२; ७.५.१; १०.९१.१
जागृऽवांसः १.२२.२१; ३.१०.९; ६.१.३
जागृऽवांसम् ८.५.३६
जागृऽवांसा १.१३६.३
जागृवि ८.८९.१

जागृविः १.३१.९; ३.२.१२; २६.३; २९.१; २; ५.११.१; ८.४४.२९; ९.३६.२; ४४.३; ७१.१; ९७.२; ३७; १०६.४; १०७.६; १२; १०.३४.१

जागृविम् ३.२८.५; ३७.८; ६.१५.८

जागृवे ३.३.७; २४.३; ८.९२.२३

जागृहि १०.८७.२४

जागृहि ९.६१.२४; ८२.४; १०.२५.८; ८५.२७

जाग्रतः १०.१६४.३

जाग्रत्ऽस्वप्नः १०.१६४.५

जातः १.६६.४; ६९.३; ८१.५; ९८.१; १३०.९; १४५.४; १५२.५; १६५.९; २.१२.१; १३.१; २२.३; ३.३.१०; ५.८; ८.५; २९.७; १०; ३२.९; १०; ४८.१; ४.२.२; ७.९; २०.६; ३६.१; ५.१४.४; ३०.४; ६.२९.६; ७.१३.३; ३२.२३; ३३.११; ९९.२; १०१.१; ८.४५.४; ७७.८; ९.९.३; ६२.१५; ७४.१; ९४.४; १०.१.१–३; ६; २१.५; ४६.१; ३; ९०.५; १३; ९५.१२; ११०.११; १२१.१; १४८.२; १४९.३; १५३.२; १६८.३

जातःऽजातः ७.९०.२

जातम् १.८३.५; ८९.१०; ११७.१६; १५६.२; १६३.१; २.२५.१; ३.१.४; १३; २.७; २९.१३; ३१.३; ५१.८; ५४.८; ५.२.२; ३२.११; ६.७.१; १६.४०; ४२; ७.३३.१३; ८.६२.१०; ७०.५; ८९.६; १०३.१; ९.१८.२; ५५.२; ६१.१०; १३; १००.१; ७; १०.२२.११; ५५.२; ७३.१०; ८८.१६; ९०.७; १५३.१; १६२.३; १६३.६; १८३.१

जातऽविद्याम् १०.७१.११

जातऽवेदः १.४५.३; ७८.१; ३.१५.४; २९.४; ५.४.१०; ६.१६.२९; ३०; ३६; ८.४३.२; ९.६७.२७; १०.५१.१

जातऽवेदः १.४४.१; ५९.५; ७९.४; २.२.१२; ३.६.६; १७.२–४; २०.३; २१.१; २२.१; २५.५; २८.१; ४; ६; ५७.६; ४.३.८; ५.११; १२; १२.१; ५.४.४; ९; ११; ४३.१०; ६.५.३; ७.३.८; ५.७; ८; ९.६; १३.२; १७.३; १०४.१४; ८.११.३; ४; ७१.७; १०.४.७; ८.५; १५.१२; १३; १६.१; २; ४; ५; ५१.३; ७; ६९.८; ९; ८७.२; ५–७; ११; ८८.५; ११०.१; १४०.३

जातऽवेदसः ३.११.८; ६.८.१; ८.११.५; ४३.६; १०.१८८.२; ३

जातऽवेदसम् १.४४.४; ५०.१; १२७.१[२]; २.२.१; ३.२.८; ३.८; ११.४; ५.९.१; २२.२; २६.७; ६.१५.७; ४८.१; ८.२३.१; १७; २२; ४३.२३; ७१.११; ७४.३; ५; १०.६.५; १६.१०; १५०.३; १७६.२; १८८.१

जातऽवेदसा ७.२.७

जातऽवेदसि ६.१६.४२

जातऽवेदसे १.९४.१; ९९.१; ३.१०.३; ५.५.१; ७.१४.१; १०.९१.१२; ११५.६

जातऽवेदाः १.७७.५; २.४.१; ३.१.२०; २१; ५.४; २३.१; २६.७; २९.२; ४.१.२०; १४.१; ५८.८; ६.४.२; १०.१; १२.४; १५.१३; ७.९.४; १२.२; १७.४; १०.१६.९; ४५.१; ६१.१४; ८३.२; ८८.४

जातस्य १.९६.७; २.३३.३; ४.७.१०; ८.२.२१

जाता १.१८१.४; ३.३९.३; ६.६१.१२; ८.१.१८; ३९.६; ८८.४; ९.८८.२

जाताः १.२३.१२; १८४.३; ३.४.५; ५.५५.३; ८७.२; १०.७.२; ६३.२; ७२.८; ८०.६; ९०.१०; ९७.१

जातान् ४.२.२

जातानि १.१२८.४; ५.८२.९; ६.२५.५; ७.८२.५; ८.४१.७; ६२.२; ९६.६; ९७.९; १००.४; १०.१२१.१०; १५३.५

जातासः ९.१०६.१; १०.१२.३

जातासु ३.५५.५

जातु १०.२७.११

जातूऽभर्मा १.१०३.३

जातूऽस्थिरस्य २.१३.११
जाते ३.३१.१०; ४.३.११; ८.९९.३; १०.८८.२; १३०.६
जाते इति १.१८५.१; ५.४७.५; ९.९.३
जातेन २.२५.१; १०.४५.१०
जातेभिः ३.३१.११
जातेषु ४.१८.४
जातैः ५.१५.२
जातौ २.४०.१; ५.७३.४; ७.३३.१३
जानत १.६८.४; ८.७२.१४
जानता ५.५१.१५
जानताम् १०.१९१.२
जानती १.१०४.५; १२३.९; १३४.१; ३.३१.६; ५.४५.२
जानतीः १.१४०.७; ३.३१.४; ४.१.१६
जानते ३.५७.३; ७.७६.५; १०.३०.६; ७१.२
जानन् १.१४०.७; ३.२९.१०; ९.७०.६; ९६.७
जानन्तः १.१५६.३; १०.१२३.४
जानन्ति ३.७.५; १०.११४.२
जानन्ति ३.३०.१३
जानम् १.३७.९; ५.५३.१; १०.३२.३
जाना १.९५.३ १०.७२.१
जानात् १०.१३९.६
जानाति ५.६१.७
जानाति ४.४.६; ६.९.३
जानामि १.१६४.३७; ६.९.२
जानीत १.९४.८
जानीथ ८.१८.१५
जानीमः १०.३४.४
जानीहि १.५१.८; ७.५४.१
जानु १०.१५.६
जाम् ९.८९.२; १०.३.२
जामयः १.२३.१६; ३१.१०; ३.५७.३; ६.२५.३; ८.१०२.१३; ९.२६.५; ६५.१; ६६.८; ८९.४; १०.१०.१०
जामये ३.३१.२
जामर्येण ४.३.९
जामातुः ८.२६.२१
जामातरम् ८.२६.२२
जामाता ८.२.२०
जामि ३.५४.९; ७.७२.३; ८.६.३; ७२.४; १०.८.७; १०.४
जामिः १.६५.४; ७५.३; ४; १२३.५; ४.२५.६; ९.१०१.१४
जामिऽत्वम् १.१६६.१३; १०.५५.४; ६४.१३
जामिऽत्वाय १.१०५.९
जामिऽभिः १.७१.७; १००.११; ८.७२.१४; ९.२८.४; ३७.४; ६८.४; ७२.३
जामिम् १.१११.३; १२४.६; ३.२.९; ४.४.५; ६.४४.१७; ८.१२.३१; ९.९६.२२
जामिऽवत् १०.२३.७
जामिषु १०.२१.८
जामी इति १.१५९.४; १८५.५
जामीन् ६.१९.८
जामीनाम् ३.१.११
जाम्योः ५.१९.४
जायत १.१२८.१; ४.१.११
जायताम् १.१०५.१५; १०.४३.९; ६२.८
जायते १.३१.११; ३.४.९; १०.६; ३९.१; ६.४८.५; ७.२.९; ५०.३; ९.४७.३; १०.३९.१२; ८७.१३
जायते २.३.९; ३.८.५; ४.११.४; ५.१.४; ८३.४; ६.७.३; ४८.२२; ७०.३; ७.९०.२; ८.२७.१६; ९.६८.५; ७४.४; १०.४.५; ५२.३; ६३.१३; ८५.१८; ८८.६
जायथाः ३.४८.२; ८.८९.५
जायन्ते २.३५.८; ३.३६.५; ४.११.३; ५.१९.१; ५८.५
जायमानः १.९६.१; १४३.२; १६३.१; १६५.९; ३.६.२; ५; ८.४; ४.१७.७; १८.५; २२.३; ५०.४; ६.७.५; ८.२; ९.१; १०.४; ४४.२२; ७.५.७; १३.२; ३६.३; ६७.२; ९९.२; ८.९६.१६; ९.५९.४; ९६.१०; १०.४५.६; ७९.४; ८५.१९
जायमानम् १.६०.३; १६४.४; ६.७.४; ९.११०.८; १०.८९.१३

जायमानस्य १.९६.७; २.९.५
जायमाना १.९२.१०; ३.३९.२; ६.६७.४; १०.६१.१९
जायमानाः ६.५२.४
जायमानात् १.९५.५
जायमानाम् ५.४२.१३
जायमाने ८.७०.४; १०.९५.७
जायमानौ २.४०.२
जायवः १.११९.३; १३५.८[2]
जायसे ५.३.१
जायसे १.१२७.९; २.१.१; ५.११.३; ६; ८.४३.९
जायस्व १०.१८३.१; २
जाया १.१०५.२; ३.५३.४; ६; १०.१७.१; ३२.३; ३४.३; १०; १३; ८५.२९; १०९.४
जायाऽइव १.६६.३; १२४.७; ४.३.२; ९.८२.४; १०.१०.७; ७१.४; ९१.१३
जायाम् १.८२.५; ११६.१; ११७.२०; ४.१८.१३; १०.३४.२; ४; ११; ८५.२२; ३८; १०९.५; १४९.४
जायुः १.६७.१
जाये १०.९५.१
जायेमहि १.९७.४; ४.२.१५
जायेमहि २.३३.१
जारः १.४६.४; ६६.४; ६९.१; ५; ११७.१८; १३४.३; ६.५५.४; ५; ७.९.१; १०.१; ९.३८.४; ९६.२३; १०१.१४; १०.३.३; ११.६; १११.१०; १६२.५
जारःऽइव ७.७६.३
जारम् १०.१०६.७
जारम् १.१५२.४; ९.५६.३; १०.७.५; ४२.२; १२३.५
जारम्ऽइव ९.३२.५
जारयत्ऽमखः १०.१७२.२
जारयायि ६.१२.४
जारस्य १.९२.११
जारिणीऽइव १०.३४.५
जारिषुः १.१२५.७; १३९.८[2]
जार्यम् ५.६४.२

जाऽवतः ८.९४.५
जासु ७.४६.२
जाहुषम् १.११६.२०; ७.७१.५
जिगत्नवः ९.१०१.१२; १०.७८.३; ५
जिगत्नु ७.६५.१
जिगत्नुम् ९.९७.१७
जिगत्नू इति १०.१२०.७
जिगर्तिम् ५.२९.४
जिगात् ९.७१.५
जिगात १.८५.६; ७.५७.७
जिगातन ५.५९.६
जिगातम् २.२४.१२
जिगाति ५.८७.४; ७.४.१; ७१.४; १०४.१७; १०.१२३.८
जिगाति १.२.३; ८७.५; ३.४.३; १२.२; २७.१; ३९.१; ६२.१३; ६.६.१; ७.७५.४; ८४.१; ८.४९.२; ९.१४.६; ९६.९; १०.६.४; ८.२; ४७.६
जिगातु ८.४५.३२
जिगातु २.३४.१५
जिगाय ३.३४.४; ५.४५.६; १०.१०२.९
जिगाय १.३०.१६; ११६.२; ६.३२.२; १०.६९.११; १०२.५
जिगासि १०.७३.३
जिगासि ३.२२.३; ५.१५.४
जिगीवांसः २.१८.८; ५.६२.९; ६.१९.७; १०.७८.४
जिगीवान् २.१२.४
जिगीषमाणम् १.१६३.७
जिगीषसे १०.४.३
जिगीषा १.१७१.३; १८६.४
जिगीषुः २.३८.६
जिगृत ७.५७.६
जिगृतम् १.१५८.२; ४.५०.११; ७.६४.५; ६५.५; ९७.९
जिगेथ १.१०२.१०; ९.६६.१६; १०.६९.६
जिग्यथुः ६.६९.८
जिग्युः ८.१९.१८; १०.८७.१९; १०७.९[4]

जुषध्वंम् ५.५५.१०; १०.१५.४
जुषध्वम् १.१३९.११; ५.५८.३; ७.५६.१४; १०.५३.४
जुषन्त १.१४८.२; १६७.४; ७.५.६; ११.४; ५६.२०; ८.१३.६; ९.१०२.५
जुषन्त १.३.९; ६८.२; ५; १२७.६; २.२७.२; ४०.२; ५.४१.२; ४६.२; ६.१६.८; ५२.११; ७.३४.२५; ३५.१४; ५२.३; ५६.२५; ५८.६; ६४.१; ८.१३.२९; ९.८१.५; १०.८.३; ७०.८
जुषन्ताम् ३.२२.४; ६.५२.१०
जुषन्ताम् १०.५३.५
जुषमाणः ४.२३.१
जुषस्व १.७५.१; १४४.७; २.३२.६; ४१.१८; ३.२४.२; २८.१; ६; ३९.७; ५१.६; ५२.२; ६२.४; ५.४.४[2]; ६.२.१०; ६१.१४; ७.२.१; ८.६.३२
जुषस्व १.१२.१२; १०१.१०; ३.१.१; १४.२; १५.२; २१.१; ४; २८.२; ४; ३३.८; ३५.१०; ४०.८; ५२.१; ४; ६१.१; ६२.८; ४.२.२०; ३.१५; ५.४.८; ८.४; २९.१५; ६.५.६; ४७.१०; ७.२२.३; ४२.५; ५४.१; २; ९५.५; ९९.७; १००.७; ८.१२.५; ४३.१६; ४४.२; ५; ९०.३; १०२.२०; १०.१५.१३; ६९.३; ४; ७०.१; १२२.३
जुषाणः १.१३५.२; २.१४.९; ३.३२.५; ४३.४; ४४.१; ४.२३.१; ५८.८; ५.५१.५; ६.४७.२८; ७.७.२; १४.३; २४.४; २९.२; ९८.२; ८.१३.१३; ४४.८; ४८.२; ६५.८; ७२.२; ९७.११; १०.६.४; ६९.१०; १२२.२; १६०.२; १७९.३
जुषाणा १.११८.१०; ३.५८.७; ५.७५.३; ७.३८.४; ९५.४; ८.५७.२
जुषाणाः १.१७१.२; ३.४३.२
जुषाणौ ७.६६.१९
जुषाते ४.४३.१
जुषेत १.१३१.६
जुषेत २.१०.५; ७.३४.२१; ८६.२
जुषेताम् ५.७२.३
जुषेथाम् १.९३.७; २.३६.६; ५.७८.३; ६.६९.१; ४; ७.९३.१; ८.३५.४; ३८.४; ६
जुषेथाम् ४.५७.५; ५.५१.६; ७.७०.७; ७१.६; ७३.३; ८.३५.५; ६[2]; ३८.५
जुषेरत १.१३६.४; १०.६५.१४
जुष्टः १.४४.२; ५.४.५; १३.४; ९.९.२; १३.८; ७०.८; ९७.१९; १०८.१६
जुष्टः ९.४४.२
जुष्टऽतमः १.१६३.१३
जुष्टऽतमासः १.८७.१
जुष्टऽतरस्य ८.९६.११
जुष्टम् १.४४.४; ३.५३.३; ५९.५; ७.९७.५; ८.४४.७; ८७.३; ८९.७; ९.९७.२२; १०.८८.१; १२५.५
जुष्टयः १.१०.१२
जुष्टाः १.१०.१२; १८२.६; ५.३३.१०
जुष्टानि १.७३.१०
जुष्टाम् १.३३.२; ४.२९.३
जुष्टासः ४.३७.२
जुष्टिम् १०.११४.१
जुष्टी ७.३३.४
जुष्ट्वी १.११८.५; ८.६२.६; ९.९७.१६
जुहवाम १.११०.६; ११४.३
जुहाव ७.२१.८; ८.९.१०
जुहुऽआस्यः १.१२.६
जुहुत ७.१५.१; १०.१४.१३
जुहुते ६.१०.६
जुहुमः १०.१२१.१०
जुहुमः ५.७२.१
जुहुयाम ७.१.१७
जुहुरः ७.४.४
जुहुरन्त १.४३.८; ३.५५.२
जुहुराणः १.१७३.११; ४.१७.१४; १०.१३.५
जुहुराणम् १.१८९.१
जुहुराणा ८.२६.५
जुहुरे ५.१९.२
जुहुरे २.९.३

जुहूभिः १.५८.४; ५.१.३; १०.२१.३
जुहूमसि १.४.१; ८.५२.४
जुहूरे १.४८.१४; ८.८.६
जुहूर्थाः ७.१.१९
जुहोत १.१५.९; २.१४.१; ७.१०२.३; १०.१४.१४
जुहोत २.१४.५; ८; ९; ३.९.८; ५९.१; ५; ५.२८.६; ७.४७.३
जुहोतन ७.९८.१; १०.१७९.१
जुहोतन २.३२.७; ५.५.१; ८.४४.१; १०.१४.१५
जुहोति १०.७९.५
जुहोति १०.९९.४
जुहोमि ३.१८.३; १०.८३.७
जुहोमि १.१६२.१९; २.२७.१; १०.१७.११; १२; १९१.३
जुह्वः १.५८.७; १४५.३; ६.६६.१०; ८.४३.१०; ४४.५
जुह्वत् ७.८५.१; १०.८१.१
जुह्वतः ८.२७.२२
जुह्वति २.४१.१८; ५.७.५
जुह्वते १०.४०.४
जुह्वम् १०.६.५; १०९.५
जुह्वा १.६१.५; ७६.५; २.१०.६; २७.१; ३.३१.३; ४.४.२; ६.११.२; ७.३.४; १०.६.४; ११५.२
जुह्वानः १.७५.१; ८.२३.६
जुह्वानाः ७.९५.५
जुह्वानाय ८.२७.२१
जुह्वानासः ८.७४.६
जुह्वे १.३२.६; ४.३७.३; ६.२.३; १०.१४९.५
जुह्वे ८.३९.३
जूः २.१४.३
जूजुवत् २.३१.४
जूजुऽवांसम् ५.३१.११
जूजुऽवान् ४.११.४
जूजुवानस्य १०.९३.८
जूजुवानेभिः ५.२९.९
जूजुवः ७.२१.५
जूतः ४.१७.१२; ९.९७.५२
जूतये १.१२७.२
जूताः ९.६४.१६
जूतिऽभिः १.११६.२; ३.३.८
जूतिम् ३.३४.२; ४.३८.९; ९.९७.९
जूती ८.४१.६
जूत्या ३.१२.३
जूर्णः १.१८०.५
जूर्णाऽइव १.१८४.३
जूर्णाम् ९.८६.४४
जूर्णायाम् १.४६.३
जूर्णिः १.१२७.१०
जूर्णिः १.१२९.८; ७.३९.१; ८.७२.९
जूर्णिनी ६.६३.४
जूर्यः ६.२.७
जूर्यति १.१२८.२
जूर्यत्ऽसु ३.२३.१
जूर्यन्ति १.११७.४
जूर्यन्त्यै १.११७.७
जूर्वः ६.६.६
जूर्वन् १.१९१.९
जेः ६.४.४
जेता १.६६.२; १७८.३; २.४१.१२; ४.२०.५; ६.४५.२; ९.९०.३; १०.५५.६; १०७.११
जेतारम् १.११.२; ५.२५.६; ८.९९.७
जेत्वानि ६.४७.२६
जेन्यः १.७१.४; १२८.७; १४०.२; १४६.५; २.१८.२; ५.१.५
जेन्यम् १.१३०.६; २.५.१; ८.१०१.६; ९.८६.३६; १०.४.३
जेन्यस्य ६.४२.४; १०.६१.२४
जेन्या १.११९.५; ३.३१.११
जेन्याऽवसु इति ७.७४.३; ८.३८.७
जेमना १०.१०६.६
जेषः १.१०.८
जेषत् ८.४०.१०
जेषाम् ८.६३.११; ९.७६.५
जेषि ६.४५.१५; ९.४.१

जेषि १.१३२.४; २.३०.८; ९; ३.५४.२२; ९.४४.६
जेषे १.१००.११; ६.४४.१८
जेष्म ७.१८.१३
जेष्म ६.४५.१२; १०.१५६.१
जेष्यामि १०.३४.६
जेह्मानम् १.११०.५; १६३.६
जेह्मानस्य १०.३.६
जेह्मानाः १०.१५.९
जैत्रम् १.१०२.३; ५; १०.३६.१०; १०३.५
जैत्रस्य ९.१०६.२
जैत्रा ८.१५.३
जैत्राय ८.१५.१३; ९.१११.३
जैत्रीः ३.३१.४
जैत्रीम् १.१११.३
जोगुवानः १.६१.१४
जोगुवाम् १०.५३.६
जोगुवे १.१२७.१०; ५.६४.२
जोष १०.१५८.२
जोषत् १.१६७.५
जोषत् १०.८१.७
जोषति १०.१०५.८
जोषम् १.७७.५; ११३.१०; २.२१.३; ३०.२; ३७.१; ४.२७.२; ५.३३.२; ६.२३.८; ६४.५; ६६.४; ७.४३.४; ८.१९.२८; ९४.६; ९.७२.३; १०.९६.७
जोषयन्ते १.८३.२
जोषयासे ३.५२.३; ४.३२.१६; ५.३.१०
जोषयेते इति १.९५.५; ६
जोषऽवाकम् ६.५९.४
जोषि २.३७.६[४]
जोषि ४.९.७
जोषिषत् २.३५.१
जोषे १.१२०.१
जोष्टारःऽइव ४.४१.९
जोष्या १.१७३.८
जोह्वीति ७.३८.६
जोहुवीति ३.३३.४; ६२.२; ५.४३.१; ७.४१.५; ५६.१८
जोह्वीमि ३.४३.३; ५.४.१०; ७.९३.१
जोहवीमि १.३४.१२; १६४.५२; १७५.६; १७६.६; २.१०.६; ५.६९.३; ६.४०.३; ७.२९.४; ८.९७.१३
जोहुवत् ९.६६.२९
जोहुवतः ७.९३.३
जोहुवती ७.२४.२
जोहुवन्त ७.२१.७
जोहुवानम् ५.४२.७
जोहुवाना ५.४७.१
जोहुवानान् ७.२८.३
जोहूत्रः २.१०.१. २०.३
जोहूत्रम् १.११८.९
ज्ञातयः ७.५५.५; १०.६६.१४; ८५.२८
ज्ञाती इति १०.११७.९
ज्ञायन्ते ४.५१.६
ज्ञासः १.१०९.१
ज्ञुऽबाधः ६.१.६
ज्ञुयाः २.१०.६
ज्मः १.१५७.१; ४.५०.१; ६.६२.१; ८.१.१८; १०.८९.१; ११
ज्मन् ७.२१.६; ६०.२
ज्मयाः ७.३९.३
ज्मा ६.५२.१५
ज्मायन्तम् ८.६८.३
ज्यया १०.१६६.३
ज्या ६.७५.३
ज्याकाः १०.१३३.१–६
ज्याम् ४.२७.३
ज्यायः ६.२६.७; ७.३२.२४; ९.४८.५
ज्यायसः १.२७.१३
ज्यायस्यै १.१२४.८
ज्यायांसम् ५.४४.८
ज्यायान् ६.७५.१४; १०.५१.६
ज्यायान् ३.३८.५; ४.३०.१; ६.३०.४; ७.२०.७; ८६.६; १०.५०.५; ९०.३
ज्याऽवाजम् ३.५३.२४
ज्येष्ठः १.१००.४; ८.७०.१; १०२.११; ९.६६.१६; १०.५०.४; १६०.१

ज्येष्ठः ४.३३.५; १०.११.२
ज्येष्ठऽतमा ६.६७.१
ज्येष्ठऽतमाय २.१६.१
ज्येष्ठऽतातिम् ५.४४.१
ज्येष्ठम् १.८४.४; ५; १२७.२; १३६.१; २.३५.९; ३८.५; ४.१.२; ५.४९.२; ६.४६.५; ४८.२१; ७.४३.४; ६५.१; ८६.४; ९७.३; ८.४.४; ४६.१९; ५३.१; ७४.४; १०.१२०.१; १२४.८
ज्येष्ठऽराजम् २.२३.१; ८.१६.३
ज्येष्ठस्य ९.९७.२२
ज्येष्ठा ४.२२.९
ज्येष्ठाः १०.७८.२
ज्येष्ठाभिः ८.२३.२३
ज्येष्ठासः ५.८७.९; १०.७८.५
ज्येष्ठे २.१८.८
ज्येष्ठे इति ४.५६.१
ज्येष्ठेन ८.२.२३
ज्येष्ठेभिः १.१६७.२; १०.३.५; ६.१; ६१.१७
ज्यैष्ठ्याय १.५.६; ३.५०.३
ज्योक् १.२३.२१; ३३.१५; १३६.६; २.३०.१०; ४.२५.४; ६.१५.१; २८.३; ७.२२.६; ९.४.६; ९१.६; १०.९.७; ३७.७; ५७.४; ५९.६; १२४.१
ज्योतिः १.३६.१९; ४८.८; ५०.१०[2]; ५७.३; ५९.२; ६९.१; ८६.१०; ९२.४; १७; ९३.४; १००.८; ११३.१; १६; ११७.१७; २१; १२४.१; ३; १८२.३; २.११.१८; २७.११; १४; ३.२६.८; ३०.१४; ३१.४; ३४.४; ३९.७; ८; ४.१.१४; १०.३; १४.२; १६.४; २५.३; ५१.१; ५.६३.४; ८०.२; ६; ६.३.१; ९.४-६; ४४.२३; ४७.८; ७.५.६; ३२.२६; ३३.८; १०; ७६.१; ४; ७७.१; ७८.३; ७९.२; ८१.१; ८२.१०; ८३.१०; ९०.४; १०१.२; ८.६.३०; १२.३०; १६.१०; २४.२१; ३५.१९; ४८.३; ७३.१६; ८९.१; १०१.१२; ९.४.२; २९.२; ३५.१; ६१.१६; १८; ६६.२४; ८६.१०; ९२.५; ९४.५; ९७.४१; १०७.२६; ११३.७; १०.१२.७; ३५.१; ५; ३६.३; ३७.८; ४३.४; ८; ५४.६; ५५.२; ५६.२; ६७.४; १०; ६८.११; १०७.१; ११०.७; १३६.१; १३९.१; १५६.४; १७०.२; ३; १८५.३
ज्योतिःऽअग्राः ७.३३.७; १०१.१
ज्योतिःऽअनीकः ७.३५.४
ज्योतिःऽकृत् १.५०.४
ज्योतिःऽकृतः १०.६६.१
ज्योतिःऽजरायुः १०.१२३.१
ज्योतिःऽरथः ९.८६.४५
ज्योतिःऽरथम् १.१४०.१
ज्योतिःऽरथाः १०.६३.४
ज्योतिषः १.२३.५; २.२८.७; ४.५०.४; १०.६६.२
ज्योतिषा १.३३.१०; ९१.२२; २.१७.४; २३.२; ३४.१२; ३.२.३; ४.१३.१; १४.३; ३८.१०; ५२.६; ५.२.९; १४.४; ३१.३; ८०.५; ६.८.३; ९.१; ७२.२; ७.७८.२; ८०.२; ८.९८.३; ९.९७.३९; १०८.१२; १०.१.१; ३५.६; ३७.३; ४; ४३.९; ५५.३; ५६.१; ६८.५; ८७.१२; १२७.२; १७०.४; १७८.३
ज्योतिषाम् १.११३.१; १०.१७०.३
ज्योतिषि १०.५४.६
ज्योतिष्मत् १.१३६.३
ज्योतिष्मतः १०.५३.६
ज्योतिष्मता ७.७८.१
ज्योतिष्मती १.४६.६
ज्योतिष्मतीम् १.१३६.३
ज्योतिष्मन्तः ९.११३.९; १०.७७.५
ज्योतिष्मन्तम् २.२३.३; ८.५८.३
ज्योतींषि १.५५.६; ३.१०.५; ८.१५.५; ४४.१७; ६२.१२; ९.३६.३; ८६.२९; ९१.६
ज्रयः १.९५.९; १०१.७; १४०.९; ४.५२.५; ५.४४.६; ८.३६.१-६; ९.६८.३; १०.९२.५
ज्रयति ९.७१.५

६७.५; ७३.४; ७४.१; ८२.१; ५; ८५.७; ८७.२^{२}; ६.५.६^{२}; १७.६; १८.३^{२}; ५; १३; १५; २०.७; २१.७; २२.४; २३.५; २६.५; ७; ३०.३; ४; ३४.३; ३५.२; ३; ४४.६; ४५.२२; ३३; ४६.८; ४७.१०; १८; ४८.२२; ४९.१४^{४}; ५१.७; ५२.१; ५६.४; ६२.८; ६५.२; ६६.१; ६७.८; ६९.५; ८; ७२.१; ७.२.९; १६.४; १८.१७; ३२.२४; ३३.१०; ३४.२३^{३}; २४; २५; ३८.६; ४०.२; ५०.२; ३; ५२.२^{२}; ३; ५४.१; ५६.२५; ५८.४; ५; ५९.९; ६४.३; ६६.१२; १६; ७०.१; ८१.५^{२}; ८६.२–४; ९३.७^{२}; ९४.९; ९९.७; १००.५; ७; १०१.५; ६; १०३.५; ७; १०४.३; १२; ८.३.९^{२}; १०; २०; ४.४; १६; १७; ६.५; ९.२; १३; १३.५; २०^{२}; १५.६; १८.३; १२; १८; १९.१५; १६; २०.१४^{२}; २४.११; २५; २५.१३; १४^{२}; २१; २७.२०; २२^{२}; २८.४; ३२.३; ३३.१७; ४०.६; ४१.४; ४३.१०; ३३; ४५.६^{२}; २७; ३१; ४०–४२; ४६.२८^{२}; ४७.३; १०; १३; १४; १८; ५७.३; ५९.३; ६१.६; १३; ६२.३; ८; ९; ६३.३; १०; ६५.८; ६६.५; ६७.१८; १९; ६९.१३; ७२.१७; ८०.९; ८३.१; ८८.३; ८९.५^{२}; ६^{३}; ९२.५; ३१; ९३.४; ५; ९४.३; ९६.२; १२; ९७.१५; ९९.२; १०२.२१; ९.१.५; १९.१; ६७.२१; ७३.९; ८३.१^{२}; ९२.५; ९६.४^{२}; ९७.४१; ५८; १०१.१३; १११.२; १०.२.३–५; १०.४; १२.३; १६.६; १७.२; २२.७; २७.१८; २१; २८.८; ३०.१२; ३२.३; ४; ३४.१२; १३; ३५.८; १२; ३६.२–८; ९^{२}; १०^{२}; ११; १२; ३७.१; ६; १०–१२; ३८.२; ३९.२; ४०.९; ११^{२}; ४३.५; ४७.८^{२}; ४९.१०; ५१.१^{२}; ५३.४; ५५.१; २; ६; ५८.१–१२; ६१.५; १३; १८; २४; ६२.४; ६७.११; ६८.८; ६९.३; ७१.१; ७२.३^{२}; ७३.९; ७४.४; ६; ७६.२; ३; ७९.४; ८१.४; ८५.१४; १६; ८७.१२; ९०.१२; ९२.१३; ९३.१४; ९४.१३; ९५.५; ११; १३; ९७.४; १०३.२^{२}; १०६.१; १०८.२; ११२.४; ११४.८; ११७.४; १२०.१; ७; १२१.१०; १२४.४; १२६.२; १२९.२–४; १३५.५; १३९.४^{२}; ५; १४३.४; १४४.६; १५५.३; १५९.१; ४; १७४.४; १७९.३

ततः १.८३.५; १६४.२५; ४२; १९१.१५; ३.३७.११; ४०.९; ७.२७.३; ३३.१३^{२}; ८.५.१९; ६१.१३; ९७.३; १०.२७.२२; ८५.५; ८८.६; ९०.४; ९७.१२; १२१.७; १२५.७; १३५.६; १८६.३; १९०.१^{२}

ततः ९.११२.३; १०.१३०.१

ततक्ष १.५२.७; ३.८.६; ६.३.८; १०.१०५.६

ततक्ष १.३२.२; १२१.१२

ततक्षिरे १०.९२.७

ततक्षुः १.२०.२; ४.३४.९

ततक्षुः ४.५८.४; ८.९७.१०; १०.५.६; ४६.९; ४८.११; ८०.७

ततक्षे ५.३३.४

ततनः १.३८.१४; ७.२.१

ततनत् ८.२१.१८

ततनन् १.१६६.१४; ७.८८.४; १०.३७.२

ततनन् ४.५.१३

ततनन्त १.५२.११

ततनाम १.१६०.५; ५.५४.१५

ततनुष्टिम् ५.३४.३

ततने ७.२९.३

ततन्थ ६.१.११; ४.६; १०.१.७

ततन्थ १.९१.२२; ३.६.५; ६.६.६; १६.२१; ७.५.४; ८.४८.१३

ततऽअन्नाय ८.४७.१६

ततन्युः १.१४१.१३

ततन्वत् ६.२१.३

ततन्वान् ७.६१.१

ततप ७.१०४.१५

ततऽअपः ५.४७.२

ततपते ४.२.६

तन्वः १.३१.१२; ७२.३; ५; ११४.७; १४०.६; ११; १६२.२०; १६५.५; २.१७.७; ३६.५; ३९.६; ३.२०.२; ५०.१; ४.१६.१७; २४.३; ५.१५.३; ४१.१७; ६०.४; ८०.५; ६.४६.१२; ७.५६.११; ५९.७; ९१.४; ८.४४.१५; ४८.९; १०.४.७; ७.७; ८.३; १६.४; २८.११; १२; ५१.१; २; ४; ५४.३; ५६.१; ७२.८; ९५.५; ९; ९७.१०; ९८.१०; १००.१०; १०७.६; १०८.६

तन्वते ६.५९.७

तन्वते १.१३४.४; १५९.४; ५.१३.४; १५.३; ४७.६; ९.१०.५; ६६.५; १०.७१.९; १०१.४

तन्वन् १०.५३.६

तन्वन्तः ४.४५.२; ६

तन्वन्ति १.१९.८

तन्वन्ति ९.९९.१

तन्वम् १.१२३.११; १४७.२; ४; २.१७.२; ३.१.१; १८.४; ४८.४; ५१.११; ५३.८; ४.१६.१४; ५.८०.४; ६.११.२; ५१.७; ६६.४; ७.८.५; ९५.३; १०१.३; १०४.१७; ८.११.१०; ४४.१२; ७६.१२; ९१.६; ९६.१५; ९.७०.८; ७३.२; ९६.२०; १०.७.६; १०.३; ७; ११; १२; १३.४; १५.१४; ५६.२; ५९.५; ७; ७१.४; ८१.५; ८५.२७; १०४.९; ११२.३; ११६.६; १२०.९; १२८.१; १५७.२; १६९.३

तन्वा १.१२३.१०; १२४.६; १८१.४; २.१०.५; ३५.१३; ३९.२; ३.४.६; १५.२; ३४.१; ४१.६; ४.३८.७; ५६.६; ६.९.४; ४५.२७; ४९.१३; ७५.१; ७.३.९; १९.२; ११; ७२.१; ८६.२; ९९.१; १०४.१०; ११; ८.१.१८; १००.१; १०.१०.११; १२; १४.८; १६.५; २७.२; ३४.६; ५४.२; ६५.२; १२८.३

तन्वाथे इति १०.१०६.१

तन्वानः ३.३.६; ९.८६.३२

तन्वानम् ९.२२.६

तन्वानाः ७.१०.२; ८.४३.२०; ५९.६; ९.१०२.७; १०.९०.१५

तन्वि १.५५.८; २.१६.२; ४.६.६; ६.४९.१२; ८.९६.११; १०.६५.७; ६६.९

तन्वे १.२३.२१; ८४.१७; १६५.११; १५; १६६.१५; १६७.११; १६८.१०; १८९.६; २.३९.५; ४.१८.१०; ५.४.६; ६.१८.१४; ४०.४; ४१.५; ४६.१२; ८.१७.६; ४६.१५; ६८.१२; ९६.१०; १०.८.४; ९.७

तप ३.१८.२; ६.५.४; २२.८

तप २.२३.१४

तपः ७.८२.७; १०.१०९.१; १५४.२; १६७.१

तपःऽजान् १०.१५४.५

तपःऽभिः ७.१.७

तपत् १.१६२.२०

तपत ८.८९.७

तपतम् ७.१०४.१

तपति २.२४.९; ३.५३.२२; १०.६०.११

तपतु ८.१८.९; १०.१६.४; १८२.३

तपनः २.२३.४

तपनाः १०.३४.७

तपनी २.२३.१४

तपन्तः ५.४३.७

तपन्तम् ९.१०७.२०

तपन्ति ६.५९.८; ७.३४.१९

तपन्ति १.१०५.८; ३.५३.१४; ७.८३.५; १०.२७.२३; ३३.२

तपसः १०.१२९.३; १८३.१[२]; १९०.१

तपसा ६.५.४; ८.५९.६; ६०.१६; ९.११३.२; १०.१६.४; ८३.२; ३; ८७.१४; १५४.२[२]; १६९.२

तपसे १०.१०९.४

तपस्व १०.१६.४

तपस्वतः १०.१५४.४; ५

तपस्वान् ६.५.४

तपाति ५.७९.९

तपिष्ठ ६.५.४

तपिंष्ठाः १०.८७.२०

तपिंष्ठाम् ३.३०.१६

तपिंष्ठेन ४.५.४; ७.५९.८; १०.८९.१२

तपिंष्ठैः ४.४.१; ७.१५.१३

तपुः २.४.६; ६.६२.८; ७.१०४.२

तपुःऽअग्राभिः १०.८७.२३

तपुःऽजम्भ १.३६.१६

तपुःऽजम्भः १.५८.५

तपुःऽजम्भस्य ८.२३.४

तुपुःऽपा ३.३५.३

तपुःऽमूर्धा ७.३.१; १०.१८२.३

तपुःऽवधेभिः ७.१०४.५

तपुंषः ३.३९.३

तपुंषा २.३०.४; ३४.९; ८.२३.१४

तपुंषिम् १.४२.४; ३.३०.१७; ६.५२.३

तपूंषि ४.४.२; ६.५२.२

तपो इति ३.१८.२[२]

तपोः ९.८३.२

तुप्तः ५.३०.१५

तुप्तम् १.११२.७; ११८.७; ४.१.६; १०.३९.९

तुप्ताः ७.१०३.९

तुप्यतुः २.२४.९

तुप्यते १.१६४.१३; १०.३४.१०; ९५.१७

तम् १.४.९; १०.६[३]; १८.५; २३.२३; ३०.१०; ३१.७; १३; ३३.११; ३६.७; ११[२]; ३९.८; ४०.६; ४२.२; ४५.१०; ४७.१; ५२.३; ४; ५३.२; ५५.३; ५६.२; ५७.६; ५९.२; ६०.३; ५; ६६.५; ७३.४; ७४.५; ७७.२; ३; ७८.२–४; ८०.७; ८१.१; ८२.४; ८३.१; ८९.५; ९१.१४; ९२.८; ९६.३; १००.७[२]; ८[२]; १३[२]; १०२.१; ३; १०४.१; १०५.७; १५; १६; ११३.३; ११६.३; १६; ११७.४; १५; १२१.१०; १२३.५; १२५.१; १२७.५; १२८.२; १२९.१; २; १३१.२; ४; ७; १३२.६; १३६.४; ५[२]; १४०.८; १४१.१०; १४३.४; ६; १४४.५; १४५.१; २; ३[२]; १५१.७; १५६.३; ४[२]; १६२.१५; १६४.४९; १६६.८; १६७.७; १६९.४; १७३.५; १८०.१०; १८३.१; १८६.७; १८७.११; १९०.२; २.२.३–५; ६.३; ९.३; १३.५; १४.४; ११; २०.४[२]; २३.४–७; २४.४; ६; ७; २६.४; २७.१३; ३०.२; ९; ११; ३४.७; ९; ३५.३; ४; १३; ३७.२; ३८.९; ४०.३; ३.२.१३; १४; ८.४; ९.६; १०.९; १३.२[२]; ३; २६.२; ९; २७.४; ६; १४; २८.२; २९.१०; ३०.१९; ३१.४; १९; ४२.२; ४६.५[२]; ४७.५; ४८.२; ५३.२१; ५८.९; ४.१.९; २.८; ४.४; ५.७; ७.५; ६; १०.१; १३.३; १५.६; १०; १६.९; १६; २१.४; २४.३; ६; २५.५; ३२.१३; ३६.७; ९; ३७.८; ३९.१; ३; ४४.१; ४६.६; ५०.१; ९; ५८.११; ५.२.६; ६.१; ९.७; १४.२; ३; १६.४; १७.२; १८.३; २०.१; २२.४; २३.२; २४.२; २६.२; २९.१२; ३०.१५; ३२.६; ११; ३३.३; ३५.१; ५; ४०.९; ४२.१०; ११; ४४.१; ८; १४[३]; १५[३]; ५२.१३; ५३.१०; ५४.१२; ५६.७; ९; ५८.१; ६३.४; ८२.३; ६.१.२; ६; ७; ३.२; ५.४; ७; १०.२; ३; १५.१०; ११[३]; १६.११; १४; १५; ३२; १८.१; १९.४; ७; ११; २०.१; २१.२; ६; २२.१; २; ३[२]; ५; ७; २३.९; २४.६; १०; ३३.१; ३५.५; ३६.३; ३८.३; ४०.२; ४४.५; १४; ४५.१०; ११; १६; ४६.३; ४८.१४; ५२.१; २; ८; ५४.४; ६०.१०; ६६.११; ७५.१९; ७.१.२; ३.५[२]; ४.५; ५.९; ६.४; १६.४; १२; २०.५; २४.१; २५.२; २६.४; ३१.८; ३२.१२–१४; ४१.५; ४७.१; २[२]; ५९.८; ६८.९; ८२.७[२]; ९०.२; ९७.३–६; ९८.४; १००.५; १०४.१६; ८.२.३; ३.८; ६.९; १६; १७; २७; १२.१–३; १३.३; १७; १८; २४; १५.१; ४; १६.३; ५; ६[२]; ९[३]; १८.१४; १९.१; ६; ३२; २१.९; २३.७[२]; १६; २०; २४.१८; २६; २७.१५; ३१.२; १७; ३२.१३; ३९.८; ४०.१०; ११;

४१.२; ४३.२०; २२; २३; २८; ४६.६; ७; १२; ४७.७^{2}; १६; ५१.३; ५; ६; ५२.४; ५३.२; ८; ५८.३; ६०.१६; ६१.२^{2}; १४; ६२.१२; ६४.७; १२; ६५.७; ६८.१०^{2}; ६९.११; १७; ७०.२; ३; ८; ७१.४; ७२.३; ७५.५; १४; ८१.८; ८४.८; ८८.१; ९०.६; ९२.५; २१; ९३.७; ९५.६; ९६.६; १३; २०; ९७.२; ३; १३; १०२.१२; १७; ९.१.७; ८; २.८; ६.६; १२.५; १७.७; २६.१–६; ३५.५; ४३.१; २; ४८.१; ५२.३; ५३.४; ६०.२; ६१.१४; ६२.१७; १८; ६३.१७; ६४.२३; ६५.११; २७; ६६.२०; ६७.३०; ६८.६; ७१.२; ७४.१; ४; ८०.४; ५; ८६.३९; ९५.४^{2}; ९८.९; १२; ९९.३–५; १०१.३; ९; १०५.१; १०७.१३; १७; १०९.११; ११३.३^{3}; ११४.१; १०.६.५; ७; ९.९; १२.६; १६.४^{3}; १०; १३; १७.१२; १३; १९.४; २१.४; २७.३; ४; ७; ११; १६; ३०.२; ९; ३७.५; ६; ३८.४; ३९.१; ११; ४२.९; ४५.२; ९; १०; ४६.८; ५१.३; ५७.२; ६२.९; ६७.९; ८२.३; ६; ७; ८३.५; ८४.५; ८७.६–८; ११; १७; ८८.५; ८^{3}; १०; ९०.७; ९१.६^{3}; ८^{2}; ९७.२२; १०१.८; १०२.९; १०; १०७.५; ६^{2}; १०८.४^{2}; ७; ११०.९; ११३.१; २; ११४.४^{2}; ७; ११५.३; ११८.५; ६; ९; १२२.३; १२५.५^{3}; १२६.१; १३३.२; ४; १३४.२; १३५.४; १६०.४; १६१.२; १६२.२–६; १६३.५; ६; १६४.५^{2}; १८४.३

तमः १.३२.१०. ३८.९; ४६.६; ५४.१०; ५६.४; ८६.१०; ९१.२२; ९२.४; ११३.१६; ११७.१७; १२३.७; २.२४.३; ४.१.१७; १३.४; ४५.२; ५२.६; ५.१४.४; ३१.३; ६.८.३; १०.४; २१.३; ४८.६; ६४.३; ६५.२; ७.९.२; ७५.१; ७८.३; ७९.२; ८०.२; ८१.१; ९.१०८.१२; १०.३७.४; ६८.५; ११; ८८.१२; ११३.७; १२४.१; १२७.२; ३; ७; १२९.३; १५२.४; १७२.४

तमःऽगाम् ५.३२.४

तमःऽभिः ८.६.१७

तमःऽवृधः ७.१०४.१

तमःऽहनम् १.१४०.१

तमःऽहना ३.३९.३

तमत् २.३०.७

तमसः १.३३.१०; ५०.१०; ९२.६; १२१.१०; १७३.५; १८३.६; १८४.६; ३.५.१; ३१.४; ३९.७; ४.५१.१–३; ५.१.२; ६.५०.१०; ६५.१; ७.६७.२; ७१.५; ७३.१; १०.१.१; १०७.१

तमसा १.१२३.६; २.२३.१८; ४.६.६; ५.४०.५; ६; ९; १०.८८.२; ८९.१५; १०३.१२; ११३.६; १२९.३; १६२.६

तमसि १.१००.८; ११७.५; १८२.६; ३.३९.५; ५.३२.५; ६; ६.९.७; ७.६.४; १०४.३; १०.५१.५; ६७.४

तमसे ४.१३.३

तमांसि २.१७.४; २३.३; ४०.२; ३.२७.१३; ४.१६.४; ५०.४; ५.३१.९; ८०.५; ६.४.६; ९.१; ७२.१; ७.५६.२०; ६३.१; ७७.१; ७८.२; ८.४३.३२; ७४.५; ९.९.७; ६६.२४; १००.८; १०.१.२; ६८.९; ७३.५; ८९.२

तमिषीचीः ८.४८.११

तमिस्राः २.२७.१४

तमूऽतमम् १.१३२.६^{2}; ६.४२.३; ८.६८.७; १०.१२५.५

तम्राः १०.७३.५

तया १.२२.३; ८५.११; ३.५७.५; ६.४१.२; ४५.१४; ५३.८; ८.७४.८; ९.४५.६; ४९.२; १०.८७.१३

तयोः १.१७.६; २१.१; २२.१४; १३६.३; १६४.२०; ३.५५.११; १५; ५.८६.३; ७.१०४.१२; १०.११४.१

तरु ८.७५.१५; ९.५९.३

४.५४.५; ५.६२.१; ६९.२; ६.८.४; ७.९१.३; ८.९६.१
तस्थुषः १.६.१; ८९.५; ११५.१; ३.३८.९; ५.५३.२; ७.३२.२२; ६६.१५; १०१.६
तस्थुषीः ५.६२.२
तस्थे १.७२.९; ५.४४.९; ६.२१.७; १०.४८.५; १०९.३
तस्थौ १.६४.१३; ५.५६.८; ६.२०.१; ७.८.४; ८.१०२.१४; १०३.२; ९.८४.२; १०.२७.१४; १०५.५
तस्थौ १.३३.१४; ६४.९; १४६.२; १६४.१०; ३.७.२; ३८.४; ५५.१४; ४.५०.७; ६.६३.५; ६६.६; ८.५२.७; १०१.१४; १०.४.५; ५.६; २०.५; २८.२; ४८.१०; ७३.१०; ८८.१६; १२९.३
तस्मात् १.१६४.३२; २.२८.१०; ६.१६.३१; ७.८९.५; ८.१०१.४; १०.५१.६; ९०.५; ८; ९^{३}; १०^{३}; १२९.२
तस्मिन् १.८०.१५; १६; १४५.१^{२}; १६४.१३; १४; ४८; १७६.२; ३.३.३; ४.२.७; २४.७; ४१.४; ५.३४.९; ७.१८.१८; ६०.८; १०१.६; ८.४६.७; ९७.२; ९.११३.७; १०.१६.८; ३७.१२; ८८.७
तस्मै १.४.१०; ५.४; १२.९; ४०.४; ६८.३; ९३.२; १०; ११६.१६; १२५.५^{२}; १३२.५; १६१.१२; २.१४.२; ३; ५; २०.८; २५.४; ५; ३७.१; ३.५९.५; ४.१६.१; २५.४; ३५.६; ५०.८^{२}; ५.३४.९; ३७.१; ३९.५; ६३.१; ६.२३.९; ५२.२; ७.१९.९; २६.१; ५९.१; १०२.३; ८.८.१५; ४४.१५; २८; ४८.१०; १२; १३; ६६.७; ७५.६; ८०.१०; ९.६७.३२; १०.९.३; २८.१०; ३०.३; ७; ३४.१२; ४२.५; ७९.५; १३५.२; १६५.१; ४; १६८.४; १७३.३^{२}
तस्य १.११.६; ७; १२.८; २२.६; ३६.११; ४२.४; ५६.१; ५९.३; ८३.६; ९३.८; १००.१३; १०४.९; १४१.७; १४८.२; १६४.१; १३; २२; २.२३.१२; २४.८; २५.२; ३२.२; ३५.९; ३.१.२१; ३.९; १७.५; ३३.६; ३५.८; ३९.१; ५९.४; ४.२.६; ४.१०^{२}; २१.२; ४१.११; ४२.७; ५.१२.६; ३९.२; ४८.५; ५५.८; ८७.९; ६.७.६; २८.४; ३९.१; ४७.१३; ४९.१३; ५०.१५; ७.३१.११; ४०.३; ७२.२; ८.४.१२; १७; ७.१८; १९.६^{२}; २३.१५; २५.१६; ३१.३; ३८.१–३; ४१.३; ४५.१५; ४८.८; ६४.१०; ९.६५.९; १०.९.२; १०.१४; १५.७; २२.८; २७.२४; ४०.११; ४३.३; ५१.४; ७१.६; ८५.३; २१; ८७.१०^{२}; १७; ८८.१; २; ९१.११; ९९.१; ११७.६; १३१.७; १३३.५; १३९.१; १४९.२; १६०.३
तस्याः १.७१.१०; १६४.४२; २.७.२; १३.१; ५.२९.१४; ६.५३.९; ७.८१.४; १०.३९.६; १६१.१
तस्याम् ७.५७.४; १०.११४.३
तस्यै २.३२.७
ता १.१३.८; १५.८; १७.१; ३; २१.१; २^{२}; ३^{२}; ५; २२.२; २३.५; २८.७; ८; ३२.१५; ५१.८; १३; ९१.१९; १०९.३; ११८.१०; १२०.३^{२}; ७; १२; १३६.१; १५४.६; १६१.७; १६२.८; ९; १४; १७^{२}; १६४.१६; ३८; १६५.४; १७३.४; १७४.८; १८४.१; २.१३.२–४; १५.२–९; २४.५; ११; ३३.१३; ३४.४; ४१.६; ९; ३.३.१०; १२.३; ३१.५; ५५.६; १०; ५६.१; ४.१.७; २.२०; १६.१६; २२.५; ६; ३०.२२; ३२.११; ४१.३; १०; ४२.६; ७; ५.२९.१३; ६४.२; ६५.२^{२}; ३; ६६.२; ३; ६८.३; ७०.२; ७३.९; ८५.८; ८६.२; ४–६; ६.२.११; ४.८; १३.५; १४.६; १५.१५; १६.२४; १७.१३; २१.४; ७; २९.५; ३७.५; ६०.२; ४; ५; १२; १४; ६१.१; ६२.२–६; ६७.६–८; ६८.२^{२}; ३; ७.२.७; १९.६; २६.३; ३४.२२; ६४.४; ६५.२^{२}; ३;

६६.३; ६७.५; ७४.५; ८५.१; ९३.१; २; ९४.५; ६; ८.५.६; ३६; ३७; ८.९; २२; १०.४; २१.८; २२.६; १४; २५.१; ३; २३; २६.३; ३१.६; ८; ४०.३; ४५.२५; ७७.१०; ८६.१–३; ८७.२–४; ६; ९१.६; १००.६; १०१.२; १०२.२०; ९.८६.३८; १०.१०.१०; १४.१६; २२.११; १३; २४.६; ३९.४; ५; १३; ४०.१३; ४९.११; ५९.२; ३; ६६.७; ७३.२; ८६.२०; ९६.६; १०६.६; १२१.१०; १३२.२

ताः १.९.८; २३.१७; ८४.११; १२; ११३.१८; १२४.९; १५१.५; १५५.३; १८८.८; १९१.१२; १४; २.५.५; २३.९; ३.७.३; ४.२२.७; ४१.८; ४७.४; ५१.७^{२}; ८; ९; ५८.८; ५.२.४; १९.५; ३०.१०; ४६.७; ४८.२; ६.२८.३; ४^{३}; ६५.२; ७.२७.१; ४७.३; ४९.१–४; ५०.४; ५५.८; ८.४३.१८; ४५.३३; ६९.३; ९.९.५; ७४.६; ७८.३; ८६.२७; ३७; ८७.९; ८९.५^{२}; १०.१.४; ९.१; २७.८; ३०.५; ६१.८; ९५.६; ८; ९; ९७.१४; १५; ९८.६; १०३.११; १२४.७; ८^{३}; १३२.७; १३७.६; १६९.३

ताळिह् १०.९५.१६; १८०.२

तात् ६.२१.६

ताऽता १.१६२.१९

तात्या १.१६१.१२; ७.३७.६

तादीत्ना १.३२.४

तादृक् ५.४४.६

तान् १.१२.४; १४.७; १६.६; २३.१; ४५.२; ७४.६; ८९.३; ९४.३; १०४.२; १४७.३; १६४.१६; १९^{२}; १७७.२; १८९.७; २.१.१५; १६; २.१३; २७.१६; ३४.११; १४; ३.२१.५; ४२.५; ४५.१; ५४.२२; ४.४.१३; ५.४; ३१.१३; ३६.२; ७; ५.५१.६; ५६.२; ६.२२.८; ३३.३; ५१.९; ७.६.३; १६.८; १०; ३२.४; ३३.७; ३९.४; ५८.५; ८५.२; ९८.४; १०४.९; ८.२.११; २०.१४^{२}; ५७.३; ७५.१५; ७७.३; ९३.६; १४; ९६.९; ९.७९.३; ९१.५; ९७.२०; ९८.११; १०७.१९; १०.२२.१०; ३८.३; ६३.३; ५; ८५.३१; ८९.१५; ९०.८; ११५.९; १२८.९; १३०.६; १५४.१–४

तानि १.५३.६; ८५.१२; १३९.८; १६१.३; १६४.१९; ४३; ४५; ५०; १७१.४; १८२.४; २.३८.७; ३९.८; ३.३४.७; ३७.९; ५४.१२; ६०.१; ४.४२.२; ५५.८; ६.७.५; २५.५; ७.१९.५; २३.२; ७६.३; ८.२.३०; ४२.१; ६३.८; ९१.५; ९.९.७; २९.३; ८४.२; ९४.५; १०.५४.४; ८५.३५; ९०.१६

तान्वः ३.३१.२; १०.९३.१५

तान्वा ९.१४.४; ७८.१

तापयिष्णवः १०.३४.७

ताभिः १.१४.१२; ४७.५; ५०.९; ९१.९; ११२.१–२३; २.३२.५; ३.१७.३; २०.२; ४.३३.४; ६.२५.१; २८.३; ५८.३; ६०.८; ९; ७.३.८; ८.५.२४; ८.२०; २१; २२.१०; १२^{२}; ५९.३; ४; ९.६२.७; १०.१६.४; ८७.४; १०४.९; १६८.२; १८८.३

ताभ्यः १०.१९.८; १६९.२

ताभ्याम् ६.५७.३; ९.६६.२; १०.१४.११; ८८.१५; १३७.७

ताम् १.४६.६; ४९.४; १०८.६; १३७.३; १३८.३; १३९.७^{२}; १७५.६; १७६.६; ३.५७.६; ६२.८; ४.४२.१०; ४४.२; ५७.७; ५.४१.१८; ४६.१; ४८.४; ६.५७.५; ७.५.८; ८.१००.११; १०.२७.११; ५४.१; ६४.१२; ७१.३^{३}; ७२.५; ८५.३७; १२५.३; १३३.७; १५६.२; १७७.२^{२}

तायते १.११०.१

तायमाने १०.१७.७

तायवः १.५०.२; ५.५२.१२

तायुः ५.१५.५; ६.१२.५

तायुम् १.६५.१; ४.३८.५; ७.८६.५
तारः ८.५५.२
तारि १.११९.६; ४.१२.६; ९.९३.५; १०.५९.१; १२६.८; १४४.५; ६
तारिषः ९.७९.५
तारिषत् १.२५.१२; ४.३९.६; ८.१९.१४; १०.२५.११; १८६.१
तारिषीमहि २.२३.१०
तारिष्टम् १.३४.११; १५७.४
तारीः ६.८.७; २५.२; ८.४८.४; ७; १०.५४.५
तारीत् १.६९.३; ७३.१; १५२.३; २.२०.८; ६.४७.९; ८.७९.६; ९.११४.४; १०.६९.५
तार्क्ष्यः १.८९.६
तार्क्ष्यम् १०.१७८.१
ताळिह १०.१८०.२
तावकेभ्यः १.९४.११
तावत् ६.२३.६; ७.७९.४; १०.८८.१९; ११४.८
तावती १०.११४.८
तावान् १.१०८.२
तासाम् १.३२.८; ११२.३; १४०.८; २.५.६; ३.२.९; ६.१७.१२; १०.५.६; ९७.१८; ११४.२; १६९.४
तासु २.२८.९; ३५.१३
तिगितेन २.३०.९
तिगितैः १.१४३.५
तिग्मऽअनीकम् १.९५.२
तिग्मऽआयुधः २.३०.३; ९.९०.३
तिग्मऽआयुधाः ५.२.१०
तिग्मऽआयुधाय ७.४६.१
तिग्मऽआयुधौ ६.७४.४
तिग्मऽइषवः १०.८४.१
तिग्मऽजम्भ १.७९.६
तिग्मऽजम्भः ४.५.४
तिग्मऽजम्भस्य ४.१५.५
तिग्मऽजम्भाय ८.१९.२२; ४४.२७
तिग्मऽभृष्टिः ४.५.३
तिग्मम् १.१३०.४; ३.४८.३; ४.६.८; ६.३.४; ७.१८.१८; ८.२५.१५; २९.५; ४७.७; ७२.२; ९६.९; १०.६१.३; १८०.२
तिग्मऽमूर्धानः ६.४६.११
तिग्मऽशृङ्गः ६.१६.३९; ७.१९.१; ९.९७.९; १०.२८.२; ८६.१५
तिग्मऽशृङ्गम् १०.४८.१०
तिग्मऽशोचिषे १.७९.१०
तिग्महेती इति तिग्मऽहेती ६.७४.४
तिग्मऽहेते ४.४.४
तिग्मा ४.१६.१७; २३.७; ५.८६.३; १०.१०८.५
तिग्माः ५.१९.५; ८.४३.३; ६०.१३
तिग्मानि ९.६१.३०; १०.११६.५
तिग्माम् ४.७.१०
तिग्मे इति ९.८७.७
तिग्मेन १.३३.१३; ६.१५.१९; १६.२८; ८.४३.२६; १०.८७.२३
तितउना १०.७१.२
तितिक्षते २.१३.३
तितिक्षन्ते ३.३०.१
तितिरुः १.३३.८; २.२३.५
तितिर्वः ६.४१.४
तितिर्वांसः १.३६.७
तितृत्सात् १०.७४.४
तितृप्सात् १०.८७.१७
तित्याज १०.७१.६
तित्रतः २.३१.२
तित्विषाणः ८.९६.१५; १०.५५.१
तित्विषाणस्य ५.८.५
तित्विषे १.५२.६
तित्विषे १.१०२.७; ८.६.५; १२.२४
तिर ३.४०.३
तिर १.१०.११; ११.७; ४२.१; ९४.१६; ३.१७.२; ८.३२.३; ४४.३०; ५३.६; ९.१९.७; १०.५९.५; १३३.५
तिरः १.१९.७; ८; ४१.३; ४६.६; ५६.५; ६१.७; १३५.६; ३.२७.१३; ५८.५; ४.२९.१; ३८.४; ५.५३.१४; ७४.८;

तिष्ठात् १०.९५.१७
तिष्ठाति ४.२०.२
तिष्ठाति १.८२.४
तिष्ठाते १.१२४.११
तिष्ठाथः ८.९.८
तिष्ठे १०.१२५.७
तिष्ठेम १.११०.७; ८.२१.१२
तिष्यः ५.५४.१३
तिष्यम् १०.६४.८
तिसृऽभिः ८.६०.९
तिसृऽभ्यः २.५.५
तिसृषु ६.४७.४
तिसृणाम् ५.६९.२; ८.१९.३७. १०१.६
तिस्तिराणा १.१०८.४
तिस्तिरे ३.४१.२
तिस्थिपत् १.१६२.२०
तिस्रः १०.७०.८
तिस्रः १.१३.९; ३४.७; ८; ३५.६; ७२.३; १०२.८; ११६.४; १३३.४; १६४.१०; २५; १७४.७; २.३.२; ८; २७.८; ३५.५; ३.२.९; ४.८; १७.३; २०.२^{२}; ५६.२; ५; ४.५३.५^{२}; ५.५.८; ३५.२; ७.२.८; ३३.७; ८७.५^{२}; १०१.१; ४; १०४.११; ८.२.८; ५.८; ३२.२२; ४१.३; ९; १०१.१४; ९.५.८; ३३.४; ५०.२; ९७.३४; १०.३३.५; ६७.४; १०७.६; ११०.८; ११४.२
तीक्ष्णऽशृङ्ग १०.१५५.२
तीक्ष्णेन १०.८७.९
तीर्थम् १०.४०.१३; ११४.७
तीर्थे १.४६.८; १६९.६; १७३.११; ८.७२.७; ९.९७.५३; १०.३१.३
तीव्रः २.४१.१४; ६.४७.१; ९.१७.८; १०.७२.६
तीव्रम् ४.३५.६; ५.५.१; ३७.४; ९.६५.१५; १०.२७.२
तीव्रऽसुतम् ६.४३.२
तीव्रस्य १०.१६०.१
तीव्राः १.२३.१; ५.३०.१३; ६.७५.२; ८.२.१०; ८२.२; १०.४२.८
तीव्रान् ६.७५.७; १०.४२.५
तीव्रैः १.१०८.४; ८.६२.५; १०.४३.६
तु १.५.१; १०.११; २९.१–७; ६९.४; १३२.३; १६९.४; १७७.४; ३.३०.२; १२; ३६.९; ४१.१; ५०.२; ५१.१०; ४.१.१०; २२.५; ६; ३२.१; ५.२.७; ६.२१.८; २३.७; २९.५; ३६.५; ४८.९; ७.२९.१^{२}; ३१.४; ८६.१; ८.१.१०; १६; २६; २.२२; ७.११; १३.१४^{२}; २१.१०; २७.१४; ३२.२४; ५१.४; ६९.१६; ८१.१; ८२.४; ९५.२; ९.७२.८; ९; ८७.१; ९७.३८; १०७.२४; १०.१.५; ६; ८५.३५; ८८.६; १०१.१०
तुग्रः १.११६.३
तुग्रम् ६.२०.८; २६.४; १०.४९.४
तुग्रस्य ६.६२.६
तुग्राय १.११७.१४
तुग्र्यम् ८.३.२३; ७४.१४
तुग्र्यऽवृधः ८.१.१५
तुग्र्यऽवृधम् ८.४५.२९; ९९.७
तुग्र्यासु १.३३.१५
तुग्र्ये ८.३२.२०
तुग्वनि ८.१९.३७
तुचे ६.४८.९; ८.१८.१८; २७.१४
तुच्छयान् ५.४२.१०
तुच्छयेन १०.१२९.३
तुजः १.१५१.५; ३.३४.५
तुजतः ३.३९.८
तुजता १.६१.६; ९.९१.४
तुजन् १.६१.६
तुजम् ३.४५.४
तुजयत्ऽभिः ७.१०४.७
तुजये १०.४९.४
तुजये ५.४६.७
तुजसे ४.२३.७
तुजा १.५६.३; ५.१७.३; ६.६८.२; ८.१७.१५
तुजिम् ६.२६.४

तु॒जे॑ ८.४.१५
तु॒जे ४.१.३; ५.४१.९
तु॒जेते॒ इति॑ १.६१.१४
तु॒ज्यते १.८४.१७
तु॒ज्यमा॑नासः १.११.५
तु॒ज्या॑ः ३.६२.१
तु॒ज्या॑नि १०.१३८.५
तु॒ञ्जते॑ १.१३१.२
तु॒ञ्जन्ति॑ ९.१५.३
तु॒ञ्ज॒न्ति॒ ९.७९.५
तु॒ञ्ज॑माना: ३.१.१६
तु॒ञ्जाते॒ इति॑ १.१०५.२
तु॒ञ्जा॑नः ९.८७.६
तु॒ञ्जा॒नः ९.५७.२
तु॒ञ्जेऽतु॑ञ्जे १.७.७
तु॒तु॒ज्यात् १.१४३.६
तु॒तु॒र्यात् ६.६३.२
तु॒तु॒र्या॑त् ५.१५.३; ७७.४; ८.९६.२
तु॒तु॒र्या॑म॒ ५.४५.११
तु॒तु॒र्वणि॑ः १.१६८.१
तु॒तो॑द १.१६२.१७
तु॒द॒ ६.५३.६
तु॒दत् ८.१.११; १०.९६.४
तु॒दन्त॑ः १०.९४.१४
तु॒न्द॒ते॒ १.५८.१
तु॒न्नः ९.६७.१९; २०
तु॒भ्य॑ १.५४.९; १३५.२; २.११.३; ३.४२.८; ५.११.५; ३०.६; ७.२२.७; ८.५१.९; ७६.८; ८२.५; ९.६२.२७; ८६.३०; १०.१६७.१
तु॒भ्य॑म् १.६८.३; ७१.६; ८०.७; १२१.५; १२९.३; १३४.४[२]; ५; १३५.१; १३९.६; १७३.१३; २.२३.४; ३६.१; ५[२]; ३.१४.२; ४; ७; २१.३; ४; २८.२; ३०.२०; ३५.७; ८; ४७.३; ५०.४; ५१.६[२]; ५२.२; ८; ६०.६; ६२.७; ४.२.९; ३.१६; ६.११; १७.१; ५०.३; ५.१.१०; ६.५; ११.५; २९.५; ४३.१५; ६.१७.११; २०.२; १३; ४०.१; ४१.१; ४४.१०; २०; ७.१४.३; १९.१०; २२.७; २९.१; ३२.२१; ६४.५; ६५.५; ८६.३; ८; ९०.२; ८.२.३०; ६.३३; १२.२९; ३३.१२; ३९.३; ४३.१८; २९; ६०.१८; ९३.२५; ९.३१.३[२]; ५; ६२.२७; ६६.६; ८८.१[२]; ९४.५; १०.७.२; ५१.९; ५६.२; ८५.३८; ९१.११; १०४.१[२]; २; ३; ११६.७[३]; १४८.३; ४; १६०.१; २[२]
तु॒म्र॑ः ३.५०.१
तु॒म्र॑म् ४.१७.८; १८.१०; ६.२२.५; १०.२७.२; ८९.९
तु॒रः १.१८.२; १२१.३; १७३.९; ६.२५.५; ४४.३; ७.४१.२; ८६.४; ८.३.१३; ४१.८; १०.२५.१०
तु॒र॒ःऽपेये॑ १०.९६.८
तु॒र॒ऽगा॑तु १.१६४.३०
तु॒रणे॑ १.१२१.५
तु॒र॒ण्य॒तः ४.४०.३
तु॒र॒ण्य॒ति॒ ४.४०.४
तु॒र॒ण्यन् १.१२१.१
तु॒र॒ण्य॒न् १०.६१.११
तु॒र॒ण्यव॑ः १.१३४.५; ७.५२.३; ८.५१.१०
तु॒र॒ण्य॒ऽसत् ४.४०.२
तु॒र॒तः ६.१८.४
तु॒र॑म् ४.३८.७; ५.८२.१
तु॒रम् ७.५६.१९; ८.६६.५; ७९.२
तु॒रय॑न् ४.३८.७
तु॒रय॑न्तम् ८.९९.६
तु॒र॒य॒न्ते॒ २.३४.३
तु॒र॒ऽया: ४.२३.१०
तु॒रस्य॑ १.६१.१३; ९६.८; ५.४३.९; ८६.४; ६.१८.४; ४४.५; ७.२२.५; ८.२६.४; ७८.७
तु॒रा १०.९६.७
तु॒राः ८.२७.६
तु॒राणा॑म् १.१७१.१; ५.४१.५; ६.४८.१२; ७.४०.१; ५६.१०; ५८.५
तु॒राय॑ १.६१.१; १२१.७; ४.३.८; ६.३२.१; ४९.१२; ६६.९; १०.७३.१

तुविऽम्रक्षः ६.१८.२
तुविऽम्रक्षासः ६.६.३
तुविऽरवम् १०.९९.६
तुविऽरवान् १०.६४.४; १६
तुविऽराधसः ४.२१.२; ५.५८.२
तुविऽराधसम् ७.२३.५
तुविऽवाजाः १.३०.१३
तुविऽवाजेभिः ६.१८.११
तुविऽशग्म ६.४४.२
तुविऽशुष्म ८.६८.२
तुविऽशुष्मः २.२२.१
तुविऽशुष्मा ६.६८.२
तुविश्रवःऽतमः ३.११.६
तुविश्रवःऽतमम् ५.२५.५
तुविष्मः ७.२०.४
तुविष्मान् १.५५.१; १६५.६; १९०.३; ८; २.१२.१२; ४.५.३; २९.३; ७.५६.७; ५८.१; ८७.६; १०.४४.१; ७४.६
तुविऽस्वनः १.१६६.१
तुविऽस्वनसः ४.६.१०
तुविऽस्वनसम् ५.८.३
तुविऽस्वनि ५.१६.३; ६.४८.१५; ९.९८.९
तुविऽस्वनिः १.५८.४; १२७.६; २.१७.६; ५.५६.७
तुविऽस्वनीनाम् ८.४६.१८
तुषयन्ती १०.२७.१६
तुष्टवत् ८.८.१६
तुष्टुऽवांसः १.८९.८; २.२८.२; ७.७६.६
तुष्टुवानाः ७.५१.३
तुष्टुवुः ८.६.१२[2]; १८
तूताव १.९४.२
तूतुजान १.१३९.१
तूतुजानः १.३.६; ६१.१२; ६.२९.५; १७.५
तूतुजानः ८.१३.११; १०.४४.१
तूतुजाना ७.८४.५; ८५.५
तूतुजानाः ७.६७.६
तूतुजिः ४.३२.२; ७.२८.३
तूतुजिः १०.२२.३
तूतुजिम् ६.२०.८; १०.३५.६
तूतुमा १०.५०.५; ६
तूतूर्षति १०.१००.१२
तूतोत् २.२०.५; ७
तूतोरिति तूतोः ६.२६.४
तूयम् ३.४३.३; ५२.८; ५३.१६; ४.२६.५; ५.२९.७; ६.५.६; २२.११; ७.२९.२; ५९.४; ८.१.९; ४.३; ८; ५.७; १३; २२.१०; ६५.१. ९; १०.१०.८; १०४.१; ११०.८; ११२.२
तूयान् १०.२८.३
तूर्णयः १.३.८
तूर्णाशम् ८.३२.४
तूर्णिऽअर्थः ३.५२.५
तूर्णिऽअर्थाः ५.४३.१
तूर्णिः ३.११.५; १०.७३.४; ८८.६
तूर्णिऽतमः ४.४.३
तूर्णिम् ३.३.५; ५१.२
तूर्य ८.९९.५
तूर्वतम् ६.५०.१०
तूर्वथ ८.२०.२४; ७४.१०
तूर्वन् १.१००.५; ६.१५.५; २०.३
तूर्वन्तः ६.१४.३
तूर्वयाणः १०.६१.२
तूर्वयाणम् १.५३.१०; १७४.३; ६.१८.१३
तूर्वये ९.४२.३
तूर्वसि ८.९९.६
तूर्वुं १.११२.४
तूष्णीम् २.४३.३
तृंहत् १०.१०२.४
तृक्षिम् ८.२२.७
तृक्षौ ६.४६.८
तृळ्हा ६.१६.४८
तृळ्हाः १.१३३.१
तृणत्ति ८.१०३.५
तृणम् १.१६१.११; १६२.८; १६४.४०; १०.१०२.१०
तृणऽस्कन्दस्य १.१७२.३
तृणा ३.२९.६

४७; १७.४; २७.१; २; ४९.१[२]; ५०.११; १२; ५१.१०[२]; ११; ५२.१५; ५५.६; ६६.६; ७.१.४; १७.६; ७; २३.५; २९.४; ३०.४; ३३.९; ३५.१५; ३६.७; ३९.४; ४०.४; ४३.४; ४४.३; ४७.४; ४८.३; ५६.२; १६; ६६.९[२]; ७६.४; ५[२]; ९०.५; ९१.१; ३; ९३.३; १०४.२४; ८.७.८; ३६; १६.५; १८.५; १७; १९.१७; १८[४]; ३५; २०.१२; २५.११; १५; २७.१४[२]; २८.३[३]; ३०.३[३]; ४३.२९; ३०; ४६.३२; ४८.५; ५३.७; ५४.१; ६७.१४; ७२.१४; ७७.२; ८३.२; १०१.६[२]; १०३.१३; ९.८.२; १३.५; ६४.६; ६५.२४; ६७.१८; ७०.३; ७३.४; ७७.३; ९८.११; १०.१०.३; १५.१; ३; ४; ५[३]; ७; १२; १३; १७.४; १८.१२; १९.७; २०.८; २१.२; २७.१५; ३२.२; ३५.११; १४; ३६.१०; १३; ४४.६; ४८.११; ५०.३; ७; ६१.२७; ६२.५[३]; ६३.१; २; ७; ८; ६४.६; ७; ६५.३; १५; ६६.१५; ६७.८; ७१.९; ७३.२; ७४.३; ७६.७; ७७.२; ८[२]; ८२.४; ८७.२०; ९०.१६; ९२.१०; ९३.४; ९४.३; ८[२]; ९; १०७.२; ३; ४[२]; १०८.८; १०९.१; १२४.४; १२५.४; १२६.३; १२८.६; ९; १४८.३; १८१.२; ३

तै १.४.३; ४; ५.७; ८.९; ९.४; ५; ११.२; ६; ७; १४.२; ८; १६.७; २४.४–६; ९[२]; १४; २५.१; ३; २८.६; ३०.४; ५; ९; १२; २०; २१; ३१.१८; ३२.१४; ३५.११; ३६.२–४; १२; ४२.५; ४३.९; ४८.४; ६; ४९.३; ५१.८; १०; १३; ५२.७; १०; ११; ५३.११; ५४.१; ८; ५५.७[२]; ८; ५७.२; ४; ५[३]; ५८.४; ५९.१; ५; ६१.१६; ६३.१; २; ९; ६८.२; ३; ६९.४[२]; ७३.१०[२]; ७५.२; ३; ७६.१[३]; ७९.२; ८०.३[२]; ८[३]; १३; १४; ८१.२; ६; ९; ८२.१–४; ५[२]; ६; ८३.३; ८४.१; ३[२]; १९; २०[२]; ९१.३; ४; ९; १६; १८; १९[२]; ९४.४; १०; ११[२]; १४; ९५.९; ९७.४[२]; १००.१७; १०१.१०; १०२.१[२]; ३; ७; १०३.१; १०४.१; ६; ७; १०५.८; १०६.५; ११४.२; ३[२]; ९[३]; १०[२]; १२१.५; ८; १२; १५[२]; १२३.११; १२४.१२; १२७.९[२]; १३०.२; ६; १३१.४; ५; १३२.२–४; १३३.४[२]; १३४.१; ६; १३५.१; ८; ९[२]; १३८.३; ४; १४०.११[२]; १४४.६; १४७.१–३; १५०.३; १५६.१; ३; १६२.८; ९; ११; १४; १७[२]; १९; २०[२]; २१; १६३.१; ३; ४[२]; ५[२]; ६; ७[२]; ८; १६४.४९; १६५.३[२]; ९; १६७.१; १६९.३; ४; १७०.३; ४; १७३.८[३]; १२; १७४.८; १७५.१[२]; २; ५; १७६.४; १७७.२; ३; १७८.१[२]; १८७.९; १८९.१; ४; १९१.११; १४; १६; २.१.७; ९; १५; २.१२; ४.८; ६.२; ९.३; ५; ११.१; ४; ६; ७; ११; १२; १३[२]; १६; १९; २१; १२.१५; १३.१३; १४.१२; १५.१०; १६.३[३]; ६[२]; ७–९; १७.९; १८.६; ९; १९.७; ८[२]; ९; २०.१; ९; २३.२; ४; १४; २८.५; ७; ८; ३०.१०; ३२.५; ३३.१; ७; ११; ३६.५; ३७.३; ४१.१; २; १८; ३.१.२०; २३; ५.११; ६.२; ५; ७; ११; ७.११; ९.२; १०.३; १४.२; ३; ५; १५.७; १७.३; १८.२; ४; १९.२; ३; २०.२[३]; २१.२; ५[३]; २२.२; ५; २३.५; २७.३; २९.१०; ३०.२; ३; ५; ६[२]; ७; १९; ३१.१४; १७; ३२.१; २; ३[२]; ९; ११; १२[२]; ३३.८[२]; १०[२]; ३४.२; ३५.१; ४; ५[२]; ७[२]; ९; ३६.९; ३७.२; ३; ९[२]; १०; ११; ३८.२; ३९.१; ४२.१; ६; ८; ४३.७; ४४.१; ४६.१; ५[२]; ४८.१; २; ५०.२; ५१.११; १२; ५२.४; ७; ५३.२; ५; ६; १४; ५५.२२[३]; ५७.४–६; ५९.२; ६२.७; ४.२.६; ७; १९; २०; ३.२[२]; ४[२]; १५; ४.३; ६; ८[२]; १०; १३; १५; ६.६[२]; १०; ७.२; ९; ९.८; १०.१; ४[२]; ६; ११.१; १२.१; २; ४; ५; १६.७; ८; १०; १४; २१; १७.४; १८; २१; १८.९; १२[२]; १९.१०; ११; २०.१०[२]; ११; २१.९[२]; १०; ११; २२.५–७; ११; २३.६; ११;

२४.११; २९.५; ३०.२; १९; २४; ३१.६; ९; १०; ३२.१०; ११; १८^{२}; १९; २२; ३५.७; ४२.७; ४७.१; ४८.५; ५०.३; ५४.५; ६; ५८.११^{२}; ५.१.१०; २.११; ३.३; ९; ४.७; ६.४^{२}; ५; ७.९; ८.५; १०.४; ११.३; १२.४–६; १५.५; १८.२; २०.२; ४; २२.३; २५.८; २७.३; २९.१३^{२}; १४; १५; ३०.३; ३१.४–७; १०; १३; ३२.१२; ३३.३–५; ३५.१–३; ४^{२}; ३६.२; ४; ३८.१; ३; ५; ३९.२; ३; ४२.६; ४३.३; ५; ४४.२; ८; ५०.२; ५; ५६.२; ७८.७; ७९.५; ८१.५; ८४.३; ८५.८; ६.१.४; ९; १०^{२}; १३; २.४–६; ९; ३.१; ३; ४.५; ५.५; ७; ६.३; ४^{२}; १०.६; १३.४; १५.९; ११; १४; १६.१६–१८; २५; २७; ३८; ४७^{२}; १७.९; १०; १८.३; ४; १३; १५^{२}; १९.७; ९; १०; १३; २०.१०; २१.३–६; २२.४^{२}; २३.६; २४.३^{२}; ४^{२}; २५.१; ७; ८^{३}; ९; २६.८; २७.३^{२}; ४^{२}; २९.३; ५; ३१.२; ३७.१^{२}; ४०.२; ४; ४१.२^{३}; ३; ५; ४३.१–४; ४४.१; २^{२}; ३; ११^{२}; २०; २१; ४५.१४; ३०; ४७.८; २२; २६; २९; ४८.१६; १८; ४९.१३; ५०.९; ५३.९^{२}; ५४.९; ५६.६; ५८.१^{३}; ३; ६१.१; ६४.२; ४; ६; ६५.५; ७५.१८^{२}; ७.१.८; ९; २०; २२; २५; ३.२; ३; ४^{२}; ६^{२}; ८; ५.६; १४.२; १७.७; १८.३^{२}; १८; २०; २१; १९.६^{२}; ७; ८; ९^{२}; २०.८^{३}; ९^{२}; १०; २१.६^{२}; ७; ९^{२}; १०; २२.१–३; ५^{२}; ६; ८^{२}; ९; २३.४; २४.१; २; ६; २५.१^{२}; ३; ६; २७.२; ५; २८.१; २; २९.३^{२}; ३०.४; ३१.७; ९; ३२.२; ६; १४; ३३.१०; ३६.४; ३७.३–५; ४२.२; ४६.३^{२}; ४; ५४.२; ३; ७९.२; ८१.४; ५; ८७.२^{२}; ८८.५; ६^{२}; ९०.२; ९२.१^{२}; ९५.६; ९६.२; ५; ९८.३; ६; ९९.१^{२}; २; ७; १००.५–७; १०४.१४; ८.१.३; ७; ९^{२}; १४; १६; ३०; २.१; ३; १०; ३०; ३.१; २; १०; १८; ४.५–७; ९; १२; ६.१६; १९; ३१; ११.५; ७;

१२.८; १०; २५; २६; २७^{२}; २८^{२}; २९^{२}; ३०; ३१; १३.४; ६; ११; १९; २२; २३; २६; ३१^{२}; १४.३; ४; ६; १०; १५.४; ६; १७.१; ५; ६^{२}; १०–१३; १९.१६; २०; ३३; २१.४; ५; ७^{२}; ८; १४; १५; १६^{३}; २४.५; ८; ९; १७; २६.१०; ३२.७; ८; ३३.११; १२; १५; १९; ३४.५; ३६.१–६; ४०.९; ४३.२; ३३; ४४.४; २३–२५; ४५.५; ६; १०^{२}; १२; १५; १९; ३२; ३६; ३९; ४२; ४६.३; ८; ११; २५; ३२; ४८.६; ७; ९; १३; ४९.५; ८; ९; ५०.५; ८; ९; ५१.७; ५२.७; ५३.४; ६; ७^{२}; ८; ५४.१; ५; ८; ५५.१; ५६.१; ६०.१४; ६१.२; ९; १८; ६२.४; ७; ८; १०; ६३.५; ८; ६४.९–११; ६५.४^{२}; ८; ६६.५; ११; १३; ६८.३; ८^{२}; ११; ६९.१२; ७०.५; ७१.८; ७४.७; ८; ७५.१०; १६^{२}; ७७.९; ११^{२}; ७८.४; ८०.६; ७; ८१.८; ९; ८२.३^{२}; ७; ९; ८४.४; ७; ८८.३; ६; ८९.२; ४; ६; ९०.३^{२}; ६^{२}; ९२.१६–१८; २३; २४; २६–२८; ९३.४; ११; १२; २६; २७; ९५.२; ५; ९६.७–९; १२; ९८.३; ११; ९९.६^{२}; १००.१; २^{२}; ६; १०१.९; ११; १०२.१९–२१; १०३.४; ९.१.६; २.७; ११.२; १६.१; २९.३; ३१.३; ४; ६; ५०.१; २; ५३.१; ५५.२; ५७.१; ६१.१; ४; ५; १०; १७; १९; २९; ३०; ६२.७; २०; २८; ६३.२२; ६४.२; ७; ११; २४; ६५.९; १५; २८; ६६.३; १०; १४; ३०; ६७.१२; १५; २३; २४; ७२.४; ५; ७४.९; ७५.५; ७८.२; ७९.४^{२}; ५^{२}; ८२.४; ८३.१; ८५.१; ८६.१; २; ४; ५; १३; २८; ३७; ४७; ८७.४; ८; ८८.८; ८९.६; ९१.५; ९६.२१; २४; ९७.६; ३१; ४६; ९८.५; १००.४; १०४.४; १०५.४; १०७.२०; १०८.२; १०९.२; ११; ११४.१; ४; १०.४.१^{२}; ६; ७; ६.७; ७.२; ६; १०.२; ३; १२^{२}; १३; ११.७; १२.३; १४.५; ११; १६.३; ४^{३};

३; १५.८; ३८.३; ६१.२; ७; ८४.५; ९८.७; १०८.११; १०.११.४; ४१.१; ८०.३; १४३.१; २; १७१.१; ३; ४; १७८.१

त्यस्य ५.३२.३

त्यस्यै १०.८६.२३

त्या १.१२२.४; ३.३०.३; ४.१५.८; ३०.१७; १८; ५.७३.२; ७४.२; ६.२.९; ५०.१०; ६३.१; ७.७३.४; ८.१०.३; १३.२७; १८.८; २२.३; ३२.२९; ९३.२४; १०.२२.५; ६१.१५; ७५.६; १३८.६

त्याः १.२९.४; ९२.१; ७.७८.३; ८.४८.११; ९.६३.९; १०.१३४.३

त्यागम् ४.२४.३

त्यान् ८.६७.१; ९४.१०; ११

त्यानि ७.८८.५

त्याम् १.६३.८; १३९.७

त्ये १.३७.१०; ५०.२; १०४.२; १८७.४; ५; १९१.५; ४.६.९; १०; ५.६.६; ७; १०.५; ३३.८–१०; ४६.६; ७.३६.७; ७५.३; १०४.२०; ८.३.१५; ७.७; २२; २३.११; ४३.५; ९.२१.७; ५१.३; ९२.४; १०.२५.५; ३५.१; १२४.५; १३८.१

त्ये इति २.३१.५; ८.२.४२

त्येभिः १.३०.२२

त्रदम् ८.४५.२८

त्रयः १.३४.२[२]; ८; ९; १२२.१५; १६४.४४; ३.५६.८; ४.४५.१; ५८.३; ५.६९.२; ७.३३.७[२]; १०१.४; ८.२.७; ८; २८.१; ३०.२; ५७.२; ९.९२.४; १०.२७.२३; ४८.७

त्रयःऽत्रिंशतम् १.४५.२

त्रययाय्यः ६.२.७

त्रयाणि १०.४५.२

त्रसदस्यवि ८.४९.१०

त्रसदस्युः ४.३८.१; ५.२७.३; ८.१९.३६

त्रसदस्युम् १.११२.१४; ४.४२.८; ९; ७.१९.३; ८.८.२१; ३६.७; ३७.७; १०.१५०.५

त्रसदस्योः ५.३३.८

त्रसन्ति ६.१४.४

त्रातः १.१२९.१०

त्रातुः ३.५६.६; ८.६०.५

त्राता १.३१.१२; १०६.७; १२९.११; १७८.५; ४.४.१०; १७.१७; ५५.१; ७; ५.२४.१; ६.१.५; २५.७; ४८.२; ७.२०.१

त्रातारः ८.४८.१४

त्रातारः ७.५६.२२

त्रातारम् १.४४.५; २.२३.८; ६.४७.११; ८.१८.२०; १०.१२८.७

त्रातुः १.१५५.४; ४.५५.५

त्रातॄन् ६.५०.१

त्राध्वम् २.२९.६[२]

त्राध्वम् ८.३०.३

त्राम् १.१००.७; ४.२४.३

त्रामणे ५.४६.६

त्रामऽभिः १.५३.१०

त्रायताम् १०.१३७.५

त्रायताम् १.१०६.७; ४.५५.७

त्रायध्वम् १०.६३.११

त्रायध्वे ५.५३.१५; ७.५९.१; १०.३५.१४

त्रायन्ताम् १०.१३७.५[२]

त्रायन्ते ८.२७.१७

त्रायमाणः ६.५०.८; ७.३५.१०

त्रायसे २.२३.४; ८.७१.४; १०.७.४

त्रायस्व ७.१९.७

त्रायस्व ७.१६.८; १०.२२.१५; १४८.४

त्रायेताम् १०.३५.३

त्रायेथाम् ५.७०.३

त्रासते १.१२८.५; ७

त्रासदस्यवम् ८.१९.३२; १०.३३.४

त्रासदस्यवम् ८.२२.७

त्रासाथे इति ५.६२.६

त्रासीथाम् ४.५५.१; ५.४१.१; ७.६२.४; ७१.२

त्रास्व ८.६१.१७; १०.७.७

१५५.४; ३.२६.८; ४.५३.५; ५.३६.६; ८.३५.३; ९.६७.२६

त्रिऽस्रयः ८.७०.१५

त्रिऽमन्तुः १.११२.४

त्रिऽमाता ३.५६.५

त्रिऽमूर्धानम् १.१४६.१

त्रिऽयुगम् १०.९७.१

त्रिऽवन्धुरः १.११८.१; १५७.३; १८३.१; ७.६९.२; ७१.४; ८.२२.५

त्रिऽवन्धुरे ९.६२.१७

त्रिऽवन्धुरेण १.४७.२; ११८.२; ८.८५.८

त्रिऽवयाः २.३१.५

त्रिऽवरूथः ६.१५.९

त्रिऽवरूथम् ४.५३.६; ६.४६.९; ८.१८.२१; ४२.२; ९.९७.४७; १०.६६.५; ७; १४२.१

त्रिऽवरूथेन ५.४.८; ६.२६.७

त्रिऽवतु ७.१०१.२

त्रिऽविष्टि ४.६.४; १५.२

त्रिविष्टिऽधातु १.१०२.८

त्रिऽवृत् १.१४०.२

त्रिऽवृतः १.३४.९

त्रिऽवृतम् ९.८६.३२; १०.५२.४; ११४.१; १२४.१

त्रिऽवृता १.३४.१२; ४७.२; ११८.२; ८.७२.८; ८५.८

त्रिऽशताः १.१६४.४८

त्रिऽशीर्षाणम् १०.८.८; ९९.६

त्रिऽशोकः १.११२.१२; १०.२९.२

त्रिऽशोकाय ८.४५.३०

त्रिषु १.१५.४; २४.१३; १०५.५; १५४.२; १६४.९; २.३.७; ३६.४; ८.२.२१; ४५.३४; ६९.३

त्रिऽसधस्थ ५.४.८; ६.८.७

त्रिऽसधस्थः ६.१२.२

त्रिऽसधस्थः १.१५६.५; ४.५०.१

त्रिऽसधस्थस्य ८.९४.५

त्रिऽसधस्था ६.६१.१२

त्रिऽसधस्थे १.४७.४; ५.११.२; १०.६१.१४

त्रिऽसप्ताः १.१३३.६

त्रिऽस्तुप् १०.१४.१६; १३०.५

त्रिऽस्तुभः ९.९७.३५

त्रिऽस्तुभम् ८.७.१; ६९.१

त्रिऽस्थम् १.३४.५

त्री १.३४.९; ३५.८; १४९.४; १५४.४; २.२७.९; ३.९.९; २०.२[२]; ५६.५; ४.५३.५; ५.२९.१[२]; ७[२]; ८[२]; ६९.१; ९.१७.५; ७३.८; ९७.५५; १०३.२; १०.५२.६

त्रीणाम् १०.१८५.१

त्रीणि १.२२.१८; ९५.३; १०२.८; १६३.३; ४[२]; १६४.४५; ४८; २.२७.८; ३.९.९; १७.३; ३८.६; ४.५३.५; ५.६९.१; ८१.४; ६.१७.११; ५१.२; ७.६६.१०; ८.६.४७; ७.१०; ८.२३; १२.२७; २९.७; ३९.९; ५२.३; ९१.५; ९.१०.२३; १०.८.९; ५२.६; ६७.५; ८७.१०

त्रीन् १.१२६.५; १६४.१०; २.२७.८; ३.६.९; ४.३३.५; ५.६९.१; ८.५.८; ३९.९; ९.७३.१

त्रेतिनी १०.१०५.९

त्रेधा १.२२.१७; ३४.८; १५४.१; १८१.७; ६.६९.८; ७.१०१.४; १०.४५.२; ७५.१; ८७.१०; ८८.१०

त्रेधाऽइव १.३४.४

त्रैतनः १.१५८.५

त्रैवृष्णः ५.२७.१

त्रैस्तुभम् १.१६४.२३; २.४३.१

त्रैस्तुभात् १.१६४.२३

त्रैस्तुभेन १.१६४.२४; ५.२९.६

त्र्यम्बकम् ७.५९.१२

त्वः १.१४७.२[२]; १५२.२; ८.१००.३; १०.७१.४[२]; ११[४]

त्वक् ९.७०.७

त्वक्षसा १.१००.१५; ४.२७.२; ६.१८.९

त्वक्षांसि ८.२०.६

त्वक्षीयसा २.३३.६

त्वचः ४.१७.१४; १०.१७१.२

त्वचम् १.७९.३; १२९.३; १३०.८; ५.३३.७;

५; ६; ८; ७५.३; ७८.३; ७९.३; ४; ८०.१; २; ८२.७–९; ८४.३; ६; ९०.२; ४^{२}; ५^{२}; ९२.३२; ९३.१०; १३; १९; २१; ३३; ९५.३; ९६.१६; १७^{३}; १८^{३}; ९७.२; ७^{२}; १४; ९८.२^{२}; ६; १०; ११^{२}; ९९.५^{२}; १००.२; १०२.१; ९.४.५; १६.८; १८.२^{२}; २०.५; २२.७; २४.४; ४५.२; ५१.४; ५६.४; ५९.३; ६२.९; २६; ६४.२५; ६६.३; १८; ६७.१–३; २६; ८६.२३; २८^{२}; २९^{२}; ३०; ३८; ३९; ८८.१^{३}; ४; ८; ९७.४३; ४८; ९८.४; १००.२; ३^{२}; ९; १०५.६; १०७.६; ७; २३; १०८.३; ११०.७; १११.२; १०.१.४; २.१; ४.१; ४; ८.४; १०.१४^{२}; १५.१२^{२}; १३; १६.१३; १८.९; २१.६; २२.५; ८–१०; २५.७–९; २८.३; ५; ४४.५; ५०.४; ५४.४; ५^{३}; ५९.५; ६१.२१^{२}; २२; ६९.६; ८; ९; ७३.३; ७^{२}; ८; ७५.२; ४; ६; ७९.५; ८३.३; ४; ८४.३; ८५.४५; ८६.४; ८; ८७.२०^{२}; २१; ८९.८; ९१.३; १०^{२}; ९३.११; ९५.१८; ९६.५; ९७.१८; २३; १०२.१२; १०४.९; १०८.९; ११०.१; ३; ११३.१०; ११८.७; ८; १२२.५; १२४.५; १२८.६; १३२.४; १३३.२; ७; १३४.४; १३७.३; १४१.१; ६^{२}; १४५.५; १४७.२; ५^{२}; १४८.२; १५३.२^{२}; ३–५; १६७.१^{३}; १७१.१–४

त्वम् १.११३.५; ६^{४}; ४.१७.१३; ८.३७.६^{२}; १०.७१.५; ८; ८५.२६

त्वम्ऽत्वम् १०.९६.५

त्वऽयतायै ७.२०.१०; २१.१०

त्वया १.८.४; ३६.४; ५३.११; १०२.४; १३२.१; १४१.९; १७४.६; १७८.५; २.१.१४; ४.९; ७.३; २३.९; १०; ३८.७; ११; ३.३०.९; ४.४.१४; २०.३; ५.४.१; १३.४; ६.२६.७; ३०.३; ४५.१२; ७.१५.८; ३१.६; ३२.२७; ४३.५; ९८.४; ८.२१.११; ६३.११; ९२.३२; १०२.३; ९.३५.३; ८५.८; ९६.११; ९७.५८; १०.३८.३; ४५.११; ८३.१; ८४.१; ४; ११५.८; १२०.५; १२८.१; १३८.६

त्वष्टः २.३६.३

त्वष्टः ३.४.९; ५.५.९; ७.२.९; १०.७०.९

त्वष्टा १.३२.२; ५२.७; ६१.६; ८०.१४; ८५.९; १४२.१०; १६१.४; ५; १६२.३; १८६.६; १८८.९; २.१.५; ३.९; २३.१७; ३१.४; ३.५४.१२; ५५.१९; ४.३३.५; ६; ५.३१.४; ४६.४; ६.१७.१०; ४७.१९; ५०.१३; ७.३४.२०–२२; ३५.६; ८.१०२.८; ९.८१.४; १०.२.७; १०.५; १७.१; १८.६; ४६.९; ४८.३; ४९.१०; ५३.९; ६४.१०; ६६.३; ९२.११; १८४.१

त्वष्टाऽइव ४.४२.३

त्वष्टारम् १.१३.१०; २२.९; ३.४८.४; ५.४१.८; ६.४९.९; ९.५.९; १०.६५.१०; ११०.९; १२५.२

त्वष्टुः १.२०.६; ८४.१५; ९५.२; ५; १६२.१९; ४.१८.३; ८.२६.२१; २२

त्वष्टृऽमान् ६.५२.११

त्वस्मै १०.७१.४

त्वस्यै १०.५४.१

त्वा ४.२८.१; २; ७.१.१३; ८.६८.९; ९२.३१

त्वा १.१.७; ४.९; ५.७; १०.१^{२}; ८; १०; १२; १४.२; ६; १५.१; १०; १६.१^{२}; ४; ९; १९.९; २४.३; ११; २७.१; ३०.१०; ३१.४; १०; ३२.१२; ३६.३; ४; १०; ४०.१; ४४.७; ८; ११; ४५.५; ७; ८; ४८.११; ४९.१; ५०.८; ५१.१०; ५२.७; १५; ५३.६; ५४.५; ५५.७; ५७.४; ५८.६; ५९.२; ६०.५; ६२.११; ६५.१; ७०.५; ७३.४; ७६.२; ७८.१–४; ८०.२; ८१.८; ८२.३; ६; ८४.१; ४; ६; ९; ९१.११; २३; ९४.३; १०१.१०; १०२.५; ७; १०३.७^{२}; १०४.९; ११४.८; १२१.११; १२५.२; १२७.२; ८; १२९.४; १०; ११^{२}; १३०.१; २; १३१.२^{२}; ३; १३४.१; २; १३८.२^{२}; ३; ४^{२}; १३९.६; १४१.१०; १४२.४;

१५०.१; १६२.१५; २०; १६३.८; १६४.३४^{२}; १७३.७; १७५.६; १७६.६; १७७.२; १८७.२; ११^{२}; १९०.५; १९१.१०–१३; २.२.२; ६.३; ११.११; १३.५; २०.२; २३.१; ८; १४; १७; ३२.२; ३३.४^{२}; ४२.१; २^{२}; ३.१.१५; ६.३; ७.२; ९.१; ६; १०.९; १७.४; १९.५; २३.४; २७.१०; १५; २९.४; १६; ३०.१; ३२.१६; ३३.११; ३६.९; ३७.१; ४०.१; ४१.९; ४२.६; ४३.२; ३; ६; ४५.१; ४७.३; ४^{२}; ५०.२; ५१.४; ८; ११; ५२.६; ८; ५३.२; ४^{२}; ६१.२; ४.२.८^{२}; ४.७; ८; ९^{२}; १०; ७.२; १६.१९; १८.८^{२}; ११; २२.८; ३०.३; ३१.२; ३२.४; ८; ९; १३; १५; ४८.४; ५२.४; ५७.६; ५.२.८; ४.१०; ९.१; ११.३; १३.१; २०.३; २१.१–३; २२.३; ४; २३.३; २४.२; २६.२–४; २९.१; ११; ३२.११; ३६.२; ३; ५; ४०.३; ५; ६१.६; ७९.४; ९; ८४.२; ६.१.२; ६; ७; २.३; ४.७; १५.१२; १५; १९; १६.११; १४; १५; २६; ३७; १७.३; ४; ८; १३; १८.१४; १९.१२; २१.१; ६; ७; १०; २३.८^{२}; २४.६; २५.५^{३}; २६.१; ३३.४; ३७.१; ४०.३; ४१.५; ४४.१०; १२; १९; ४५.१०; ११; २५; २८; ५२.३^{२}; ५३.१; ५६.४; ६१.५; ७५.१; १८^{२}; ७.१.११; ४.६; ९; १५.७; ९; १६.४^{२}; १८.३; ४; १२; २१.१; २२.१; २३.५; २४.३; ५; २८.१; २९.४; ३०.२; ३१.८; ९; ३२.१; १६; २२; २३; ३३.१०^{२}; ११; ४१.५; ५४.१; ७६.६; ७७.६; ७८.५; ७९.४; ८१.३; ८६.४; ८८.७; ९९.७; १००.५; ७; ८.१.३; १६; २०; २४; २५; २९; २.३; ११; १६; २९; ३.३; ७; ९; ११; ४.२; ४; १४; १७; ६.१८; २०; २७; ३८; ४२; ४५; ११.८; १२.२५; १३.५; १३; ३३; १५.१२; १७.२; ३; ७; १९.३; १७; २६; २१.२; ४; ६; २३.१६^{२}; १७^{२}; १८; २४.६; २६; ३०; ३२.२३; ३०; ३३.१; २; ८; १४; ३४.२; ४; ८; ९; ४३.१२; १३; १७; २१; २३; २७; २८; ४४.५; २२; ४५.५; १३; १४^{२}; १६; १७; २०^{२}; २२–२४; ४६.१७; ४९.३; ५०.४; ५१.६; ५२.४; ५३.१; २; ६०.१; २; १५; १६; ६१.३; ५; १४; ६४.१; २; ६; ६५.३; ६; ७; ६८.१; १०; ७०.५; ७४.११; १२; १५; ७६.११; ८१.२; ३; ८८.३–५; ९०.६; ९१.१^{२}; ३^{२}; ९२.१२; २२; ९५.१^{२}; २; ४; ९६.४^{४}; ७; ८^{२}; ९७.४; ९^{२}; ९८.७; ८; १०२.१३; १७; १८; ९.२.४; ८; ८.४; ५; ९; १६.५; १७.७; २६.६; ३०.५; ४८.१; ३; ५३.३; ५६.३; ६०.२; ६१.२७; ६४.२३^{२}; ६५.४; ११; २७; ६६.८; ९; ७९.४^{२}; ८०.२; ४; ५; ८६.४; ३९; ८७.१; ९२.४; १०४.४; १०७.२; १०९.२१; ११०.२; १०.१.४; २.६; ७^{३}; ४.२; ३; १४.४; १६.७; १२; १७.३^{२}; ४^{३}; १८.१०; २१.१; २२.७; २६.४; २९.३; ३२.२; ६; ३७.५; ७^{२}; ८; ४२.३^{२}; ४५.३^{२}; ४६.१०; ४७.१; ८; ५१.३^{२}; ५४.१; ५५.१; ६९.४; ५; ७३.८; ७५.४; ८३.५; ८५.५; २२; २४^{३}; २६^{२}; ३६; ८७.९; १९; २२; २४; ८८.५; ८९.१६; ९५.७; ११; १५; १७; १८; ९६.१; १२; ९८.८; १०४.६; १०५.११; १०८.९; ११५.८; ९; ११६.३; ८; ११८.२; ५; ९; १२०.४^{२}; १२२.८; १२३.६; १२४.६; १२८.१; १३१.५; १३३.२; १३४.१; १३७.४; ७^{२}; १४०.६; १४२.६; १४५.६; १४६.१; १४७.१; १४८.१; १४९.५^{२}; १५०.२; १५५.१; १५८.५; १६०.१; ५^{२}; १६१.१; ५^{२}; १६२.५; ६; १७३.१^{२}; १७४.३^{२}; १७९.२; १८३.१; २

त्वाऽइषितः ८.७७.१०

त्वाऽऊतः १.७४.८; ३.१९.३; ५९.२; ६.१.९; ३३.२; ८.५१.२

त्वाऽऊतयः ५.६५.५; ९.६६.१४; ७६.५

द

दृता १०.११५.२
दृत्त १०.५१.८; ९७.१९; २१
दृत्तम् १.१६३.२; २.३८.११; १०.१०७.१
दृत्तम् १.३४.६
दृत्तस्य ८.४५.४२
दृत्ताः १.१२६.३
दृत्तात् १०.१६.२
दृत्ताम् १०.८४.७
दृत्ते ९.९६.१
दृत्ऽभिः ८.४३.३; १०.६८.६
दत्रम् ३.३६.९
दत्रऽवान् ६.५०.८
दत्राणि ८.४९.२
दत्रै ४.१७.६
दृत्वते १.१८९.५
दृत्वाय १०.८५.३३
दद १.३९.९
दद ४.३६.९; ५.५७.७
ददः ७.२४.१; २९.१; ८.४५.३९
ददत् २.३०.७; ५.२७.४^{2}; ६१.१०; ७.२८.५; २९.५; ३०.५; ३२.५; ४१.३; ७५.७; ८.२.४१; ५.३७; ६.४८; २१.१८; ४६.२४
ददत् ४.२४.१०; १०.१७.३; ३०.३; ८५.४१^{2}
ददतः १.७३.५; १८७.५; ३.५३.७; ५.३०.१२; ३३.७; ७९.५; ७.१९.१०; ३०.४; १०३.१०; १०.३२.९; ६२.७; १५१.२
ददतम् ५.३२.१२
ददता ५.५१.१५
ददताम् ३.५३.१७
ददति ६.४८.८; ७.१६.१०; ३२.१५
ददति २.३५.१०
ददतुः १०.७३.४
ददते १.२४.७
ददथुः १.११६.६; ४.३९.२; ५; ८.८६.३
ददथुः १.११६.२३; ११७.७; ४.३८.१; २; ४२.९; ७.७४.२; ८.८६.२; १०.३९.१०
ददभन्त १.१४८.२
ददमानः ४.२६.६
ददमानात् १.४१.९
ददर्श १.१०५.१८; १६४.३२
ददर्श १.१६४.४; ४.१३.५; १४.५; ८.१००.३; १०.१०.६; ५१.२; ७१.४; १०२.१०
ददश्वान् ४.३८.६
ददात ७.५७.६
ददातन १०.३६.१०
ददाति १.४०.४; १२६.६; २.१३.३; ५.६.३; २७.२; ६.२८.३; ८.१.२१; १०.११७.३; ४
ददाति १.९१.२०; १३३.७^{2}; ५.२.१; २५.५; ६; ६.१४.४; २७.८; २८.२; ७.२७.३; १०.१४.९; ८०.१; १०७.७; ८; १६०.३
ददातु २.३२.४; १०.५७.५
ददातु १.१५.८; ४८.१३; ४.३०.२४; ७.४०.२; ६; ८.७१.१३; ९३.३४^{2}; ९.९७.२१; १०.४९.७^{2}; ८७.१८; ११५.५; १४१.२
ददाथ ६.२०.११
ददानः ५.३३.९
ददानः ५.२.३
ददानम् १.१४८.२
ददाभ ५.३२.७
ददामहे ३.२१.५
ददामि १०.११६.५
ददार ६.२७.४
ददाश १.३६.४; १४९.५; १५७.६; २.२७.१२; ६.१०.३; ७०.३; ८.१९.५; २३.१५
ददाश ६.३.२
ददाशः १.९४.१५
ददाशत् १.९१.२०; ५.३७.५; ६.५.५; ७.२०.८; १०.७७.७
ददाशति १.१५६.२; ३.१०.३
ददाशिम १.८६.६
ददाशुः १.१४७.१; ४.८.५
ददाशुषे १.११२.२०; १६६.३; २.८.१; ५.५३.६
ददासि २.३२.५

ददासि १.१९०.५
ददिः १.१५.१०; ८१.७; ११०.७; २.१७.८; ३७.१; २; ४.२४.१; ६.२३.४; ८.२१.६; १७; २४.३; ४६.१५[३]; १०.१३३.३
ददीमहि १.८.३; २.२३.९
ददीरन् ७.४८.४; ६४.१
ददुः २.१३.१०; ३.५३.१६; ५८.४; ५.१८.५; ८.६.४७
ददुः ५.५२.१७; ८.६२.७; १०.१०९.६; ११७.१
ददुषः १.५४.८; ८.७९.५
ददुषाम् ६.८.७
ददृक्षे ७.७६.३
ददृक्षे ६.६४.२
ददृऽश्वांसः ४.१.१४
ददृशानः १.१२७.११; ४.१७.१७; ९.७०.६
ददृशानऽपविः १०.३.६
ददृशानम् ४.७.१०
ददृशुषीः १०.१३९.४
ददृशे १.१३५.७; ५.४४.६; ७.६१.५; ८.७२.६; ८२.८; ९.९७.९; १०.१११.७
ददृशे १.९५.१; १६४.४४; ३.५५.८; ४.११.१; ६.१०.४; २७.३; ४४.१०; ४८.६; ७.९.२; ६२.१; ८.१.३४; ५७.२; १०.४८.१०
ददृश्रे १.२४.१०; ३.५४.५
ददृश्रे ३.८.१०; १०.७१.७; १४२.५
ददृश्वान् ४.३३.६
ददृहाणः १.१३०.४; ४.२६.६
ददृहाणम् १.८५.१०
ददृहि १.१३३.६
ददे ४.३४.४; ३७.३; ४४.५
ददे १.१२६.५; १६०.६; ४.१५.८; ५.७.३; १०; ७.६.७[२]; ८.६.४६; १९.३१; ४५.४; ४६.३२; ६३.९; ६५.११; ६८.१५; ७२.१७; ७८.१०; ९.१०.८; ६१.१०; ६८.३; १०.४८.२; ४९.२; ५५.७; १३८.४; १६६.४
ददौ ४.५.२
दद्धि १.१७६.४; २.१७.७; ४.२०.१०; ६.२०.१; १०.४७.८
दद्धि ४.२०.७; ८.१२.३३; १३.५
दद्मसि ८.४७.१५
दद्महे ९.५८.४
दद्महे ९.५८.३
दद्राणम् १०.५५.५
दद्रिरे ७.९०.१
दद्रुः १.६२.११; ४.१९.५
दद्वहे इति ८.३४.१६
दद्वान् १०.१३२.३
दध ८.२७.१९
दध ८.१०२.१४
दधः ७.३०.३
दधः १.८१.३[२]; ७.१७.७; ८.१३.२२
दधत् १.३५.८; १२८.३; १४०.९; १८८.२; ४.१५.२; ३; २०.३; ५४.१; ५.६.१०; ३१.११; ६.४५.२; ७.२४.४; ८.९३.२६; ९.३.६; २०.७; ६२.३०; ६५.२१; ६६.२१; २७; ६७.१९; ६८.१०; १०.३९.५; १५६.४; ५; १७०.१
दधत् ४.२४.७; ५.१४.१
दधतः १०.२८.८; ३४.६; ४६.४; ११४.५; ६; १७५.३
दधताम् १०.१८.४
दधति १.१६९.३; ३.३०.१; ५.५४.२; १०.९१.९
दधति १.५५.५
दधती ७.७७.५; १०.९५.४
दधतीम् १.११६.१९
दधतु ७.५१.१
दधते १.९४.२; ४.७.९; ५.४१.२; ७.१०.६; ६८.५; ९०.६
दधते ६.१.९; ९.६८.२; १०.७७.७
दधतौ ७.७०.४
दधथः ४.४४.४
दधथुः ६.७२.४

दधन् १.७१.३
दधनत् १०.७३.१
दधन्ति ७.५६.१९
दधन्तु ७.६२.६; ६३.६
दधन्युः ४.३.१२
दधन्ऽवतः ६.४८.१८[२]
दधन्वान् ९.६७.२; १०७.१; १०.११३.२
दधन्विरे ४.३१.६; ९.१०.२; १३.७; १०.१०४.१
दधन्विरे ३.६०.३; ८.१९.१; १०.९२.५; ९६.६; ७
दधन्वे २.५.३; ३.३१.१
दधन्वे ८.३३.१२; ९.९३.२
दधर्ष ५.८५.६; ६.७.५; ८.९६.९
दधर्षति १.१५५.५; ६.२८.३; ७.३२.१४; १०.१५५.५
दधर्षीत् १.१८३.४; ४.४.३
दधसे ८.३२.६
दधसे ६.१६.१७
दधात ५.२२.२; २६.७; ७.३२.१३; ३४.४; ६; ९.२१.५; ६
दधात २.२९.३; ४.३३.११; ५.३.७; ६.६२.८; ७.५८.३; १०.१५.४; ७
दधातन १०.३६.१३
दधातन ५.३४.१; ५५.४; ८.४७.१३; ९.११.६; १०.९.१; १५.११; ३७.११; ६३.१५; १०१.५; १२
दधाति १.१५५.३; ४.१२.३; ५.४८.४; ७.९.१; १६.१२; ३८.१; ७५.६; ९.७४.५; ७५.२; ८६.१०
दधाति १.६६.२; ४; १२५.१; २; १४६.२; ३.५५.१७; ४.२०.९; ५.३.१०; ६३.१; ६.१०.३; २८.२; ७.१.२३; ३२.१२; ७९.३; ९५.३; ९.९४.४; १०.८५.१९; ८८.१९; १०९.४; १२०.२; १६०.४
दधातु ३.२६.३; ४.५३.७; ७.३४.२०
दधातु १.८९.६; २.४०.६; ५.५१.११; ६.५४.१०; ७.३४.२२; ४५.४; १०४.९; ऋ.१८
१०.१७.४; ६४.१३; ८५.४७; १५८.३; १६४.३; १८४.१
दधाते इति १.१८५.६; ७; ५.७७.१
दधाते इति १.२.९; १३६.२; १८५.२; १०.५.३
दधाथ १०.९५.११
दधाथ ४.५.६
दधाथे इति ७.७०.३
दधाथे इति १.१५१.९; ३.३८.५; ७.६१.३
दधानः १.३५.४; ६७.२; ७२.१; १२८.३; १४१.१३; १४४.१; १७१.६; ३.१.८; ३४.५; ५५.१०; ४.१६.१४; २२.३; २९.४; ५.१.५; १५.४; ५; ६.४४.८; ७.४५.१; ८.४६.५; ९.१५.४; २३.५; ३९.३; ६३.१३; ६५.१०; ६६.७; ९२.२; ९६.१२; ९७.४७; ११३.१; १०.७.२; ११.७
दधानम् ८.९७.१३
दधाना १.११७.९; १२३.४; ३.५३.१६; ६.६९.३; ७४.१; ७.६९.२; ७६.७; ८०.२; ८४.१
दधानाः १.४.५; ६.४; ५३.११; ७३.५; १०; १२२.७; १४७.१; १६५.१२; २.११.४; ३.१.१६; ३८.३; ५.३.४; ४१.१३; ६.६६.५; ७.६०.८; ७३.१; ९५.५; ८.६३.१०; ९.१७.६; १०.१५.१०; १८.२; ३; ३९.१४; ६७.२; ७१.१; ८४.७; १०४.४; ५; ११५.८; १२१.७; ८
दधानान् २.१२.१०; ६.४७.२५
दधानि १०.११९.९
दधाने इति १.१४६.३; ६.७०.५; १०.११०.६
दधाम ५.४५.५; १०.१०८.३
दधामि २.३५.१२; ८.३४.५; १००.२; १०.९८.२
दधामि ७.३४.८; ८.९१.२७; १०.१८.४; ८५.२४; १२५.२; १४७.१
दधासि १.९४.१४; ८.१०२.१; १०.१४०.१; ५
दधासि १.३१.७; ९१.७; ५.८.५; १०.२१.६; ८

दधिऽआशिरः १.५.५; १३७.२[२]; ५.५१.७; ७.३२.४; ९.२२.३; ६३.१५; १०१.१२
दधिः १०.४६.१
दधिऽक्राः ४.३८.९; १०; ४०.४; ७.४४.५
दधिऽक्राम् ३.२०.१; ५; ४.३८.२; ३९.१; ५; ७.४४.१; २; १०.१०१.१
दधिऽक्रावा ४.४०.२; ७.४४.४
दधिक्रावाऽइव ७.४१.६
दधिऽक्रावाणम् ७.४४.३
दधिऽक्राव्णः ४.३९.२–४; ६; ४०.१; ३
दधिध्वम् ६.१०.१; ७.३४.९; १०.१०१.११
दधिध्वे १.३८.१; ४.३४.३; ३७.१
दधिध्वे १.१६८.१; ५.४.३; ५५.२
दधिम १०.४२.६
दधिरे १.२६.८; ४५.७; १४८.३; १५१.२; २.१३.१०; २३.१४; ३.१९.४; ४.८.६; ५.१६.१; ६.५.२; २५.७; ३८.३; ७.५३.१; १०४.१८; ८.१२.२५; १०.४६.१०; ६३.५; ११४.३
दधिरे १.३६.२; ५९.३; ६४.१०; ७२.३; ७३.७; ८३.४; ८५.२; ३; ८७.५; १३१.१; २.२५.५; ३४.१३; ३.१.६; २.५; ५०.३; ५१.६; ४.५०.१; ५.८.६; १८.४; ४४.६; ५५.१; ६१.११; ६.१.४; १५.८; १७.८; ३६.२; ४८.२१; ७.११.४; १७.६; ३१.१२; ८.२.३०; १२.२२; ५०.४; १०.५.२; ८.३; ४५.११; ४६.८; ५२.३; ४; ९१.६; ९४.५; १४०.६
दधिषे १.८२.६; ५.३८.२; ६.४३.४; ७.२८.२; ९२.१; ९८.२; ८.४५.३१; ९७.२; १०.५०.६
दधिषे १.५७.६; ६२.९; २.१३.६; ३.१८.५; ५.४५.११; ६.१०.६; ८.४.४; १०; १५.१०; ९.६.९; ६४.१; १०७.१०; १०.८.४; ६; २८.१२; ५४.५; ७३.३; ८; ९६.१०; १२०.७
दधिष्व ३.३५.६; ४०.५
दधिष्व १.३.६; १०.९; ३.३७.१०; ४२.५; १०.११६.८

दधीचः १.८४.१३; ११९.९
दधीचे १.११७.२२; १०.४८.२
दधीत १.४०.२; ८.१९.११; ७४.९
दधीत ५.६६.१
दधीत २.३५.१; ५.४१.५; ६.१५.१५; ८.७२.१३; १०.१०.१
दधीमहि ५.३५.८; ५२.४; ७.४०.१
दधुः १.३६.१०; ५८.६; १४८.१; ६.१५.२; ७.६६.११; ८.१३.२०; ९.९९.३
दधुः १.७२.१०; ७३.४; ८०.१५; २.२.४; ३.३.५; ४.५५.२; ५.२.६; ७९.५; ७.३२.२; ८२.२; ८.७.२२; १३.२९; ९.९.५; ८३.३; ११०.७; १०.१८.१४; १४०.३
दधृक् ५.६६.३; ८.८२.२; १०.१६.७
दधृषम् ३.४२.६
दधृषिः २.१६.७
दधृषिम् ४.१७.८
दधृष्वणिम् ८.६१.३
दधृष्वान् १.१६५.१०; ४.२२.५; ५.२९.१४
दधे १.२४.४; ३०.३; १०३.४; १४९.५; २.१९.१; २३.६; ३४.९; ३.२.१३; २२.१; ५.२३.४; ८.६.११; १३.१९; ४१.८; ५२.३; ९.१८.४; ९८.८; १०.१२९.७
दधे १.३.११; २२.१७; ३६.१९; ४०.७; ८; ५५.८; ८१.४; १२८.६; १३९.१; १६८.३; २.८.५; ३१.६; ३२.१; ३.१.३; २३.१; ४; २७.९; १०; ३९.६; ५५.१३; ६१.७; ४.३६.६; ५.५३.५; ८१.१; ८६.५; ७.५०.१; ८.३३.७; ८; ३९.४[२]; ४१.३; ४४.३; ९.७३.३; ८; ८२.३; १०८.१२; १११.२[२]; १०.१९.७; २७.१४; १००.५
दधौ १.९५.३; १०.२७.१३
दध्नः १०.१७९.३
दध्ना ८.२.९; ९.११.६; ८१.१
दध्मः १०.१७२.३
दध्मसि ८.१०२.२०
दध्मसि १.५०.१२[१]

दध्यङ् १.८०.१६; ११६.१२; ११९.९; ६.१६.१४; ९.१०८.४
दध्रिरे १.४८.३
दध्रे १.३७.७
दध्रे ८.१७.१३; १०.८२.५; ६
दध्वसे १०.११३.७
दन् १.१२०.६; १४९.१; १५३.४; १०.६१.२०; ९९.६; १०५.२; ११५.२
दनः १.१७४.२
दन्तः ६.७५.११
दन्तम् ४.६.८
दन्दशानाः १०.९५.९
दभः ५.१९.४
दभत् १०.१०८.४
दभत् १.१७८.२
दभन् १.८४.२०; १४८.५; २.३२.२; ६.४४.१२; ८.४५.२३; १०.८७.९; १२०.४
दभन्ति ७.३२.१२
दभाति ६.२८.३; १०.१६५.३
दभाय ५.४४.२; ७.९१.२; ९.७३.८
दभीतये २.१३.९; ४.३०.२१; ६.२६.६; ७.१९.४; १०.११३.९
दभीतिः ४.४१.४; ६.२०.१३
दभीतिम् १.११२.२३; २.१५.९
दभीतेः २.१५.४
दभ्नुवन्ति १.५५.७
दभ्यते १.४१.१
दभ्यम् १०.१०८.४
दभ्याय १०.६१.२
दभ्रऽचेताः ८.१०१.१६; १०.६१.८
दभ्रम् १.११३.५; ४.३२.२०; ७.१०४.१०; ८.४५.३२
दभ्रस्य १.८१.२
दभ्राः ४.२५.५
दभ्राणि १.१२६.७
दभ्रेभिः १.३१.६; ४.३२.३; ७.८२.६; १०.३८.४
दम ६.३.७
दमन्यत् १०.९९.६

दमम् १.७५.५
दमऽयन् ६.४७.१६
दमयन्तम् ७.६.४; १०.७४.५
दमाम् १०.४६.७
दमाय ३.६.३
दमिता २.२३.११; ३.३४.१०; ५.३४.६
दमूनसः ५.४२.१२
दमूनसम् १.१४१.११; ३.२.१५; ४.११.५; ५.८.१; १०.४१.३
दमूनसि ८.५०.१०
दमूनाः १.६०.४; ६८.५; १२३.३; १४०.१०; ३.१.११; १७; ३.६; ५.४; ३१.१६; ४.४.११; ५.१.८; ४.५; ६.१९.३; ७१.४; ७.९.२; १०.३१.४; ४६.६; ९१.१
दमे १.१.८; ६०.४; ६१.९; ६७.५; ७१.६; ७३.४; ९४.१४; १४३.४; १७४.३; २.१.२; ७; ८; २.४; ११; ४.३; ३५.७; ३.३.९; १०.२; २९.१५; ४८.२; ४.२.८; ५.१५; ८.३; ९.४; ५.४३.१२; ४८.३; ६.१.६; २.१०; १२.४; ७.१.२; ११; १२.२; ४२.४; ८.७.१२; ४४.१५; ९.१११.२[२]; १०.७.४; ९१.१; १०; १६७.४
दमेऽदमे १.१२८.४; ४.७.३; ५.१.५; ६.८; ६.७४.१; ७.१५.२
दमेषु २.८.३; ८.१०२.११
दम्ऽपतिम् १.१२७.८
दम्पती इति दम्ऽपती ५.३.२; ८.३१.५; १०.१०.५; ६८.२; ८५.३२; ९५.१२; १६२.४
दम्पतीइवेति दम्पतीऽइव २.३९.२
दम्ऽपते ५.२२.४; ८.६९.१६; ८४.७
दम्भय ८.४०.६; १०.२२.८
दम्भयः १०.२२.११
दम्भयः १.५४.६
दम्भयत् ६.१८.१०
दम्भयन् १०.११३.९
दम्यम् ३.२.८; ७.५६.१४
दम्याय ८.२३.२४

दम्येभिः ३.१.१५; ५४.१

दमूऽसु १.१३४.४; १४१.४

दमूऽसुजूतः १.१२२.१०

दमूऽसुपत्नीः ४.१९.७

दयते ८.१०३.६

दयते ४.७.१०; ५.४९.३; ६.६.५; ३०.१; ७.२१.७; ८४.४; १००.१; ८.२.३१; ९.९०.२; १०.८०.२

दयध्वम् ७.३७.२

दयन्त ७.१६.७

दयमानः १.१०.६; १२०.३; १३०.७; ३.२.११; ३४.१; १०.२३.१

दयसे २.१३.६; ६.३७.४; ७.२३.४; ५

दयसे २.३३.१०; ६.२२.९; १०.१४७.५

दयस्व १.६८.३

दरयः १.६२.४

दरयत् १०.९९.११

दरयन् ७.५.३

दरयन्तः १.५३.४

दरीमन् १.१२९.८

दर्तः १.१७४.२; ६.२०.१०; २७.५

दर्तरिति दर्तः १.१३०.१०

दर्ता ६.६६.८

दर्ता ८.९८.६

दर्तुम् ६.२०.३

दर्दः ४.१६.८

दर्दरिति दर्दः १.६३.७; ४.१६.१३; ६.२०.७; ७.१८.१३

दर्दरीति ६.७३.२

दर्दरीमि ८.१००.४

दर्दतु ७.५५.४

दर्दर्षि २.१२.१५

दर्दिरत् ८.३२.१८

दर्दहि ३.३०.२१; ७.५५.४; ८.३४.१४

दद्रत् ६.१७.५

दधर्षि ५.८४.३

दभांसः १.१९१.३

दभः ३.४५.२

दमा १.१३२.६

दमाणम् १.६१.५; १०.४६.५

दर्विः १०.१०५.१०

दर्वी इति ५.६.९

दर्शत १.२.१

दर्शतः १.१४४.७; ३.१०.६; २७.१३; ५.५६.७; ६५.१; ६.३०.२; ८.४१.३; ४; ७०.२; ९.२.६; १११.३[२]

दर्शतम् १.३६.९; ३८.१३; १०२.२; ११७.५; १४१.१; १६४.५२; ३.१.३; १३; २.१५; ४.३६.७; ५.६६.२; ६.१.३; ५१.१; ७.६६.१४; ८.७१.१०; ७४.५

दर्शतऽश्रीः १०.९१.२

दर्शतस्य १०.१४०.४

दर्शता १.६४.९; ५.८०.२; ६.६४.५; १०.७५.७

दर्शताः ३.५७.४

दर्शतात् १.११६.११

दर्शताभिः ६.६३.६

दर्शतायाः ७.७५.३

दर्शतासः ९.१०१.१२

दर्शते इति ९.५.६

दर्शथः ८.२६.४

दर्शन् १०.२७.६

दर्शनाय १.११६.२३

दर्शम् १.२५.१८[२]

दर्शि ३.५६.२

दर्शि १०.१२३.२

दर्श्यी ५.५२.११

दर्षत १०.२७.७

दर्षत् ९.७४.७; १०.२७.७

दर्षते १०.१२०.६

दर्षसि ८.३२.५

दर्षि ६.२६.५; ८.२४.४

दर्षि १.११०.९; ४.१६.८; ५.३९.३; ६.३३.३; ८.६.२३; ३३.३; ९.६८.७; १०.६९.३

दर्षीष्ट १.१३२.६

दविद्युतत् ६.१६.४५; ७.१०.१; १०.४३.४; ६९.१

दशस्यसि ८.८८.६
दशस्या ७.९९.३
दशस्येः ७.३७.५; ८.९७.१५
दशस्येत् १०.१०.९
दशानाम् १०.२७.१६
दशाभीशुऽभ्यः १०.९४.७
दशावनिऽभ्यः १०.९४.७
दशो इति ६.४७.२३
दसत् १.१२१.१५; १३९.५
दसमानः १.१३४.५
दसयन्त ५.४५.३
दसाय ६.२१.११
दस्म ५.६.५; ८.७४.७
दस्म १.४.६; ६२.५; ११; १२; १३८.४; २.९.५; ४.१.३[2]; ५.३१.७; ६.१.१; १८.५; ७.३.४; २२.८; ८.९२.१८; १०३.७; १०.७.१; ४३.२; १४७.५
दस्मः १.१२९.३; १४८.४; २.१.४; ३.३.२; ७.१८.११; ९.८२.१; १०.९९.१०
दस्मत् १.७४.४
दस्मऽतमः २.२०.६
दस्मम् १.४२.१०; ७७.३; ५.३४.१; ७.३१.९; ८.८८.१; १०.११.४; ३१.३
दस्मऽवर्चसाम् ८.९४.८
दस्मऽवर्चाः १.१७३.४; ६.१३.२; ५८.४
दस्मस्य १.६२.६; ३.१.७; ५.१७.४
दस्मा ४.४१.६
दस्माः ४.६.९; ५५.२; ५.४९.३
दस्माः ५.४१.१३
दस्मात् ८.४५.३५
दस्मे ३.५५.१५
दस्यथम् ८.२४.२०
दस्यति १०.११७.१
दस्यन्ति १.११.३; ६२.१२; १३५.८[2]; ५.५४.७; ५५.५
दस्यवः १.५१.८
दस्यवि ८.६.१४
दस्यवे १.३६.१८; १०३.३; ८.५१.२; ५६.२; ९.९२.५; १०.४९.३; १०५.७
दस्यवे ८.५५.१; ५६.१
दस्युः २.११.१८; ४.१६.९; १०.२२.८
दस्युऽघ्ना ४.१६.१०
दस्युऽजूताय ६.२४.८
दस्युऽतर्हणा ९.४७.२
दस्युऽभ्यः ४.३८.१; १०.४८.२
दस्युम् १.३३.४; ७; ९; ५३.४; ५९.६; ११७.२१; १७५.३; २.१५.९; ५.४.६; ३०.९; ६.१४.३; ७.१९.४; ८.५०.८; ७०.११; ९.४१.२; १०.७३.५
दस्युऽहत्याय १.५१.६; १०३.४; १०.९५.७
दस्युऽहत्ये १०.९९.७; १०५.११[2]
दस्युऽहत्येषु १.५१.५
दस्युऽहनम् १०.४७.४
दस्युहन्ऽतमम् ६.१६.१५; ८.३९.८
दस्युहम्ऽतमम् १०.१७०.२
दस्युऽहा १.१००.१२; ६.४५.२४; ८.७६.११; ७७.३; १०.८३.३
दस्यून् १.६३.४; ७८.४; १००.१८; १०१.५; २.११.१९; १३.९; २०.८; ३.२९.९; ३४.६; ९; ४.१६.१२; २८.३; ४; ५.७.१०; १४.४; २९.१०; ३१.५; ७; ७०.३; ६.१८.३; २३.२; २९.६; ७.५.६; ६.३; ८.१४.१४; १०.५५.८; ८३.६; ९९.८
दस्येत् ६.३७.३
दस्योः १.१०४.५; ११७.३; २.१२.१०; ३.४९.२; ६.३१.४; ८.९८.६; ९.८८.४
दस्र १.४२.५; ६.५६.४
दस्रा १.३.३; १५८.१; १८३.५; ४.४४.६; ५.७५.२; ७.६९.३; ८.५.११; ८.१; ८७.५
दस्रा १.४६.२; ९२.१८; १८२.२; ६.६२.५; ८.२६.६; ८६.१; ८७.६; १०.२६.१; ४०.१४
दस्रा १.३०.१७; ४७.३; ६; ९२.१६; ११२.२४; ११६.१०; १६; ११७.५; २०; २१; ११८.६; ११९.७; १२०.४; १३९.३;

४[२]; १८०.५; १८२.३; ४.४३.४; ६.६९.७; ७.६८.१; ८.५.२; २२.१७
दस्राः ५.५५.५
दस्रौ १.११८.३; १८३.४; ३.५८.३; ५
दस्रौ १.३०.१८; ११७.२२; ५.७५.९
दह ४.४.१५
दह १.१२.५; ३६.१४; २०; ७९.६; ७.१.७; १५.१३; ८.२३.१४; ६०.७; १०.८७.१९; २३; २४; १०३.१२; ११८.७
दहः १०.१६.१
दहतात् ३.१८.१
दहन् ३.२९.६; ८.४३.२६
दहन्ति १०.२८.८; ३४.९
दहन्तु १०.८७.२०
दहाति १.९९.१
दहामि १.१३३.१
दाः २.२.७[२]; ३.२४.५; ६.१६.२६; ७.१.५; १०.८५.३८; १४८.४
दाः १.१०४.५; ७; ८; १२१.४; १६९.४; १८९.५; २.४.८; ५.२४.१; ३३.६; ६.१३.६; १९.६; २०.७; २६.१; ३३.१; ३५.१; ७.१.१९; ४६.४; १००.२; ८.२.१५; ४८.८; ७१.७; ९.९७.२५; १०.३०.४; ४७.१–८; ४९.४; १२८.८
दात् १.१२१.१२; ८.२.३९
दात् १.२४.१; २; ५.३.१२; ६.६३.९; १०[२]; ७.४५.२; ९७.४; ८.३२.१५; ९.९७.५२; १०.१७.७; ८०.४
दात २.३४.७; ६.४९.१५; ७.५६.१५
दातम् ८.८.१७
दातवे ४.२०.१०; ७.४९.६; ८.१९.२९; ७१.१५; ९.७५.५
दातवै ४.२१.९
दाता १.२२.८; २.२२.३; ३.१३.३; ४.१७.८; ५.७.७; ६.२३.३; ७.२०.२; ८.६६.२; १०.५५.६
दाता ५.२३.२; ६.२३.१०; २९.१; ३७.५; ७.९७.२; ८.५१.५; ५२.५; ६५.१०; ९०.२; ९२.३; ९६.२०; ९.९७.५५; १०.५४.५
दाताम् १०.१४.१२
दातारः ६.५०.११
दातारम् ४.३१.७
दातारम् २.३३.१२; ८.३.२४; ४६.२[२]
दातारौ ६.६०.१३
दाति ४.८.३; ५.७.७; ४८.५
दाति १.६५.४; ६.२४.२; ७.१५.१२; ४२.४
दातिऽवारः १.१६७.८
दातिऽवारम् ५.५८.२
दातिऽवाराः ३.५१.९
दातु १०.९९.१
दातु ७.१५.११; ८.५२.५
दातुः १.१३.११
दातुम् ५.३६.१; ७९.१०
दातॄन् ६.५१.४
दातोः ७.४.६
दात्रम् ८.७८.१०
दात्रम् १.११६.६; १६६.१२; १८५.३; ३.५४.१६; ६.२०.७; ८.४३.३३; १०.६९.४
दात्रस्य ८.४४.१८; ९.९७.५५
दात्रा ४.३८.१
दात्राणि ६.६१.१
दात्रात् ७.५६.२१
दात्रे ६.४४.१०
दाधर्थ ७.९९.२; ३
दाधार १.६६.२; ६७.३; १५४.४; १५६.४; ३.३२.८; ६.३०.२; ८.१५.२; ९.३५.६; १०.६०.९; १११.४
दाधार १.६२.९; ३.५९.१; ६.४४.२४; ४७.४; ५१.८; ९.७४.२; १०.६०.८; ९; १२१.१
दाधृविः ६.६६.३
दानऽअप्नसः १०.२२.११
दानऽओकसम् १.६१.५
दानः ७.२७.४; ८.४.८; १०.३२.९
दानम् १.१२८.५; ५.३०.७; ३३.६;

७.१८.२२; ८.४६.६; ५१.७; ६१.६; ९.५२.३
दानम् ६.४५.२३
दानवम् ५.२९.४; ३२.१
दानवस्य २.११.१०; ५.३२.४
दानऽवान् ८.३२.१२
दानवाय ५.३२.७
दाना ५.५२.१४; १५; ८७.२; ८.२०.१४; ३३.८
दानाः ५.२७.५; ७.१८.२३
दानाः ८.६४.९
दानाय ६.५३.३; १०.१४१.५; ६
दानाय १.४८.४; ५५.७; ११२.२; १८०.५; २.१३.१३; १४.१२; ६.४५.३२; ८.४६.२६; ५१.६; ५२.६; ५४.५; ६१.८; ७०.८; ७१.११; ९९.४; ९.८१.१; १०.६१.२; ६२.८
दानासः ८.४६.२४
दानु ६.५०.१३
दानुः १.३२.९; ५४.७
दानुऽचित्राः १.१७४.७; ५.३१.६; ५९.८
दानुःऽदः ९.९७.२३
दानुनः १.१३६.३; २.४१.६
दानुनः ८.८.१६
दानुना १०.४३.७
दानुऽपिन्वः ९.९७.२३
दानुम् २.११.१८; १२.११; ४.३०.७
दानुऽमत् १.५१.४
दानुऽमत्याः ५.६८.५
दानून् १०.१२०.६
दानूनि ८.२५.६
दाने २.१३.७
दान्ति १०.१३१.२
दाम् १०.४९.१
दाम १.१६२.८
दामऽइव २.२८.६
दामनः ५.३६.१
दामनि १.५६.३
दामने ८.९३.८
दामन्ऽवन्तः ५.७९.४; ६.२४.४
दामा ६.४४.२; ८.७२.६
दामानः ८.२१.१६
दामानम् ४.५४.२; ८.२३.२; १०.४२.८
दाम्नः ७.८६.५
दायम् १०.११४.१०
दायि १.६१.१५; २.२०.८; ६.२५.८
दारु ६.३.४; १०.१०२.८; १४६.४; १५५.३
दारुम् ७.६.१
दारूणि ८.१०२.२०
दार्भ्याय ५.६१.१७
दावने १.६१.१०; १२२.५; १३४.१^{२}; २; १३९.६; २.१.१०; ११.१; १२; ४.२९.५; ३२.९; ५.३९.२; ५९.१; ४; ६५.३; ६.७१.२; ८.७.२७; २५.२०; ४५.१०; ४६.२५^{२}; २७; ६३.५; ६९.१७; ७०.१२; ९२.२६; ९.९३.४; १०.३२.५; ४४.७; ५०.७
दाशत् १.७०.३; ४.२.९; ६.१६.२०; ७.१००.१; ८.१९.१४; १०३.४; १०.६१.२५; ९१.११; १२२.३; १३८.५
दाशत् १.१५८.२; २.१९.४; १०.६५.६
दाशतः ७.१४.३; १७.७
दाशति १.९३.१०; १५१.७; ६.१६.३१; ६८.५; ७.५९.२; ८.२७.१६
दाशऽराज्ञे ७.३३.३; ५; ८३.८
दाशसि ८.२४.२
दाशा १.१२७.७
दाशात् १.६८.३; ७१.६; ९३.३; २.२३.४
दाशुऽअध्वरः १.७५.३; ८.१९.९; १०.१४७.४
दाशुऽअध्वरम् ८.४.१३
दाशुऽअध्वराय ६.६८.६
दाशुरिः ८.४.१२
दाशुषः १.३.७; ११०.२; १४२.२; १७८.३; २.२०.२; ३.२५.४; ५१.९; ६०.५; ४.९.८; ४६.६; ४९.६; ५.७१.३; ६.६२.३; ७.७४.४; ८.५.५; १३.१०;

२५.८; ३८.३; ४०.६; ४१.१; ३; ४; ७; ४३.११; ४५.१; ४७.१; ३; ४; ६; ५२.५–७; १४; ५३.६; ८; ५४.१; १३; ५६.१; ५७.१; ५; ५९.६; ७; ६०.३; ७; ६३.१; ३; ५; ७४.१; ७६.४; ८०.५; ६; ८३.६; ८४.३; ८७.३; ६.१.७; २.३; ४; ११; ३.७; ७.१; ६; ७; १३.१; १५.१; १६.९; १८.१२; २०.२; ३०.१; ४४.२१; ४७.४; २७; ४९.२; ५१.१; ४; ५२.१५; ५८.४; ६२.१; ६६.११; ७१.५; ७.३.६; ५.१; ६.७; १५.४; २४.३; ३४.२; ३६.३; ३८.५; ३९.५; ४५.२; ४६.३; ६०.७; ६१.३; ६३.४; ६४.२; ६६.१४; १८; ६७.२; ६९.३; ७०.३; ७५.४; ७८.४; ७९.२; ३; ८१.१; ९७.१; १०२.१; १०४.४; ५; १९; ८.१.१८; २९; ५.८; ७.७; ११; १३; ८.४; ७; १०.१; १२.६; १३.८; १३; १४.९; २०.१७; २५.७; १८; १९; २६.१७; २३; २७.१९; ३४.१–१५; ३६.४; ४०.८; ४४.१६; ५७.३; ६०.१९; ६३.२; ६५.२; ६९.३; ७२.८; ७९.४; ८२.४; ८७.४; ८८.५; ९४.९; १०; ९७.५; ९८.३–६; ९.२.५; ८.८; ९.१; १०.९; १२.४; ८; १६.७; २६.२; २७.३; ३१.२; ३३.५; ३६.६; ३७.३; ३८.५; ३९.२; ४; ४२.१; ४८.१; ३; ४९.१; ५१.२; ५७.१; ४; ६१.१६; ६२.२८; ६३.२७; ६४.८; ३०; ६५.२४; ६६.५; ३०; ६८.८; ९; ६९.५; ८; ७१.७; ७२.७; ७३.४; ५; ७४.१; २; ६; ७; ७५.२; ७६.१; ७७.२; ५; ८०.१; ८३.२^{२}; ८५.९^{२}; १०; ८६.३; ८; ९; ११; १९; २४; २७; ३३; ३५; ४६; ८७.२; ८; ८९.१; ३; ६; ९६.५; १४; ९७.२९; ३०; १०२.८; १०८.१०; १६; १०९.६; ११०.८^{२}; ११३.८; ९; १०.३.२; ७.१; ८.१; १०.२; ११.१; १५.१४; १७.६; २०.४; २२.६; २८.६; ३७.१; ३९.१२; ४५.१; ३; ४९.२; ५५.८; ५९.९; ६१.४; ६२.६; ६३.४; ६५.१३; ६६.१०; ६७.२; ७०.५; ६; ११; ७६.५; ७७.२; ३; ८९.३; १०; १२; ९२.६; ९; ९७.१७; ९८.३; १०; १२; १०८.५; १११.३; ५; ७; ११४.१; १३८.३; १३९.२; १४३.३; १४९.४; १५८.१; १७०.२; ४

दिवः १.३०.२२; ४८.१; ९; ४९.२; २.३६.२; ४.५१.१०; ११; ५.५४.१०; ७९.२; ३; ८; ९; ६.६४.४; ५; ६५.६; ७.७७.६; ८१.३; ५; ८.४७.१४; १५; १०.१२७.८

दिवःऽइव २.२.२; १०.६२.९

दिवःऽजाः ६.६५.१

दिवःऽदासम् १.११२.१४; ४.२६.३; ६.२६.५; ६१.१; ७.१८.२५

दिवःऽदासस्य ६.१६.१९

दिवःऽदासात् ६.४७.२२; २३

दिवःऽदासाय १.११६.१८; ११९.४; १३०.७; २.१९.६; ४.३०.२०; ६.१६.५; ३१.४; ४३.१; ९.६१.२

दिवःऽदासेभिः १.१३०.१०

दिवःपृथिव्योः २.२.३; ५.४९.५; १०.३.७; ३५.२

दिवःऽरुचः ३.७.५

दिवक्षसः ३.७.२; १०.६५.७

दिवक्षाः ३.३०.२१

दिवम् १.५०.११; ५२.१२; ६२.८; ६८.१; १६४.४७; ५१; ३.५९.७; ४.४२.४; ६.२१.२; ८.६.४८; ३४.१–१५; ५१.८; ५५.२; १००.८; ९.३.७; ८; १७.५; ५४.२; १०.५६.३; ५८.२; १२१.९; १८९.२; १९०.३

दिवा १.२४.१०; १२; ३४.२; ३८.९; ९८.२; १३९.५; १४४.४; ५.७६.२; ३; ६.३.६^{२}; ४९.१०; ७.१५.१५; ७१.१; २; १०४.११; ८.७.६; १८.६; ७; २५.११; ६१.१७; ६४.६; ९.९७.९; १०७.२०; १०.८७.१; ९५.४

दिवा १.१६१.१४; १६३.६; ३.६२.२;

दिव्या १.१४३.५; १५२.७; २.२७.९; ४.४३.३; ५.२९.१; ६९.४; ९.८८.७; ९७.५१; १००.३; १०७.२४

दिव्याऽइव १.१७६.३

दिव्याः २.२५.४; ६.६.३; ५०.११; ७.३५.११; १४; ४९.२; १०३.२; ८.५.२१; २५.६; ९.८६.१; ४; ८८.६; ११०.६; १०.३४.९; ९८.५

दिव्याःऽइव १.१६६.११

दिव्यात् ७.१०४.२३; १०.५३.५

दिव्यानाम् १०.१२४.९

दिव्यानि १.३४.६; ६४.३; ५; ४.५३.३; ६.२२.८; ५९.९; ९.१४.८; ३६.५; ६३.३०; ६४.६; १०.१३.१; ३२.२; ६४.१६

दिव्याम् ९.९७.१७

दिव्याय १.५८.६; ९.८५.६; १०.७६.८

दिव्यासः १.११८.४; १६३.१०; १८१.२; १०.६५.९

दिव्ये इति ७.२.६; १०.११०.६

दिव्येन ३.२.४; १०.४३.७

दिव्येषु ९.८६.२२

दिव्यैः ३.५४.१

दिशः १.३१.१४; ११९.२; १२४.३; ३.३०.१२; ५.८०.४; ६.६०.२; ९.७०.९; ११४.३; १०.६४.२; ९०.१४

दिशन्ता १०.११०.७

दिशम् १.९५.३; १८३.५; ४.२९.३

दिशमानः ३.३१.२१

दिशा १.८५.११; १३२.४

दिशाम् ९.११३.२

दिषीय २.३३.५

दिष्टाम् १.१८३.५

दिहानः १०.८७.४

दीदयुः १०.६९.७

दीदयत् १०.३०.४; ९५.१२

दीदयत् २.२३.१५; ६.१६.३६; २०.११; १०.९९.११

दीदयत् २.४.३; ५.४५.९; ८.४४.१५

दीदयतम् १.९३.१०

दीदयति ५.६.४

दीदयसि ८.४४.२९

दीदाय २.३५.४; ७.३.५; १२.१; ८.१०२.११

दीदाय ४.६.७

दीदियुः १.३६.११

दीदियुषः ८.२३.४

दीदिऽवः ७.१.८

दीदिऽवः १.१२.५; १०; ५.२४.२; ८.४४.४; ६०.५

दीदिऽवांसम् २.२.११; ३५.३; १४; ३.१३.५; २७.१२; ४.४.९; ३९.२; ५.४३.१२; ६.१.३; ६; १०.८८.१४

दीदिऽवांसा १०.१०६.३

दीदिऽवान् २.९.१

दीदिविम् १.१.८

दीदिहि ८.६०.६

दीदिहि १.७९.५; १४०.१०; २.२.६; ३.१०.२; ८; ५४.२२; ५.२१.४; २३.४^{2}; ६.४८.३; ७^{2}; ७.१.३; १५.८; ८.४३.२६; १०.११८.७

दीदेत् २.२.८

दीदेथ १.३६.१९; ४४.१०

दीद्यग्नी इति दीदिऽअग्नी १.१५.११; ८.५७.२

दीद्यत् १.१४३.७; २.९.२; ३.१.१; ७.१०.१; १०.११८.१; ८; १२२.६

दीद्यतम् ३.२७.१५

दीद्यानः १.१२७.३; ३.५.७; १५.५; ३१.१५; ६.१.७; १०.२०.४

दीद्यानम् ४.५.९

दीद्ये ३.५५.३

दीधय ३.३८.१; १०.३२.४

दीधयुः ८.२१.६

दीधयन् ७.७.६

दीधरः ८.१००.१

दीधरत् ३.२.१०; ८.६८.१९

दीधरम् ९.१०५.४

दीधरिति दीधः ६.१७.६; ६७.४

दीधितिः १.१८६.११; ३.४.३; ५.१८.४

दुःऽमतिः १.१३१.७^{२}; २.३३.१४; ३.१५.६; ७.५६.९; ८.६७.१५; १०.१३४.५
दुःऽमतिम् १.१२९.६; ४.११.६; ८.१८.१०; १०.४०.१३; १७५.२; १८२.१–३
दुःऽमतीः ८.७९.९; ९.७०.५
दुःऽमतीनाम् १.१२९.८^{२}; ११^{२}; ८.४६.१९
दुःऽमतौ ५.४२.१६; ४३.१५
दुःऽमदः १.३२.६
दुःऽमदासः ८.२.१२
दुःऽमन्तु १०.१२.६
दुःऽमन्मा ८.६०.७
दुःऽमन्मानम् १.१२९.७
दुःऽमर्षम् ८.४५.१८; ९.९७.८; १०.४५.८
दुःऽमायवः ३.३०.१५
दुःऽमित्रः १०.१०५.११
दुःऽमित्रासः ७.१८.१५; २८.४
दुःऽयुजः १०.४४.७
दुःऽवर्तुः ४.३८.८; ६.६.५
दुःऽवाससे ७.१.१९
दुःऽविदत्रस्य १०.३५.४
दुःऽविदत्रा १०.३६.२
दुःऽविदत्राम् १०.६३.१२
दुःऽविद्वांसम् ७.९४.१२
दुःऽशंसः १.२३.९; २.२३.१०; ४१.८; ७.९४.७; १०.२५.७
दुःऽशंसम् ७.९४.१२; ८.१८.१४
दुःऽशंसान् १.९४.९
दुःऽशासुः १०.३३.१
दुःऽशीमे १०.९३.१४
दुःऽशेवः १.४२.२
दुःऽसहासः ९.९१.५
दुःऽस्तुतिः १.५३.१
दुःऽस्तुती २.३३.४
दुःऽस्तुती ७.३२.२१
दुःऽस्वप्न्यम् ५.८२.४; ८.४७.१४; १७; १०.३६.४; ३७.४
दुःऽस्वप्न्यात् ८.४७.१८
दुःऽहना १.३८.६
दुःऽहनायतः १०.१३४.२
दुःऽहनायाः १.१२१.१४
दुःऽहनायुवम् ४.३०.८
दुःऽहनावान् ८.२.२०; १८.१४
दुःऽहितः ८.१९.२६
दुःऽहृणायुः ७.५९.८
दुःऽहृणायून् १.८४.१६
दुक्षः ७.४.७
दुग्धः ३.३६.६
दुग्धम् ५.१९.४; ३६.१; ८५.४; ६.४८.२२; ७.७४.३; ९८.१; ९.९६.१५; १०.९४.९
दुग्धाभिः ९.१०७.९
दुग्धाम् १.१५८.४
दुघाःऽइव ८.५०.३
दुघानाः १.१००.३; ३.३१.१०
दुघानाम् १०.६७.६
दुच्छुनऽयते १०.३७.१२
दुच्छुनऽयसे ७.५५.३; ४
दुच्छुना २.२३.६; ८.२०.४; ७५.१३
दुच्छुनाः १.११६.२१; ५.४५.५; ६.१२.६; ४७.३०
दुच्छुनाभ्यः २.३२.२
दुच्छुनाम् ९.६६.१९; १०.१७५.२
दुच्छुनायै १.१८९.५
दुदुहानः ९.८६.२१; ९६.१०
दुदुहुः ९.७९.४
दुदुहे ३.५७.१
दुदुहे ३.३१.११; ४.३.१०; ५.४३.४; ६.६६.१; ७.९५.२; ८.१००.१०; १०.११.१
दुदुह्रे ८.७.१०; ६९.६; ९.३१.५
दुदुह्रे ३.५७.२; ५.६२.२; ९.५४.१; ७०.१
दुदोहिथ २.१३.६
दुध्रवत् ५.५०.४
दुध्रवत् ७.१६.२
दुधये ६.३६.२
दुधितम् ४.१.१७
दुधिता २.१७.४; ४.१६.४
दुधुक्षन् ७.१८.४; १०.७४.४
दुधुक्षन् १०.६१.१०

दुहते ८.६.१९; ५९.३; ९.८०.४; ८५.९; १०.१०७.४
दुहध्यै १०.६१.१७
दुहन् १०.१३२.६
दुहन्तः ८.७.१६; १०.९४.९
दुहन्ता १.११७.२१
दुहन्ति १.६४.५; ८.७२.७; ९.३४.३; ६५.१५; ८०.५; १०.७६.७
दुहन्ति १.६४.६; १३७.३[२]; ३.३६.७; ४.२४.९; ९.६२.२०; ७२.६; ८५.१०; ९५.४; १०.७६.७
दुहाते इति ४.२३.१०; ६.७०.२; १०.११७.९
दुहानः ९.४२.४; १०७.५
दुहाना २.२.९; ३.५८.१; ८.१००.११; १०.६५.६; १४९.४
दुहानाः ३.१.१४; ६.२८.१; ७.४१.७; ४३.४; ८०.३
दुहानाम् २.३२.३
दुहाम् १.१६४.२७
दुहाम् ४.५७.७
दुहितः १.३०.२२; ४८.१; ९; ४९.२; ५.७९.२; ३; ८; ९; ६.६४.४; ५; ७.७७.६; ८१.३; ५; ८.४७.१४; १५; १०.१२७.८
दुहितरः ४.५१.१
दुहितरः ४.५१.१०; ११
दुहितरम् ४.३०.८; ९; १०.६१.७
दुहितरा ६.४९.३; १०.७०.६
दुहितरि १.७१.५
दुहितुरिति ६.६५.६
दुहिता १.३४.५; ४८.८; ९२.५; ७; ११३.७; ११६.१७; ११७.१३; ११८.५; १२४.३; ३.५३.१५; ५५.१२; ४.४३.२; ५२.१; ५.८०.५; ६; ६.६३.५; ६५.१; ७.६९.४; ७५.४; ७८.४; ७९.३; ८१.१; ८.१०१.१५; ९.१.६; ११३.३; १०.२७.११; ३९.१२; ४०.५; ७२.५; १५९.३
दुहितुः १.१६४.३३; ३.३१.१[२]; ५.४२.१३; ४७.१; ७.६७.२; ९.७२.३; ९७.४७; १०.६१.५
दुहित्रा १.१८३.२
दुहित्रे १०.१७.१
दुहीत २.१८.८
दुहीयत् २.११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९
दुहीयत् ४.४१.५; १०.१०१.९
दुहीयन् १.१२०.९
दुहुः २.३४.१०
दुहुः ९.१०८.११
दुहे ९.८९.२[२]; १०.१२.३
दुहे १.१०५.२; ८.१४.३; ३१.४; ९.१०.८; ६७.३२; ६९.१; १०.६०.११
दुह्यते ९.७४.४
दुह्रते १.१३४.६; १६४.७
दुह्रे ३.५३.१४; ६.६६.४; ७.१०१.१; ८.९.१९
दुह्रे १.१३४.६; १३९.७; ५.६९.२
दूत २.६.६
दूतः १.३६.५; ४४.२; ९; ५८.१; ७२.७; ७४.४; १०५.४; १६१.४; १७३.३; १८८.१; २.६.७; ९.२; ३.३.२; ५.२; ९; ६.५; ११.२; ५३.४; ५४.१९; ५५.९; ४.१.८; २.२; ७.८; ९; ९.२; ५.११.४; २६.६; ४३.८; ६.८.४; १५.९; १६.६; २३; ६३.१; ७.३.३; ७.१; १०.२; ५; ११.३; ६७.१; ८.५.३; २३.६; २६.१६; ३९.३; ९; १०१.३; १०.४.२; ८.५; २१.५; ९८.२; ११०.१; १२२.५; १३७.३; १६५.१; ४
दूतम् १.१२.१; ८; ३६.३; ४; ४४.३; ११; ६०.१; १६१.३; ३.९.८; १७.४; ४.७.४; ११; ८.१; ५.३.८; ८.६; २१.३; ६.१५.८; ७.२.३; ३.१; १६.१; ४; ८.१९.२१; २३.१८; १९; ४४.३; १०२.१८; ९.९९.५; १०.१२२.७; १२३.६
दूतमऽइव ४.३३.१
दूतस्य ७.३९.३; ८.४४.२०

१२८.६; १८२.५; ३.१.२२; ८.७; ५.२०.१; ६१.७; ६५.१; ७.२३.५; ३४.९; ५२.१; ६०.१; ८.१९.१; ३; ३४.८; १०३.५; १०.१५.९; ३०.१; ७३.७; ११०.२; १८८.३
देवऽत्वम् १.६८.२; ११५.४; १३६.१; १५१.९; ३.६०.२; १०.१५७.४
देवऽत्वा १.६९.३
देवद्रीचा १.९३.८; १६३.१२
देवद्रीचीम् ३.६.१
देवऽनिदः १.१५२.२; २.२३.८; ६.६१.३
देवने १०.४३.५
देवऽपत्नीः १.६१.८; ५.४६.८
देवऽपानः ९.९७.२७; १०.१६.८
देवऽपानम् १.१६१.५; ४.३५.५
देवऽपानानि १०.५३.९
देवऽपुत्राः १०.६२.४
देवपुत्रे इति देवऽपुत्रे १.१०६.३; १५९.१; १८५.४; ४.५६.२; ६.१७.७; ७.५३.१; १०.११.९; १२.९
देवप्सरःऽतमः ९.१०५.५
देवप्सरःऽतमम् १.७५.१
देवऽप्सराः ९.१०४.५
देवऽबन्धो: १.१६२.१८
देवऽभक्तम् १.७३.१०; ४.१.१०; १०.४५.९
देवम् १.१.१; १२.७; १५.७; २५.१४; ३५.१; ५०.१; १०; ५९.२; १२३.१०; १२८.२; १३८.२; १४४.५; १६४.१८; २.१३.५; २२.१–३; ३८.९; ३.९.१; ८; १०.१; २०.५; २६.१; ६२.१२; ४.१.१[२]; ११.५; ५.९.१; १४.२; ३; २१.३; ४; २२.२; ३; २५.१; २६.७; ४१.६; ४२.११; ४९.१; २; ६.१५.४; १६.७; ४१; ४६; ४४.१६; ४९.९; ५५.६; ७.३.१; ७.१; १६.२; २१.१; ९०.३; ८.११.६; १८.२०; १९.१; ३; ३१.१४; ४४.१५; ८९.१; ९.११.२; ६८.१; १०.१४.७; १६.१०; ७०.५; ८६.१; ११०.९; ११५.३; १२२.४; १२८.७; १३०.३; १७६.२
देवऽमादनः ९.८४.१; १०७.३
देवऽमादनम् १०.३०.७
देवऽमानम् १०.१३५.७
देवमानाऽइव १०.१०७.१०
देवम्ऽदेवम् १.२६.६; ७.७९.५; ८.१२.१९; २७.१३[२]
देवऽयज्यया १.११४.३; ५.२१.४; ८.७१.१२; १०.६६.७
देवऽयज्या १०.३०.११; १५; ७०.१; १०७.३
देवऽयज्याय ७.३.९
देवऽयताम् १.१२१.१; १९०.२; ५.१.४; ९.९७.४६
देवऽयतीनाम् १.३६.१
देवऽयते १.१५.१२; ३.२९.१२; ५.२१.१; ७.१८.१
देवयत्ऽभिः ३.५.१; १०.६९.८
देवयत्ऽसु १०.६९.७
देवऽयन् २.२६.१; १०.४६.१०
देवऽयन्तः १.६.६; ४०.१; ११५.२; १३९.३; १७३.४; ३.६.१; ८.१; ४; ६; ४.२.१७; ११.५; ४४.५; ६.१.२; ७; ७.२.५; ४३.१; ४७.१; २; ६९.६; ७३.१; ९२.२; ८.९.१९; ९.७४.८; १०.१३.२; १७.७; ९१.९
देवऽयन्तम् १.४०.७; ४१.८; ७.६९.४
देवऽयन्तीः १.७७.३; ३.६.३; ७.१०.३; १८.३; ६९.२; १०.३०.१५
देवऽयवः १.१५४.५; ७.९७.१; ८.१०३.७
देवऽयाः १.१६८.१; १७७.४; ३.८.५; ५.७६.१; ७७.२; ७.६८.४
देवऽयानम् १.१६२.४; १०.१८१.३
देवऽयानाः ७.७६.२
देवऽयानात् १०.१८.१
देवऽयानान् १.७२.७; १०.५१.५; ९८.११
देवऽयानीः १०.५१.२
देवऽयानैः १.१८३.६; १८४.६; ३.५८.५; ४.३७.१; ५.४३.६; ७.३८.८

देवऽयावा ७.१०.२
देवऽयु ९.११.२
देवऽयुः ४.२.७; ५.४८.२; ६.३.१; ८.१२.११;
९.६.१; १७.३; ३७.१; ४३.५; ५६.१;
९७.४; १०६.१४; १०८.९; १०.३२.५;
५१.५; १७६.३
देवऽयुक्ताः ७.६७.८
देवयुऽभिः ७.९३.५
देवऽयुम् १.८३.२; ४.९.१; ५.३४.५;
६.२८.२
देवऽयूनाम् ९.९६.२४
देवऽयूनि ७.४३.२
देवयो इति देवऽयो ८.३१.१६
देवयोः ७.६१.१
देवऽयोः १०.१०६.३
देवरम् १०.४०.२
देवऽवतः ७.१८.२२; ८.३१.१५
देवऽवन्तम् ६.४७.१०; १०.४७.३
देवऽवन्दैः १०.१५.१०
देवऽवातः ३.२३.२; ९.९६.९
देववातऽतमाः ६.२९.४
देवऽवातम् ९.६२.५
देवऽवातः ४.३.१५
देवऽवाताः ३.२०.२
देवऽवान् ४.२६.६; १०.६१.२६
देवऽवाहनः ३.२७.१४
देवऽवीः ९.२.१; ३६.२
देवऽवीतमः १.३६.९; ९.२५.३; २८.३;
४९.३; ६३.१६; ६४.१२; १०७.७
देवऽवीतये १.१२.९; २.२३.७; ३.२१.२;
६.१५.१८; १६.७; ४१; ६८.१०; ९.६.६;
१३.२; ३; २०.१; ४५.१; ४६.१; ५४.४;
६४.१५; ६५.१८; ६७.१७; ७०.९;
१०६.७; १०७.१२; १०.३५.१४; ६६.१२
देववीतिऽभिः ८.५४.६
देवऽवीतिम् १.११३.१२; ७.६७.६; ८४.५;
८५.५; ८.६८.१३; ९.८९.७; ९७.२१;
१०.५३.३
देवऽवीतेः १०.६.३
देवऽवीतौ ३.१७.५; ५.४२.१०; ७.१९.४;
९.९६.१४; ९७.२; ३३
देवव्यचःऽतमः ५.२२.२; २६.८
देवव्यचःऽतमम् १.१४२.५
देवऽव्यचाः ३.४.४
देवऽशः ३.२१.५
देवऽशत्रवः ६.५९.१
देवशिष्टे इति देवऽशिष्टे १.११३.३
देवऽश्रवः ३.२३.३
देवऽश्रवाः ३.२३.२
देवऽश्रुतम् १०.९८.७
देवश्रुत्ऽतमम् ९.६२.२१
देवऽसुमतिम् १०.९८.५
देवऽसेनानाम् १०.१०३.८
देवऽस्तुतः ५.५०.५
देवस्य १.२०.६; २४.१; २; १२८.७;
१४१.१; १४४.२; १५९.५; २.७.२;
२२.४; ३८.७; १०; ३.१४.६; १९.४;
२७.३; ५९.६; ६२.१०; ११; ४.१.४; ६[२];
७; २.१९; ७.२; १७.५; ५३.१; ५५.५;
५.३.१०; १३.२; ५०.१; ८१.१; ३;
८२.१; ६; ८५.६; ६.१.४; ४८.२०;
७१.२; ७.१.२२; ४.३; ३८.४; ६; ४०.५;
५२.३; ८२.१०; ८३.१०; ९७.८; ८.२.७;
१९.२८; ३१.१२; ५१.७; ७१.८; ९२.६;
१०२.१५; ९.६९.४; ७०.२; ९७.११;
१०.१२.३; २२.४; ५५.५; ६४.७; ७९.४
देवस्यऽदेवस्य १०.१.५; १३६.४
देवऽहितम् १.८९.८; ४.३७.३; ५.४२.२;
४; ६.१७.१५; ७.६६.१६
देवऽहितिम् ७.१०३.९
देवऽहूतमः ३.१३.६
देवऽहूतमान् ८.७५.१
देवऽहूतयः १०.४४.६
देवऽहूतिः ६.३८.२; ६५.५; १०.१८.३;
१२८.३
देवहूतिऽभिः १.१२.१२; ७.१४.१; ८.५३.७;
९.६८.७
देवऽहूतिम् ७.१४.३; १०.५३.३

देवऽहूतिषु ७.८३.७
देवऽहूतौ ६.५२.४; ७३.२
देवऽहूत्या १०.६३.११
देवऽहूत्यै ८.३९.४
देवऽहूयै ७.८५.२
देवऽहेळनम् ७.६०.८; १०.३७.१२; १००.७
देवा १.२२.२; २३.२; ४६.२; ९२.१८; १८४.३; ५.६८.२; ७४.२; ६.५९.३; ८.२२.३; २५.१; २६.८; ९.५.७
देवा ३.२५.४; ५३.१; ५.६७.१; ६.५९.४; ६८.६; ८; ७.६०.१२; ६१.७; ६७.५; ७४.५; ८२.७; ८.९.६; ५७.१; १०.२४.६
देवाः १.२३.१९; २.२९.१; ४.३७.१; ५.४६.२; ८.४७.६; ६७.९; १७; ८३.६; ९.६८.१०; १०.४५.१२; ६४.१२; १०१.९; १३७.१[२]; १६५.१
देवाः १.११.५; २२.१६; २३.२४; ३१.११; ३६.५; ४०.३; ५; ४५.२; ६५.२; ८०.१५; ८४.१८; ८९.१; २; ७; १०; ९४.३; ९६.१–७; १००.१५; १०७.२; ११६.१७; १२२.३; १४; १३५.१; १४७.१; १६१.२; १६३.८; ९; १६४.३९; ५०[२]; १६७.४; १६९.५; १७४.१; १७९.३; १८६.२; ८; १९०.१; २.१.१३; १४; २.३; १३.५; २३.२; १९; २४.१६; २७.४; १०; ३५.१५; ४०.१; ४१.२१; ३.४.११; ६.७; ८; ७.७; ८.८; ९; ९.९; ११.४; १७.४; १९.५; २०.१; ३२.८; ४९.१; ५१.८; ५४.२; ५५.२; १८; ५६.८; ५७.२; ४.१.१८; २.१७; ७.७; १७.१९; १८.१; ११; १९.२; ३३.९; ११; ४२.१; २; १०; ५०.९; ५.३.१; ४; ८.६; २९.५; ८; ३०.५; ३१.८; ५१.१३[२]; ६९.४; ८१.३; ६.७.१; २; ४; ९.५; ७; १७.८; १८.१४; १५; ५०.१४; ५२.१०; १४; १५; ७५.१८; १९; ७.२.२; ११; ११.४; १६.१२; २१.७; ३३.११; ३५.११; ३९.३; ४; ४९.४; ५०.३; ५१.३; ५२.३; ६६.२; ८३.७; ९१.१; ८.२.१८; १२.२५; १९.२१; २८.४; ४१.७; ४८.१; ५७.२; ६२.७; ६३.१२; ६९.११; ८१.३; ८९.२; ९४.२; ९६.७; ९८.३; १००.१; ११; ९.१४.३; ३९.१; ५१.३; ६१.१३; ६२.२०; ८१.५; ९२.४; १०९.२; ११४.३; १०.१२.३; ७; ८; १४.३; १६.८; १९.७; २०.६; २४.५[२]; २८.७; ३५.१३; ३६.१३; ३७.५; ४६.९; १०; ५१.४; ५२.२; ३[२]; ४; ६; ५३.४; ५५.७; ५६.४; ६१.७; १४; १९; ६२.११; ६३.१; ६५.४; १४; ६६.६; ६९.९; ७०.११; ७२.५; ७३.८; ७४.२; ८२.५; ६; १४; ३१; ३६; ४७; ८७.१५; ८८.१; २; ७; ८; ११–१३; ९०.६; ७; १५; १६[२]; ९२.१०; ९५.७; १८; १०९.४; ६; ११०.११; ११२.६; ११४.१; ३; ११६.९; ११७.१; १२१.२; १२२.२; ७; १२५.३; १२८.२; ३; ७; १२९.६; १३०.३; १३७.५; १४१.२; १५१.३; ४; १५७.१; ४[२]; १९१.२
देवाः १.२७.१३; ४०.६; ८९.८; ९; ९४.८; १०५.३; ५; १६; १०६.२; ११०.७; ११५.६; १३९.७; १७१.२; १८५.९; २.३.४; २८.३; २९.२; ४–६; ३.५४.१७; २१; ४.३४.११; ५५.१; ५.४१.१८; ४२.१७; ४३.१६; ६.४७.२०; ५०.११; ५१.१२; ५२.८; १३; १७; ५९.४; ७.४१.५; ५९.२; १०४.११; ८.१८.१५; ३०.२; ४७.२; ८; १०; ४८.१४; ६५.१०; ६७.७; ८०.१०; ९.५.११; ६७.२७; १०.२.४; ३५.१२; ३६.१०; ३७.११; १२; ५१.८; ५२.१; ५; ६३.२; ११; १२; ७२.६; ७; ७८.८; ८५.२३; १००.७; १०३.११; १०९.५; १३४.७; १३७.१[२]; १५९.४; १६५.२; ३; १७४.४
देवाच्या १.१२७.१
देवान् १.१.२; १२.३; १०; १३.१; ४; १२; १४.६; ९; १२; १५.४; १२; २३.१०; २७.१३; ३६.६; ४४.१; ४;

७; ९; ४८.१२; ६७.२; ७१.३; ७४.६; ७५.५; ७६.२; ५; ७७.१; २; १०५.१३; १४; १७; १२०.४; १३२.५; १३९.१; १४१.६; १४२.१; ११; १६१.६; ७; १६२.२१; १६३.१३; १८५.८; १८६.१०; १८८.३; २.३.१–३; ७; ९.६; १२.१; २४.११; ३६.४; ३७.६; ३.१.१; १७; ३.१; ४.१; ३; १०; ५.९; ६.६; ९; ७.९; १०.७; १४.५; १५.५; १७.१; २; २२.३; २५.१; २; २७.१; २९.८; १२; ५४.५; ८; ५९.८; ४.१.२; २.३; ८.२; ३; ३०.५; ५.१.२; ११; ४.४; ६; १३.६; २१.१; २६.१; २; २८.१; ५; ४०.८; ५२.१५; ६.२.११; ४.१; ११.३; १४.६; १५.१८; १६.२; ४४; १७.८; २८.३; ४८.४; ५०.१; २; ४; ९; ५२.५; ७.२.१०; ३.३; ९.५^{2}; १०.५; ११.३; ५; १३.२; १६.४; १७.२–४; ३०.३; ३४.८; ४२.३; १०४.१४; ८.२.४; १०.२; १९.२७; २७.१; ३६.३; ३९.१; ४४.३; ४८.३; ६०.४; ७५.२; १०२.२; १६; १०३.२; ९.११.१; २९.१; ४२.४; ५; ४४.१; ४५.२; ७१.६; ८०.१; ४; ९०.५; ९२.१; ९४.५; ९७.४; १२; ४१; ४२; ९८.७; १०१.४; १०.१.६; ७; २.१; २; ४; ५; ६.४^{2}; ७.६^{2}; १२.२; ५; १४.३; ३५.१०; ४९.११; ५३.२; ५४.१; ५५.३; ५६.२; ३; ६४.१४; ६५.९; १५; ६६.१; ४; १३–१५; ७०.३; ४; ७२.८; ९३.२; ९५.१८; ९८.४; १००.३; ११०.१; १३०.५; १५०.३

देवानाम् १.२२.९; ३१.१; २; ४३.५; ४४.१२; ५०.५; ६८.१; ६९.१; ७०.३; ८९.२^{3}; ९४.१३; १०७.१; ११३.१९; ११५.१; ११६.२; १३३.७; १३६.७; १४१.११; १६०.४; १६२.७^{2}; १६४.५; १८५.४; ६; ११; १८७.६; १८८.११; २.३.९; ४.२; ८.६; २३.१६; २४.३; २५.५; २६.३; ३२.६; ३.१.१७; २.८; ३.७; ४.१०; ५.५; ७.७; ८.९; ११.६; १७.३; ५४.१९; ५५.१^{2}; २–२२; ५६.१; ६०.६; ६२.१३; ४.१.२०; २.१८; १२.५; २५.३; २७.१; ३३.२; ९; ३५.३; ४३.२; ५८.१; ५.२.८; ५.१०; २६.६; ४२.४; ४६.७; ६२.१; ६.१५.९; १३; ५१.२; १२; ६२.८; ७.२.१०; ७.२; ३५.३; १५; ४१.४; ४२.२; ४७.३; ६५.२; ७६.१; ४; ५; ७७.३; ८.१३.२; ३१.७; १५–१८; ३९.६; ६०.६; ६९.३; ७५.८; ७९.९; ८३.१; ९४.८; १००.१०; १०१.१२; ९.१.४; ७६.१; ७८.१; ८१.२; ८३.४; ८४.३; ८५.२; ८६.७; १०; ८७.२; ९५.२; ९६.६; ९७.५; ७; २४; ९९.४; १०७.२२; १०८.४; १०९.४; १०.२.३; ४.२; १०.८; ११.९; १२.९; १६.२; ८; २७.२३; ३१.१; ३२.६; ३३.९; ३५.१; ८; ३६.२–१०; ११^{2}; १२; ४८.११; ५६.१; ६४.१; ७०.२; ९; १०; ७२.१–३; ७७.७; ८२.३; ८८.१५; ९३.३; १०३.९; १०९.५; ११०.३; १०; ११; १२१.७; १३७.३; १५०.४; १६८.४; १७१.४

देवाय १.२०.१; १३५.१; २.३०.१; ३५.५; ३.१३.१; ४.३.३; ५.१६.१; ६.६८.९; ७.१४.१; ३; १७.७; ४६.१; ८६.७; ८.८९.१; ९.६.७; ११.२; ९८.१०; १०८.८; १०.३७.१; १२१.१–९

देवासः १.२३.८; ३९.५; १०५.१२; २.४१.१५; ५.४१.१७; ७.५९.१; ८.७.२७; २७.१०; ३०.१; ३१.५; ४७.१३; ५४.३; ९.९७.२०; १०.१२६.१

देवासः १.३.८; ९; १९.३; ६; २६.८; ३६.४; १०; ५२.१५; ५९.२; ८३.२; १०२.१; १०३.७; १०४.२; १२३.१; १२८.८; १३१.१; १३६.४; १६२.१५; २.४.३; ३.१.३; ४; १३; २.३; ३.५; ४.२; ८.६; ११.९; २९.७; ९; ५४.९; ४.१.१; १९.१; २६.२; ३०.३; ३५.८; ५८.४; ५.२१.३; २५.२; २६.९; ६.१५.८; १६.४८;

४४.८; ५८.४; ६७.५; ९; ६८.४; ७.१७.६; ३२.९; ४३.३; ८२.२; ८.१२.२२; १३.१८; १९.१; २३.१८; २७.१४; २८.१; २९.७; ८४.२; ९२.२१; ९३.१४; ९७.९^{२}; १०२.१७; ९.१३.५; १८.३; ४९.४; ६५.२४; ७८.४; १०१.५; १०२.५; १०६.८; १०९.१५; १०.६.७; २८.८; ३३.१; ४८.३; ५३.७; १०; ६३.४; ६५.१३; ६६.९; ११; ७०.६; ८८.९; १०; ९३.७; ११३.८; १३६.२

देवासः १.३.७; १३९.११^{२}; २.३१.२; ४१.१३; ४.३६.५; ५.४१.१७; ६.५२.७; ७.४८.४; ८.२७.९; ३०.४; १०.३५.१४; ६१.२७; ६३.६; ८; १४; ६४.११; ६६.१४; १०७.११; १२८.४; ५

देविं ७.७५.२; ८.२७.५

देवि १.४८.१; १५; १२३.३; १०; १२४.१२; २.३२.६; ४१.१७; ३.६१.१; २; ५.६१.१७; ६.६१.५; ६; ६४.२; ६; ७.७७.५; ८१.४; ८.९.१६; १७; १८.४; ६७.१०; १०.१७.८

देविंऽतमे २.४१.१६

देवी १.४०.३; ४८.३; ५६.४; ९२.९; १०; १०६.७; १०९.४; ११३.१३; १४; २.३.८; ४०.६; ४.१४.३; ३४.१; ५१.११; ५५.७; ५.३२.१०; ४१.१८; ४३.११; ५१.११; ८०.३; ६.५०.५; ६१.४; ६४.५; ७.३४.१; ३७.७; ३८.४; ४०.२; ४; ७५.७; ७८.२; ७९.३; ९०.३; ८.२५.१०; ९.५८.२; १०.११.८; ५९.७; ७०.८; १२७.१–३; १३४.१–६; १४१.२

देवी इतिं १.१०६.३; १६०.१; २.३१.५; ३.२५.३; ४.५६.२; ५.३२.९; ६.४४.५; ७.९७.८; ८.९३.१२; १०.६४.१४; ७०.६

देवी इतिं ४.५५.६; ९.९८.९

देवीः ५.५.५; १०.११०.५; १२८.५

देवीः १.१३.६; ९; २२.११; २३.१८; ८३.२; १४२.६; १५३.४; १७३.८; २.३.५; ८; ३५.५; ३.४.८; ७.२; ३२.६; ३४.८; ५६.४; ४.३.१२; ५.१३; २२.७; ५१.८; ५.५.८; ४६.८; ७.२.८; ४७.३; ४९.१–४; ५०.४; ७२.३; ८५.३; ९.५.५; ८; ९.६; ६९.४; १०.९.४; १७.१०; ३०.६; ६४.९; १०४.८; १०९.१; ११०.८

देवीः १.१२४.१३; ४.५१.४; ५; १०; ५.४६.७; ८.८०.१०; १०.७०.८; ९७.४

देवीम् १.८८.४; ११५.२; ३.१८.३; २०.५; ६१.५; ४.४३.१; ५५.३; ५.४३.६; ६९.३; ८०.१; ६.५०.१; ७.३४.९; ४४.२; ८५.१; ८.१००.११; १०१.१६; १०.१०१.१; ९

देवृषु १०.८५.४६

देवे ७.१०४.१८

देवेन १.९१.२३

देवेभिः १.१.५; १४.१; २; ३४.११; १२७.११; १५९.१; १७९.२; २.२०.८; ३६.३; ३.३.२; ६; १०.४; १३.१; १५.६; २४.४; ४०.३; ४६.३; ४७.३; ५३.१०; ४.४६.६; ५६.२; ५.२६.४; ५१.१; ३; ८; ६.११.६; १६.१; २०.२; २५.८; ५०.१३^{२}; ६७.१०; ७.१४.३; ३४.१५; ७२.२; ७५.७; ८.१८.४; २६.८; ३८.७; ७१.३; ९.९३.४; ९७.१; १०.६.२; ६४.१०; ८२.५; ८८.३; ९२.६; ९८.६; ९९.१०; १००.१; ११३.२; १२५.५

देवेभ्यः १.१३.११; ५९.५; ७४.९; १३९.७; १४२.६; १६२.४; ११; १८७.११; १८८.१०; २.३.१०; ३८.१; ३.९.५; ६; ३४.७; ४.५४.२; ५.५.११; ६.४४.७; ५१.८; ७.९८.३; ८.१०१.१६; ९.३.९; ८.५; ११.७; २३.६; २५.१; २८.२; ४२.२; ६२.२०; २१; ६५.२; ३; ६७.२८; ८०.४; ८६.३०; ९९.७; १००.६; १०३.६; १०५.३; १०६.६; १०७.२३; १०९.५; १२; २१; १०.१३.४; १६.९; ११; १७.३; ५१.७; ६५.६; ७०.२; ८५.१७; १९; ९७.१; १०४.८; ११०.४; ५; ११८.५; ११९.१३; १५०.१; १८०.३

दैव्या १.१३.८; १४२.८; १८८.७; २.३.७; ३.४.७; ७.८; ५.५.७; ६.४८.१०; ७.९७.२; ८.१८.८; ९.५.७; १०८.३; १०.६५.१०; ६६.१३; ११०.७

दैव्याः १०.२.१; १२८.३; १३०.७

दैव्यानि १.७०.१; ९२.१२; १२४.२; ४.४.५; ५.४१.१४; ७.४.१; ७५.३

दैव्यायाः १०.८७.११

दैव्ये ४.५४.३; ७.८९.५

दैव्येन २.३५.८; ३.८.१; ४.१.१५; ३४.८; ७.३३.११; ५३.२; ८२.८; १०.८७.१२; १०८.९

दोः ५.६१.५

दोघम् ५.१५.५

दोधतः १.८०.५; २.२१.४; ८.६.६; १०.११९.२; १७१.२

दोधवीति २.४.४

दोधुवत् ९.१५.४; १०.२३.१

दोषण्यम् १०.१६३.२

दोषा १.१०४.१; २.८.३; ४.२.८; ११.६; ५.३२.११; ६.५.२; ३९.३; ७.१.६; ३.५; ८.२२.१४; २५.२१; १०.४०.२; ४

दोषाः १.३४.३; १७९.१

दोषाम् ४.१२.२; ५.५.६; १०.३९.१

दोषाऽवस्तः १.१.७; ४.४.९; ७.१५.१५

दोहत् १.१६४.२६

दोहते ९.१८.५; ८६.१८; १०.१३३.७

दोहते १.१३४.४; ८.९३.३

दोहना ८.१२.३२

दोहनाः १.१४४.२; ९.७५.३

दोहसा १०.११.१

दोहसे १.१४१.२; ६.४५.७; ६६.१; ५

दोहसे ५.४४.१

दोहेन १०.४२.२

दौःऽगहे ४.४२.८

द्यवि १.३९.४; ३.२७.१२; ५.६.४; ६.५२.१३; ७.३१.९; ८.६.४०; ४३.४; ४४.२९; ९.२६.३; २७.५; १०.९४.५; १३८.६

द्यविऽद्यवि १.४.१; २५.१

द्यवी इति ४.५६.५

द्याम् १.३०.१९; ३१.४; ३२.४; ३३.१४; ३५.७; ९; ५०.७; ५१.९; ५२.११; ६७.३; ९६.२; १२१.२; ३; १२७.२; १४१.८; १५४.४; १६४.११; १७३.६; १७४.३; १८०.१०; २.११.५; १५; १२.२; १२; १५.२; १७.२; ५; ३.३०.९; ११; ३२.८; ३४.८; ३८.२; ४४.३; ५९.१; ४.६.२; २२.३; ३३.१; ३६.१; ४३.५; ५२.७; ५.२९.६; ४६.३; ५७.३; ६२.३; ६३.३; ६; ८५.४; ६.१७.७; ३०.५; ४७.५; २९; ४८.२१; ५१.८; ६४.२; ६७.६; ७२.२; ७.३.३; २४.५; ८.१४.१४; ४१.१०; ४२.१; ७२.१८; ८९.५; ९.८५.९; ८६.२९; ९६.३; ९७.१३; १००.९; १०.३.५; १६.३; ४५.७; ५५.१; ६३.१०; ६५.७; ६७.१०; ६८.११; ७४.२; ८१.२; ६; ८८.३; ९; ८९.४; ९२.१; ९४.१२; १११.५; ११९.८; १२१.१; १२५.७; १४९.१; १५३.३

द्याम्ऽइव ४.७.३; ३१.१५; ७.३३.५; ८.४१.८

द्यावः १.३५.६; ५१.१; १५१.९; २.३४.२; ३.३२.९; ५१.५; ४.१६.१९; ५७.३; ५.४१.१४; ५३.५; ६.४.३; २४.७; ३८.४; ७.८७.५; ८८.४; १०१.४; ८.६.१५; ७०.४; ५; १०.१२.४; ११५.७

द्यावा १.६१.१४; ६३.१; ११३.२; १४३.२; १५९.१; १८५.२–८; २.१२.१३; ४१.२०; ३.६.४; ५.४३.२; ६.११.१; ७.४३.१; ५३.१; ६५.२; ८.९७.१४; ९.७०.२; १०.१२.१; ३५.३; ३७.२; ४६.९; ९१.३

द्यावाक्षामा १.९६.५; १०२.२; १२१.११; १४०.१३; ३.८.८; ६.३१.२; १०.३६.१

द्यावाक्षामा ८.१८.१६

द्यावापृथिवी इति १.३५.९; ५२.१४; ६१.८; १०१.३; ११२.१; ११५.१; ३; १६०.१; २.१.१५; २.७; ३.३.११; २५.३; २६.८;

३०.४; ३२.१०; ५८.८; ४.१४.२; ५४.६; ५६.१; ३; ५.४७.२; ५१.११; ५५.७; ६३.२; ८३.८; ६.१८.१५; ४४.२४; ७०.१; ४; ५; ७५.१०; ७.३५.५; ४४.१; ८.२२.५; ४८.१३; ९६.१६; ९.६८.१०; ८१.५; ९७.४२; १०.१.७; २.७; ३१.७; ८; ३५.१; ३६.१; ३७.६; ४५.१२; ४७.८; ६३.९; ६४.१४; ६५.८; ६६.४; ६; ९; ७०.१०; ८१.४; ८२.१; ८९.६; ९२.११; ११०.९; ११३.१; ५; ११४.८; १२५.६; १४९.२

द्यावापृथिवी इति १.३१.८; १५९.५; १६०.५; १८५.११; २.३२.१; ६.५०.३; ७.५२.१; ५३.२; ३; ८.४२.२; ९.६९.१०; १०.६७.१२; ९३.१; १०

द्यावाभूमी इति १०.६५.४; ८१.३

द्यावाभूमी इति ४.५५.१; ७.६२.४; १०.१२.४

द्युक्ष ८.३३.१५; ६६.६

द्युक्षः ६.२४.१; ३७.२; ७.३४.२४; ९.५२.१

द्युक्षऽतमः ९.१०८.१

द्युक्षम् १.१३६.२; ६; २.२.१; ५.३९.२; ७.३१.२; ८.६९.१६; ८८.२; ९.७१.४; १०.१८५.१

द्युक्षऽवचसम् ६.१५.४

द्युक्षा १.१००.१६

द्युक्षाय ८.२४.२०

द्युक्षासः ३.४०.५

द्युऽगत् ८.९७.४

द्युतत्ऽयामा ६.४९.४

द्युतत्ऽयामानम् ५.८०.१; १०.९३.१२

द्युतम् ९.५४.१

द्युतयन्त २.३४.२

द्युता ६.२.६; १०.९९.२

द्युतानः ४.५.१०; ७.८.४; ९.६४.१५; ७५.३

द्युतानम् ६.१५.४

द्युतानात् १०.१८१.१–३

द्युतानाम् ७.७५.६

द्युऽभक्तम् ४.१.१८; ७.४०.२

द्युऽभक्ताः १.७३.६

द्युऽभिः १.३४.८; ५३.४; ११२.२५; २.१.१; ३.३.२; ३१.१६; ५.१६.२; ५३.३; ६.५.६; ७.१८.२; ३१.८; ८.४०.८; ९.८६.४२; ११२.२; १०.३.३; ७.४; ५; ५९.४; १८९.३

द्युऽमः ६.१०.२

द्युऽमत् १.७४.९; २.९.६; २३.१५; ३.१०.८; १३.७; ५.११.१; १८.५; १९.३; २३.४; ६.१६.४५; ४८.७; ७.८.६; ६६.१७; ९.१३.४; ३२.६; १०.२.७

द्युऽमतः ६.१७.१४; ५०.११

द्युऽमता ६.६२.१०

द्युऽमतीम् ६.३८.१; ७.५.८; १०.९८.२; ३

द्युऽमते १.६३.३

द्युमत्ऽतम १.५३.३

द्युमत्ऽतमः ९.६५.१९; १०८.३

द्युमत्ऽतमम् १.२८.५; ५.२४.१; ६.४४.९

द्युमत्ऽतमानि ८.१०१.७

द्युमत्ऽसु १०.६९.७

द्युऽमन्तः ५.१२.४; २५.८; ६९.२; ७.१.४

द्युऽमन्तम् १.६४.१४; २.७.१; ३.३०.१९; ४.३६.८; ५.६.४; २६.३; ३१.४; ६.१७.४; ७.१५.७; ९.२९.६; ६३.२९; ६५.४; ६७.३; १०६.४; १०.४०.१; ८४.४

द्युऽमान् १.६२.१२; ४.१५.४; ३१.१४; ५.३४.३; ८.३१.३; ९.५.३; ६१.१८; ६४.१; ८०.२; १०.११.७; ६९.७

द्युम्नम् १.९.८; ५४.११; ७३.४; ७७.५; १०३.३; २.२.१०; ३.३७.१०; ५९.६; ५.७.९; १०.१; ५०.१; ७९.७; ६.५.७; १९.९; ३५.२; ४६.७; ७.२५.३; ८२.१०; ८३.१०; ८.१९.१५; ९.८.८; १०८.९; १०.२९.४

द्युम्नऽवत् ३.२९.१५; ९.६६.३०

द्युम्नवत्ऽतमः ६.४४.१; ९.२.२

द्युम्नऽवर्धनः ९.३१.२

द्युम्नऽवान् ५.२८.४

द्युम्नऽश्रवसे ५.५४.१
द्युम्नऽसहम् १.१२१.८
द्युम्नऽसाता १.१३१.१
द्युम्नस्य ५.७.३; २३.१
द्युम्नहूतिऽभिः १.१२९.७[२]
द्युम्नऽहूतौ ४.१६.९; ६.२६.८
द्युम्ना ४.४.९; ५.३८.१; ८६.१; ६.१९.६; ६८.७; ८.१९.३३; २६.२२; १०.४२.६
द्युम्नानि १.१२२.१२; १३९.८; ३.४०.७; ४.४.६; ५.२८.३; ८.२८.५; ९.४०.४; ६१.११
द्युम्नाय ६.६०.११; ८.९.२०; २४.१२; ९.१०९.११
द्युम्निऽतमः ८.९२.१६
द्युम्निऽतमम् ८.१९.६
द्युम्निनः १.१३८.२[२]
द्युम्निनम् ३.३७.८
द्युम्निनी ८.७४.९
द्युम्निन्ऽतमः १.१२७.९; १७५.५
द्युम्नी १.३६.८; ९१.२; ८.८७.१; ८९.२; ९३.८; १०३.९; ९.१०९.७; १०.६९.५; ९६.३; १५९.४; १७४.४
द्युम्ने ९.६१.२९
द्युम्नेन १.४८.१; १६; ३.२४.३; ६.५.५; १६.२१; १८.७
द्युम्नेभिः १.९१.२; ६.६१.१३; ७.७.६
द्युम्नेषु ३.३७.७
द्युम्नैः १.७८.१–५; ४.१२.१; १६.१९; ६.४४.१; ८.५.३२; १९.१४; २०.१६; ७४.९; १०.११५.७
द्यून् १.३३.११; ७१.६; ११३.१३; ११६.२४; १२१.३; ७; १४८.४; १६७.१०; १८०.८; १९०.४; २.१३.१३; १४.१२; २७.८; २८.२; ३.२३.२; ४.४.८; ९; ३३.७; ४३.३; ५.६९.१; ८६.५; ६.६७.६; १०.११.७; १७.११; २७.५; ४५.११
द्योः १.११५.५; ४.२७.३; ३८.८; ६.६६.८; ६७.६; १०.६८.४
द्योतनः ८.२९.२
द्योतना १.१२३.४
द्योतनाय ६.२०.८
द्योतनिम् ३.५८.१; १०.१२.७
द्योतमानाम् १०.१७७.२
द्योतयत् ६.३९.३
द्यौः १.८.५; २२.१३; ५२.१०; ५७.५; ६५.२; ७१.८; ८९.४; १०; ९०.७; ९४.१६; ९५.११; ९६.९; ९८.३; १००.१९; १०१.११; १०२.११; १०३.८; १०५.१९; १०६.७; १०७.३; १०८.१३; १०९.८; ११०.९; १११.५; ११२.२५; ११३.२०; ११४.११; ११५.६; १३०.१०; १३१.१; १३३.६; १६४.३३; १९१.६; २.२.५; ३.६.३; ३२.११; ५४.१९; ४.१.१०; १७; १७.१; २; ४; १३; २१.१; २२.४; ५१.११; ५.३६.५; ४१.११; ४५.२; ३; ५४.९; ५८.६; ५९.८; ६.१२.२; १७.९; २०.१; ३६.५; ४८.२२; ५०.१३; ५२.२; ६८.४; ७०.६; ७२.३; ७.५.४; ७.५; ३४.२३; ८४.२; ८.७.२६; १५.८; २०.६; ४०.४; ५६.१; १००.१२; ९.८६.९; ९७.५८; १०.१०.५; २९.६; ३६.२; ४४.८; ४५.४; ८; ४९.३; ७–१०; ६३.३; ६७.५; ७४.२; ८५.१; ७; १०; ८८.२; ८; ९०.१४; ९२.४; १२१.५; १३२.१; ४; ६; १३३.५; १७३.४
द्यौः ६.५१.५
द्यौःऽइव २.४.६; ५.५७.४; ६.५८.१; ७.८७.६; ८.४१.५
द्यौत् ४.४.६
द्रप्सः ६.४१.३; ७.८७.६; ८.१७.१४; १९.३१; ९६.१३; १५; ९.६९.२; ८९.२; ९६.१९; १०.१७.११–१३; ९८.३; १२३.८
द्रप्सम् ४.१३.२; ७.३३.११; ८.९६.१४; ९.७८.४; ८५.१०; १०.११.४; १७.११
द्रप्सस्य ९.७३.१
द्रप्साः १.९४.४; ९४.११; ५.६३.४; ९.१०६.८; १०.९८.४
द्रप्साःऽइव ८.७.१६

द्रुग्धानि ७.८६.५
द्रुऽघनम् १०.१०२.९
द्रुणः १.१६१.१
द्रुणा ५.८६.३; ८.९६.११; ९.१.२; ६५.६; ९८.२
द्रुऽपदे ४.३२.२३
द्रुऽपदेषु १.२४.१३
द्रुऽसत् ९.७२.५
द्रुऽसदम् १०.११५.३
द्रुऽसद्वा ६.३.५
द्रुहः १.१२१.४; १३३.१; ३.३१.१९; ७.६१.५; ७५.१; ८.३७.२
द्रुहः २.२३.१६; १७; ३५.६; ४.४.१५; २८.२; ५.७४.४; ६.२०.५; ७.१६.८; ५९.८; १०४.७; ८.४७.१; ९.७१.१; १०.२५.८; ४८.१०; ७३.२
द्रुहन् १.५.१०; ४.२३.७
द्रुहम्ऽतरः १.१२७.३[2]
द्रुहा ७.१०४.७; १७
द्रुहे २.३०.९
द्रुह्वः ७.१८.६; १४
द्रुह्वि ८.१०.५
द्रुह्युम् ७.१८.१२
द्रुह्युषु १.१०८.८
द्रुह्यौ ६.४६.८
द्रुह्वणे ६.२२.८; १०.९९.७
द्रुह्वाणः १.२५.१४
द्रूणानः ४.४.१
द्रोः १०.१०१.१०
द्रोघऽमित्रान् १०.८९.१२
द्रोघऽवाचः ७.१०४.१४
द्रोघाय ६.६२.९
द्रोणऽआहावम् १०.१०१.७
द्रोणम् ६.४४.२०; ९.९३.१
द्रोणऽसाचम् १०.४४.४
द्रोणा ९.६७.१४
द्रोणानि ९.३.१; २८.४; ३०.४; ३३.२; ३७.६; ६५.१९; ९६.१३
द्रोणिऽअश्वासः १०.९९.४
द्रोणे ६.२.८; ३७.२
द्रोणेषु ९.१५.७
द्रोण्यः ५.५०.४
द्वके इति १०.५९.९
द्वयान् ६.२७.८
द्वयाविनः १.४२.४; २.२३.५; ९.८५.१
द्वयीभिः ९.७२.३
द्वयुः ८.१८.१४
द्वयुम् ८.१८.१५; ९.१०४.६; १०५.६
द्वयेन १.१४७.४; ५; ५.३.७; १२.२
द्वयोः १.८३.३; ६.४५.५; ८.४५.३४
द्वरः १.५२.३
द्वरिषु १.५२.३
द्वा १.१३१.३; १४४.४; १६१.३; १६२.१९; १६४.२०; ४.३०.१९; ३३.५; ६.६७.१; ७.१८.२२; ८.२९.८; ९; ७२.७; ९.८६.४२; १०.१७.२; २७.१७; २३; ४८.७
द्वादश १.२५.८; १६४.४८; ४.३३.७; १०.११४.५
द्वादशऽअरम् १.१६४.११
द्वादशऽआकृतिम् १.१६४.१२
द्वादशस्य ७.१०३.९
द्वाऽद्वा ८.६८.१४; १०.४८.६
द्वाभ्याम् २.१८.४; १०.६७.४
द्वारः १.१३.६; १३०.३; १४२.६; २.३.५; ७.१५.२; ९.५.५
द्वारः ५.५.५; १०.७०.५; ११०.५
द्वारा १.१२८.६; ३.५.१; ४.५१.२; ८.३९.६; ६३.१; ९.१०.६
द्वाराऽइव ८.५.२१
द्वारौ १.४८.१५; ७.९५.६
द्विः १.५३.९; १२२.१३; ४.६.८; ६.६६.२; ८.७०.१२; ९.९८.६; १०.१२०.३
द्विऽजन्मा १.१४०.२; १४९.४; ५
द्विऽजन्मानः ६.५०.२
द्विऽजन्मानम् १.६०.१
द्विऽजाः १०.६१.१९
द्विऽजानिः १०.१०१.११

ध

धक्तम् १.१८३.४
धक्षत् १.१३०.८; २.४.७; ६.३.४
धक्षतः १०.९१.७
धक्षि १.७६.३
धक्षि १.१४१.८; २.१.१०; ४.४.४; ६.१८.१०
धक्षुषः १.१४१.७
धक्षोः २.४.४; १०.११५.४
धत् ४.२७.५[२]
धत्त १.१७१.१; ४.३३.१०; ७.५६.२०; ९.६८.१०; १०.४५.१२
धत्त १.६४.१५; ८५.१२; २.१२.५; ४.३४.१०; ५८.१०; ५.६०.७; १०.१५.७
धत्तन १.२०.७; ६४.१४; १०३.५; ५.५३.१३; १०.३०.१४
धत्तम् १.४७.१; १८०.९; ७.६७.१०; ६९.८; ९७.१०; ९८.७; ८.८.१३; ३५.१०–१२; २२–२४; १०.४०.१३
धत्तम् १.४७.६; ९३.२; ७; १२; १५९.५; ४.४२.१०; ४९.४; ५७.८; ६.५२.१६; ६९.१; ६; ७४.३; ७.५३.३; ८४.४; १०४.२; ८.८.१५; ९.२; ३५.१०[२]; ११[२]; १२[२]; ५९.४; ७[२]
धत्तात् ३.८.१
धत्ताम् ४.५१.११
धत्ताम् १०.१८४.२
धत्ते १.८५.९; ६.१३.४
धत्ते १.४०.४; ९५.१०; १२२.९; १२५.१; ३.१०.३; ४४.४; ५.१८.२; २८.२[२]; ८.२३.२१; १०३.४; ५; ९.७६.२
धत्थ ४.३४.१०; ८.२७.२१
धत्थ ५.५४.१४; ७.३७.२
धत्थः ६.६८.६; ७.६८.६
धत्थः १.१५७.५; ६; ५.६३.७
धत्से ८.९६.५
धत्स्व १०.८७.२
धनऽअर्चम् १०.४६.५
धनऽजित् १०.१७०.३
धनऽजिते २.२१.१
धनऽदाः ६.१९.५; ७.३२.१७; १०.११६.९; १४१.१
धनऽदाम् १.३३.२; १०
धनऽभक्षेषु १०.१०२.१
धनम् १.३६.४; २.१३.१०; ३.२.१२; ६.४५.२; १२; १५; ७.३२.१२; ८.१९.१८; ६८.९; ८०.८; ९.९७.३८; १०.३१.११; ३४.१०; ४२.५; ४८.५; ६४.६; ८४.७; ९७.८
धनम्ऽजय ९.४६.५
धनम्ऽजयः १.७४.३; ९.८४.५
धनम्ऽजयम् ३.४२.६; ६.१६.१५; ८.४५.१३
धनम्ऽधनम् २.२३.१३; ९.८५.८; १०.१५६.१
धनयन् १.७१.३
धनयन्त १.१६७.२
धनयन्ते १.८८.३
धनऽसाः २.१०.६; ८.३.१५; १०.६५.१०
धनऽसातये १०.१५०.४
धनऽसातौ १०.१५०.४
धनऽसाम् १.११२.७; १०; ८.८६.४
धनऽसैः १०.६७.७
धनऽस्पृत् ३.४६.२
धनऽस्पृतम् १.३६.१०; ६४.१४; ५.८.२; ६.१९.८; ८.७.१८; ५०.६; ९.६२.१८; १०.४७.४
धनस्य ६.४४.९; ८.३.५; ९.९७.२९
धना १.६४.१३; ८१.३; १०२.१०; १३०.६; १५७.२; २.२४.९; १३; २६.३; ५.३२.९; ९.६१.२३; ७९.२; १०.३४.१२; ४२.९; १२०.४; १४७.४
धनानाम् १.४.९; ३१.८; १०२.५; १२४.७; ३.१८.५; ३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.११; ३६.११; ३७.११; ३८.१०; ३९.९; ४३.८; ४८.५; ४९.५; ५०.५; ४.२०.३; ५.४२.५; ७; ६.२६.८; ९.९६.२०; १०.३०.११; ८९.१८; १०४.११; १३९.३
धनानि १.३०.१६; ४२.६; १००.९; १३; १०८.१३; १३०.६; ७[२]; ४.५०.९;

८.१४.६; ९.६५.९; ७९.२; ९०.३; १०.४२.१०; ४३.१०; ४४.१०; ४८.१
धनाय १.१००.८; १०४.७; ४.२३.१; ८.७१.५; ९.९७.४; १०९.१०
धनिनः १.१५०.२
धनिनम् १.३३.४; ४.२.१५
धनिष्ठा १०.७३.१
धनुः ६.७५.२; ८.७२.४; ७७.११; ९.९९.१; १०.१८.९; १२५.६
धनुऽतरौ ४.३५.५
धनुत्रीः ३.३१.१६; ९.९३.१
धनुऽभ्यः ८.३.१९
धनुम् १०.२७.१७
धने १.३१.६; ४०.२; ५४.६; ११६.१५; १३२.१; ५; ६.४५.११; १३; ६१.५; ८.३.९; ५.२६; ८.२१; ४९.९; ५०.९; ९२.९; ९.५३.२; १०.६३.१४; १४७.३
धनेऽधने ५.३५.७
धनेन १०.१८.२
धनेषु ७.३८.८; ८.१६.५
धनोः १.३३.४; १४४.५; १०.४.३
धन्या ३.१.१६; ५.४१.८; ६.११.३
धन्याय ९.८६.३४
धन्व १.३५.८; २.३३.१०; ३८.७; ४.३३.७; ५.७.७; ६.१२.५; ९.९७.३; १०.८६.२०; ८९.६; १८७.२
धन्व ९.७५.५; ९७.१६–१९; ५२; १०५.४; १०६.४; १०९.१; ११०.१
धन्वऽअर्णसः ५.४५.२
धन्वऽइव ३.४५.१; १०.९३.६
धन्वऽचरः ५.३६.१
धन्वऽच्युतः १.१६८.५
धन्वन् १.३८.७; ९५.१०; ११६.४; १३५.९; ६.३४.४; ७५.३; ९.६९.१; ७९.३
धन्वनः १०.११६.६
धन्वना २.२४.८; ५.५३.६; ६.७५.२४; १०.११५.६
धन्वन्ऽइव १०.४.१
धन्वन्ति ९.९७.२०
धन्वन्तु ९.७७.३; ७९.१; २; ९७.२६
धन्वऽसहा १.१२७.३
धन्वसि ९.२४.३; ८६.३४
धन्वऽसु ५.५३.४; १०.६३.१५; १३३.१–६
धन्वाति ३.५३.४
धन्वानि ४.१७.२; १९.७; ५.८३.१०; ६.५९.७; ६२.२; ८.२०.४; १२
धम १०.१४५.२
धमतः ९.७३.१
धमति ५.९.५; १०.८१.३
धमथः ५.३१.९
धमनिम् २.११.८
धमन्तः १.८५.१०; २.३४.१; ४.२.१७
धमन्तम् ८.९६.१३
धमन्ता १.११७.२१
धमन्ति ८.७.१६; ९.१.८
धमन्ति ९.७३.५
धमन्तीः ३.३०.१०
धमितम् २.२४.७
धम्यते १०.१३५.७
धयति १.१७९.४; २.३५.५; १३; ८.९४.१
धरीमणि १.१२८.१; ९.८६.४
धरुणः १.७३.४; ५.१५.१; ९.२.५; ७२.७; ७४.२; ८६.८; ८७.२; ८९.६; १०.५.१; ४५.५
धरुणम् १.२३.१३; ५६.५; ६; १२१.२; ५.१५.२; ५; ७.३४.२४; ९५.१; ८.७२.१५; ९.१०७.५; १०.४७.२; ८३.७; १११.४
धरुणऽह्वरम् १.५४.१०
धरुणानि ४.२३.९
धरुणाय १०.५६.२; ६०.८
धरुणे ५.१५.२; ९.८९.५; १०.४४.४; १७०.२
धरुणेषु १.५२.२; ३.३.१; ९.७३.३; १०.५.६
धर्णसि १.१०५.६
धर्णसिः ५.४३.१३; ९.२.२; २३.५; ३७.२; ३८.६

धानाः १.१६.२; ३.३५.३; ७; ५२.५–८; ४.२४.७; ६.२९.४; १०.२८.१
धानानाम् ८.७०.१२
धानाऽवत् ३.४३.४
धानाऽवन्तम् ३.५२.१; ८.९१.२
धान्तु ९.८.२; १०.७४.३
धान्यऽकृतः १०.९४.१३
धान्यम् ५.५३.१३; ६.१३.४
धापय १०.१५१.५
धापयन्ते ५.४७.४
धापयेते इति १.९६.५; ३.५५.१२
धापयेते इति १.९५.१
धाम १.५७.३; ९१.३; ९५.९; १२१.६; १२३.८; ९; १४४.१; १५२.४; ५; १५३.२; २.३.११; ३.७.६; ४.५.४; ६.२.९; २१.३; ६७.९; ७.६१.४; ६३.३; ८७.२; ८.४१.१०; ९.६९.६; ८६.१५; ८८.८; ९४.२; ९६.१८; १९; ९७.५; ३१; ३२; १०९.४; १०.१०.६; ४५.२; ४८.११; ६५.५; ६७.२; ८९.८; १२४.३; १८१.२; १८९.३
धाम १.१२२.१२
धामऽधाः ९.८६.२८
धामन् १.४३.९; ४.७.७; ५८.११; ७.३६.५
धामनि ८.१२.३२
धामनी इति ९.६६.२
धामऽभिः १.१४.१०; २२.१६; ८५.११; ३.३.४; ३१.२१; ३७.४; ४.७.५; ७.६६.१८; ८.१९.१४; ९.६६.५; ६७.२६; १०२.२; १०.९३.६
धामऽभ्यः ८.२७.१५; ९२.२४
धामऽशः १.१६४.१५
धामऽसाचम् ३.५१.२
धामऽसु ८.१३.२०; ९.८६.२२; १०.२५.२
धामहे १.९२.१३; ५.१६.५; ९.७४.५
धामानि १.९१.४; १९; २.३.२; ३.३.१०; ५५.१०; ४.५५.२; ७.६०.३; ८.२१.४; ४१.७; १०१.६; ९.२८.२; ५; ६३.१४; ६६.३; ८६.५; ११४.१; १०.१३.१; ५६.५; ७०.७; ८०.४; ८१.५; ८२.३; ९७.१; २; १२२.३
धाम्नः १.८७.६; ७.५८.१
धाम्ना ९.३९.१; १०.१६६.४
धाम्ने ५.४८.१; ८.६३.११; ९२.२५; ९.२४.५; १०.७६.८
धायःऽभिः ६.३.८
धायसा ७.९५.१
धायसे १.३१.१३; ७२.९; ९४.१२; १३०.२; १४१.६; २.५.७; १७.२; ३.३८.३; ५०.३; ५.७.६; ९; १५.४; ७०.२; ९.७०.५; ८६.३
धायि १.१५८.३; ५.४४.८; ७.५.२; ८.६३.१२; १०.४६.१
धायि १.१४१.१; १४५.५; १७१.२; १९०.८; ४.७.१; २८.२; ३६.७; ५.४१.१५; ५६.७; ६६.२; ६.२०.२; ५; २९.५; ७.४.४; ८.५०.३; ७०.२; ९२.२९; १०.१०.३; ४५.७; ९६.४; ११५.२
धायीः १.१४७.५
धायुः ३.३०.७
धायू इति ७.३६.४
धारऽपूता २.२७.२; ९
धारय १०.२५.४
धारय १.३०.२२; ६.८.६; ८.१३.१२; ९५.८; ९.१२.९; ६३.१; ३०; १०.१९.३; २४.१; ५९.५; ६०.५; १२२.८; १७३.२
धारयः ९.२२.७; १०७.२३; १०.७३.४
धारयत् ७.६४.४; ८.३२.२५; ७७.६
धारयत् १.१०३.२; २.१५.२; १०.९२.१०
धारयतम् ५.२७.६; १०.१९.१
धारयताम् १०.१७३.५
धारयति ७.८५.३
धारयत्कवी इति धारयत्ऽकवी १.१६०.१
धारयत्ऽक्षितिम् १.१३६.३
धारयत्क्षिती इति धारयत्ऽक्षिती १०.१३२.२
धारयथः ५.६९.१
धारयथाः ६.३६.१
धारयध्वम् १०.७०.५

१३४.२[२]; १३५.५; १४३.६; १५१.६; २.२१.५; ३.३४.५; ६२.१०; ४.४१.८; ५०.११; ५.४७.६; ७१.२; ८१.१; ६.२१.१; ३५.१; ३; ५३.४; ६२.३; ७.१.१; २७.१; ६४.५; ६५.५; ६६.३; ७९.५; ८२.३; ९४.२; ९७.९; ८.३.१; १२; २१.६; १२; २६.२५; ३५.१६; ४०.९; ४६.११; ६०.१२; ६३.१; ८४.७; ९२.११; ९.१९.२; २२.३; ४७.४; ७९.१; ८६.१७; ९४.१; २; १०८.१०; ११२.१; १०.७.४; ३९.२; १०१.२; १०६.१; १३३.३; १३९.५[२]; १४२.२; १४३.३; १५६.१

धियः १.२३.३; ८७.४; ४.४१.५; ६.१.१; ७.३६.८; ९.७५.२; ९९.६

धियध्यै ७.३४.२४

धियम् १.२.७; ६१.१६; ८०.१६; ८८.४; १०२.१; १०९.१; १४३.७; १४४.१; २.३.८; ११.१२; २८.५; ३४.६; ३८.१०; ४०.५; ६; ३.१८.३; ५४.१७; ६२.८; ५.४५.६; ११; ६.१४.१; ४७.१०; ४९.७; ५२.१६; ५३.१०; ७.१.१०; ३४.८; ९; ३६.७; ४१.३; ६७.५; ८.६.४३; १३.२६; ४२.३; ८६.२; ९५.५; १०२.२२; ९.१००.३; ११०.७; १०.४२.७; ४६.५; ६४.१२; ६७.१; ७४.३; १०१.९

धियम्ऽजिन्वः ६.५८.२

धियम्ऽजिन्वम् १.८९.५

धियम्ऽजिन्वा १.१८२.१; ८.२६.६

धियम्ऽजिन्वासः ७.३३.१

धियम्ऽधाः १.६७.२; ७२.२; ४.४५.७; ७.२.२; १०.६१.१८

धियम्ऽधियम् १.१६८.१; ६.४९.८

धियम्ऽधे ७.१३.१

धियसानः ५.३३.२

धियसानस्य १०.३२.१

धिया १.१.७; २.६; ३.२; ५; ४६.२; ८; ५२.३; १३९.१; १४३.६; १५९.१; १६६.१३; २.३१.६; ३.२.१; ३.६; ११.२; ३; १२.१; २७.६; ९; ६०.२; ५; ६२.१२; ४.१.१०; १६.२१; १७.२१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११; ५६.४; ५.४५.११[२]; ६१.१५; ६.२.४; २२.७; ३८.३; ७१.६; ७.१.५; ३७.६; ८३.८; ९४.४; ८.१.१९; ३.१८; ४.१५; ६.२८; १३.८; २४.७; २६.१९; २७.८; १३; ६१.१; ६६.८; १४; ६९.१; ८७.६; ९२.१५; ९३.१७; ९६.११; १०३.११; ९.१५.१; २५.२; २६.१; ४; ४४.२; ६४.१६; ६७.२७; ७१.६; ७२.४; ७४.७; ७६.३; ८६.१३; ९१.१; १०१.३; १०.११.१; २९.४; ४०.१; ५३.६; ७४.१; ९२.१२; १५०.३; १७२.२; १७६.२

धियाऽजुरः ५.४३.१५

धियाम् ५.४४.१३

धियाऽयते १.१५५.१

धियाऽयते ९.१५.२

धियाऽयवः १.८.६

धियाऽवसुः १.३.१०; ५८.९; ६०.५; ६१.१६; ६२.१३; ६३.९; ६४.१५; ३.३.२; ८.८०.१०; ९.९३.५

धियावसो इति धियाऽवसो ३.२८.१

धिये १.२७.११; १११.४; ४.१.१८; २१.७; ५.४१.६; ६.५३.१

धिरे १.१६६.१०; ८.२८.५; ९.६८.१

धिषणा १.९६.१; १०२.१; ७; १०९.४; ३.३१.१३; ३२.१४; ४.३४.१; ५.४१.८; ६.११.३; १९.२; ७.९०.३; ८.१५.७; १०.३०.६; ९६.१०

धिषणाऽइव ३.४९.४

धिषणानाम् ५.६९.२

धिषणाभ्यः ४.३६.८; ९.५९.२

धिषणाम् १.२२.१०; ३.२.१; १०.३५.७

धिषणायाः १.१०९.३; १०.१७.१२

धिषणे ३.५६.६

धिषणे इति १.१६०.१; ३.४९.१; ६.८.३; ८.६१.२; १०.४४.८

धूर्तयः ८.४५.९
धूर्तिः १.१८.३; ७.९४.८; ८.२७.१५; ४८.३
धूर्तेः १.३६.१५; १२८.७²; ७.१.१३
धूर्वणे ९.६१.३०
धूर्वन्तम् १०.८७.१२
धूर्वन्ति ८.४५.९
धूर्वन्तु ६.७५.१९
धृतऽदक्षम् १०.४१.३
धृतऽदक्षा ५.६२.५
धृतऽव्रतः १.२५.८; १०; ४४.१४; १४१.९; २.१.४; ४.५३.४; ६.१९.५; ८.९७.११; १०.६६.५
धृतऽव्रता ८.२५.२; ८
धृतऽव्रता १.१५.६; ६.६८.१०
धृतऽव्रताः २.२९.१; १०.६६.८
धृतऽव्रताय १.२५.६; ८.४४.२५
धृतऽव्रते ८.२७.३
धृषजः ५.१९.५
धृषत् १.५४.३; ४; ५.३५.४; ६.४२.३; ४५.२१; ४७.६; ८.२१.२; ३२.४; ३३.३; ४९.४; ६२.५
धृषतः १.५४.३; ८.६२.५
धृषता १.५४.४; ७१.५; १६७.९; १७४.४; २.३०.४; ४.४.२; ५.६; २२.५; ६.६.३; ६; १८.१३; २२.६; ७.१९.३; ८.२४.४; ८१.७; ८९.४; १०.१११.६; ११५.६
धृषती २.३०.८
धृषत्ऽमनः १.५२.१२; ८.८९.४
धृषत्ऽवर्णम् १०.८७.२२
धृषत्ऽविनः ५.५२.२
धृषमाणः १.५२.५
धृषितः ८.३३.६; ९६.१७; १०.११३.५; १३८.४
धृषिता ८.५२.३
धृषिताः १०.८४.१
धृषितेषु १०.३८.१
धृष्णवः १.९२.१
धृष्णवः ५.५२.१४
धृष्णवे १.८१.३; २.१६.४; ८.२४.१; ९.९९.१

धृष्णु ३.३६.४; ६.६६.५; ८.६९.८; १०.३४.१४; ४९.२
धृष्णुऽओजसः २.३४.१
धृष्णुऽओजसम् ८.७०.३
धृष्णुः १.६३.३; ६.२५.५; २९.३; ७.२०.५; ९.४७.२; १०.१६.७; ६९.५; ६
धृष्णुना १.५४.२; ५६.४; १६७.९; १०.१०३.२
धृष्णुम् ६.६७.११
धृष्णुऽया १.२३.११; ४६.५; ५३.७; ४.२१.४; ३०.१३; ३१.१४; ५.१०.५; ५२.१; २; ४; ६.१६.२२; ४६.२; १०; ८.४९.२; १०.१०२.१
धृष्णुऽसेनः ३.५४.१५
धृष्णुऽसेनाः ६.६६.६
धृष्णुहि १.८०.३
धृष्णू इति १.६.२
धृष्णो इति १.३०.१४; ८४.१; २.३७.३; ३.५२.८; ४.१६.७; २२.५; ६.१७.१; २१.७; ३७.४; ७.१९.३; ८.२४.४; ३३.३; ४५.१४; ७३.१८; ७८.३; ८१.७; ९.१०८.६; १०.१११.६; १२०.४
धृष्णोः ७.५६.८; १०.२२.३
धेतन ८.६७.५; १०.३७.१२
धेथे इति १.१५८.२
धेनवः १.३२.२; ७३.६; ८४.११; १२०.८; १२५.४; १३४.६; १३५.८²; १५१.५; १५२.६; १७३.१; २.२.२; ५.५; ३.१.७; ७.२; ४५.३; ५५.१६; ५७.३; ४.२२.६; ५.६.१; २; ४३.१; ५३.७; ५५.५; ६९.२; ६.४५.२८; ७.३२.२२; ३६.३; ४२.१; ८.४.८; ४९.५; ७०.४; ८८.१; ९.१.९; १३.७; ३३.४; ६६.६; १२; ६८.१; ६९.४; ७०.१; ७७.१; ८६.१७; २५; ९७.३५; १००.७; १०.३२.४; ७५.४; ९५.६; ९६.२
धेनवे ८.४७.१२
धेना १.२.३; १०.१०४.१०
धेनाः १.१४१.१; ३.१.९; ३४.३; ४.५८.६;

ध्रुवा १.३६.५; २.५.४; ८.१७.१४; १०.१७३.४^{२}

ध्रुवाः ९.१०१.१२; १०.९४.१२

ध्रुवाणि १.१६७.८; ३.५६.१; ४.५.४; ५.६९.४

ध्रुवासः १.५९.३; ६.५२.४; ७.१००.४; १०.१७३.४

ध्रुवासु १.७३.४; ७.८८.७

ध्रुवे १.२२.१४; २.४१.५; ३.५४.७; ९.४०.२

ध्रुवेण १०.१७३.३; ६

ध्रुवेभिः १.८४.१८

ध्वजेषु ७.८५.२; १०.१०३.११

ध्वनयीत् १.१६२.१५

ध्वन्यस्य ५.३३.१०

ध्वरसः २.२३.५

ध्वरसम् ४.२३.७

ध्वसनौ १.१६४.२९

ध्वसन्तिम् १.११२.२३

ध्वसयः १०.७३.६

ध्वसयन्तः १.१४०.५

ध्वसयन्तम् १.१४०.३

ध्वसिराः ७.८३.३

ध्वस्मनऽवत् ६.१५.१२; ७.४.९

ध्वस्मा ८.६६.१५

ध्वस्मानः ४.६.६

ध्वस्रयोः ९.५८.३

ध्वस्रा १०.४०.३

ध्वस्राः ४.१९.७

ध्वान्तम् १०.७३.११; ११३.७

ध्वान्तात् १०.७३.२

न

न १.५.४; ७.७; ८.५; ७; ८; ११.३; १६.५; १८.४; ७; ९; १९.२; २३.१५; २४.६^{४}; २५.३; ४; ६; १४^{३}; १६; २७.१; ३०.२; ३; १४; १५; २१; ३२.४; ६; ८; ९; १३^{३}; १४; १५; ३३.२; ६; ८; १०^{२}; ३५.६; ३६.१३; २०; ३७.६; ३८.१; २^{२}; ५; ८; १३; ३९.१; ४; ९; १०; ४०.८^{३}; ४१.४; ९; ४२.८; १०; ४८.३; ६; ५१.१; १४; ५२.१; २; ४; ७; १४^{३}; ५३.१; ५४.१; ५५.१^{२}; २; ३; ७; ८; ५६.१; २^{२}; ३; ४; ५७.२; ३^{२}; ५८.२^{२}; ३; ५; ६^{२}; ५९.३; ४; ६०.५; ६१.१; ४; ८; १०; १२; ६२.७; १०; ११; १२^{२}; ६३.१; ७; ८^{२}; ६४.१; २; ६; ७; ९^{२}; ११; ६५.१; २; ३^{६}; ४; ५^{३}; ६६.१^{६}; २^{४}; ३^{३}; ४; ५^{२}; ६७.१^{२}; ३; ६८.५; ६९; १^{२}; २^{२}; ३^{२}; ५; ७०.२; ५; ६; ७१.१^{२}; ४; ७^{२}; ९; १०; ७२.२; १०; ७३.१^{३}; २^{२}; ३^{३}; ७४.७; ७७.३; ७९.१; २; ८०.३; १२^{२}; ८१.५^{३}; ८३.२; ८४.१; १९; ८५.१; ७; ८^{२}; ८८.१–३; ५; ६; ९१.३; ६; ८; १३; ९२.३–६; १२^{२}; ९४.२; ९५.६^{२}; १००.३; ५; १२; १३; १५^{२}; १०२.१०; १०४.१; ५; १०५.१; ७; ८; १६^{२}; १०६.१–६; १०९.१; ११२.२; १७; ११३.३^{२}; ११५.२; ११६.३; ९; १२; २३; ११७.४^{२}; ५^{३}; ११८.४; ११९.७; १२०.४; ५^{२}; १२१.६; १३; १२२.२; ९; १५; १२३.९; ११; १२४.३; ४^{२}; ६^{४}; १२७.१; ३^{३}; ५; ६^{२}; ८; ९^{२}; १०^{२}; ११; १२८.२; ५^{२}; ६^{२}; ७; १२९.१; २; ५; ६; ८^{२}; १०; १३०.१^{२}; २^{३}; ३; ६; ८; १३१.२^{२}; ७; १३२.५; १३३.६^{२}; १३५.५; ८^{२}; १३६.१; १३७.३; १३८.१^{२}; २^{२}; ४; १३९.१; १४०.६^{२}; १४१.७–१०; ११^{२}; १३; १४३.३; ४; ५^{२}; ७; १४४.३^{२}; ४; १४५.२^{३}; १४७.३; १४८.१–४; ५^{३}; १४९.२; ३^{२}; १५१.१; २; ४; ८; ९^{४}; १५२.४; १५३.१–३; १५४.२; १५५.६; १५६.१; १५८.३; ५; १६०.२; १६१.१; ११; १६२.२१^{२}; १६४.६; १०; १३^{२}; १६; १९; २२^{२}; ३२; ३७–३९; ४४; ४५; ४८^{२}; १६५.९^{३}; १४; १६६.२^{२}; १०; १६७.३^{२}; ४; ५; ९; १६८.२^{३}; ३^{२}; ५^{२}; ७^{२}; १६९.३; ४; ६; ७; १७०.१; ३; १७३.२; ३; ६^{२}; ९^{२}; १०^{२}; ११^{२}; १७४.३; ८; ९; १७५.३; ६; १७६.१; २;

४; ६; १७८.२; १७९.३; १८०.३–५; ६^{२};
९; १८१.३; ६; ८; ९; १८३.१; ५;
१८५.२; १८६.२; ५; ७^{२}; ८^{२}; ९;
१८७.११; १८९.७; १९०.२; ३; ४^{२}; ५;
६^{२}; ७^{२}; १९१.१; १०–१२; **२**.२.२–५;
७^{२}; ८; १०; ४.३–५; ६^{२}; ७^{२}; ८.३;
४; ९.५; १०.५; ११.१; ३; २०;
१२.५; ९; १०; १३.५; १४.३^{२}; ११;
१६.३^{३}; ७^{२}; ८^{२}; १८.८; १९.२;
५; ७; ८; २०.१; २३.४; ५^{४}; १६;
२५.३^{२}; २७.११^{४}; १३; २८.२; ४^{३};
८; ३०.१; ७^{४}; ३१.१; ७; ३३.९–११;
१५^{२}; ३४.१^{२}; २^{२}; ४–६; ८; १२–१४;
३५.६^{२}; ३८.९^{४}; ४१.८^{२}; ११; **३**.१.४;
९; १२; १४; २.१^{२}; ३; ७; १०; ११;
१४; १५; ३.१; ९.२; १०.५; १५.५;
२२.१; २६.३; ५; २७.१४;
२८.४; २९.६^{२}; १४; ३०.२; १२; ३१.२;
३२.७; ८; ९^{३}; ११; १६^{२}; ३३.४;
३५.१; ३६.४; ३८.१; ४१.५; ६; ४५.१;
४; ४६.४; ५; ४९.३^{२}; ४; ५३.२; १४^{२};
२३^{२}; २४^{२}; ५४.८; १४; २१; ५५.२१^{२};
५६.१^{४}; ५७.२; ५८.४; ५९.२^{४}; ६०.४;
६२.१; **४**.१.३; ६; १९^{२}; २.८; ९^{२}; १४;
१७; ३.१२; ४.१; ४; १३; ५.१; ३; ५^{२};
६; १२; १३; १५; ६.३–५; ६^{२}; ७^{३}; ८^{२};
१०^{२}; ७.११; १०.१^{२}; ३–५; ६^{२}; १३.२;
५; १४.५; १५.६^{२}; ७; १६.२; ३; ११;
१३; १४^{२}; १५^{२}; १९–२१; १७.४; १२;
१५; १६; १९; २१; १८.२; ३^{२}; १३;
१९.२; ४; ५; ७; ११; २०.५^{३}; ६^{२}; ७^{२};
११; २१.१; २; ९; ११; २२.८^{२};
११; २३.६; ११; २४.९; ११;
२५.५^{२}; ६^{३}; ७; २७.२; ४;
२८.३; ३०.१; १९; ३१.४; ९; ३२.८;
३३.१०; ११; ३४.११^{२}; ३८.२; ३; ५^{२};
६; ३९.२; ४०.३; ४१.१; ८^{२}; ४२.८;
४३.३; ४५.२; ४; ६; ४७.२; ४८.१;
५१.६; ८; ५२.५; ५४.४; ५५.६;

५८.५–७; **५**.२.१^{२}; ४^{२}; ५; १०; ११;
३.२; ५^{२}; १२^{२}; ४.९; ७.७; ८.५; ९.४^{२};
६; १०.२; ५^{२}; १२.१; २^{२}; ३; १५.३;
५; १६.१; २; ४; १७.३; १९.३; ४^{२};
५; २०.२; २९.८; १४; १५; ३०.१४;
३३.३; ५; ९; १०; ३४.४^{२}; ५^{२}; ३६.१;
२^{२}; ३; ३७.४; ४१.१; ४; ९; १०;
१२; ४२.२; ६^{३}; ४३.७^{३}; ८^{२}; १४;
४४.२; ९^{२}; १३; ४५.२; १०; ४६.१^{३};
४८.५; ५१.७; ५२.३; १२; १४; १५;
५३.१६; ५४.४; ५^{२}; ७^{७}; ८; १०; १३; १५;
५५.५; ७^{२}; ५६.३; ४; ५७.१;
५९.२–४; ७; ६१.३; १८; ६२.९; ६३.५;
६४.७; ६६.२; ६९.४; ७४.५; ७६.२;
३; ७७.२; ७९.९; १०; ८०.४; ५;
८२.२; ८४.२; ८५.३; ६; ८^{२}; ८६.६;
८७.२^{२}; ३^{२}; ५; ६; ८; ९; **६**.२.१^{२}; ४;
६; ७; ८^{२}; ९; ३.२^{२}; ३^{२}; ४^{३}; ५^{२}; ६;
७^{२}; ८^{२}; ४.२; ३^{२}; ५^{२}; ६^{२}; ७; ६.५;
७.४; ८.५; ९.१; २^{३}; १०.२; ११.१;
४–६; १२.१; २; ३^{२}; ४^{२}; ५; १३.१; २;
१५.२; ४; ५^{३}; १६.३९; ४०^{२}; १८.३;
८^{२}; १०^{२}; १२^{३}; १९.५; २०.१; २; ४;
६–८; १२; २१.३; १०; २२.११^{२};
२३.९; २४.३; ४; ६^{२}; ७^{३}; ८^{३}; २५.५^{३};
२७.३^{२}; २८.२; ३^{३}; ४^{२}; २९.३; ५;
३०.३; ४^{२}; ३४.२; ३^{२}; ४; ३५.३;
३६.३; ५; ४१.१; ४४.३^{२}; ६; २०;
४५.३; ७; २२; २३; २५; २७; २८; ३१;
४६.२; १४; ४७.१; ३; १०; १४^{२}; ४८.१;
१४^{३}; १५; २१; २२; ४९.१२; ५०.८;
१०; ५१.१; ५२.१^{४}; ५३.१; ५४.३^{२}; ४;
९; ५६.१; ५९.४; ६०.४; ६१.५; ६३.१;
२^{२}; ६४.१; ३; ६६.२; ४; ५^{२}; ६; ८^{२};
१०^{२}; ११; ६७.४; ७; ९^{३}; ६८.८; ९;
६९.८^{२}; **७**.१.५; २.५^{२}; ३.२; ४; ५;
६^{३}; ४.७; ५.७; ७.१; ३; ८.४; १०.१;
२^{२}; ११.१; १३.१; ३; १६.४; ९–११;
१५; २०^{३}; २१; २४; २५; १९.१; २०.६;

२१.३; ५[२]; ६[२]; २२.१; ५[२]; ८[२];
२३.४[२]; २४.५; २५.४; २६.१[२]; २;
२७.२; २८.३; ३०.३; ३१.११; ३२.२[२];
३; ९; १०; १२[२]; १८; २१[२]; २३[४];
३३.१; ४; ८; ३४.१; ४; ७[२]; १९;
३६.२; ३; ८; ३७.३; ४; ४०.३;
४३.१–३; ४७.३; ४८.१; ५६.१३; १६[४];
५७.३; ५८.३; ५९.७; ६१.२; ५[३]; ६३.३;
५; ६४.५; ६५.३; ५; ६७.१[२]; ८;
६८.८; ७०.१[२]; २; ७६.३; ५[२]; ७७.१;
७९.२; ८१.३; ४; ८२.७[४]; ८३.७; ८५.१;
८६.५[२]; ६; ७; ८७.१; २; ४; ६;
८९.२; ९०.७; ९१.२; ७; ९३.३; ९५.५;
९७.६; ९९.१; २[२]; १०३.२[२]; ३; ७[२];
८; ९; १०४.३; १३[२]; ८.१.२; ५[३]; १३;
१९; २०[२]; २३; २७[२]; २.२; ५[३]; ६;
१२[२]; १४; १७; १८; २२; २६; २८;
३.१०; १८; २३; ४.८; १०; १७; ५.३४;
३९; ६.७; १२; १५[३]; २३; २५; ३४;
३८; ७.१९; २६; ३६; ९.६; ८; १९;
११.४; १२.४; ६; ७; १३; १५;
२४[२]; १३.८; १४.४[२]; ९; १५.११; १६.२;
१९.६[२]; ८[२]; २६[५]; २७; ३३; २०.१०;
१३[२]; १४; २०; २१.१; १६; २३.८;
१५; २४.५[३]; १५[२]; १७; २१[२]; २५.२;
१५; १९; २६.२४; २७.९; १५; २२;
३०.१; ३१.६; ७[२]; १४; १६[३]; १७[२];
३२.४; ५; १५; १६[२]; २३; ३३.१; ८;
९; १३; ३४.३; ५; ३७.६; ३९.३;
४१.६; १०; ४३.७; २५[२]; ३२; ३३;
४४.२९; ४५.५; ९; २०; २९; ४६.२९;
३०; ४७.१; ३; ७[२]; १२[३]; ४८.५; ६;
१०; ४९.३; ५; ६[२]; ५०.२; ३; ५;
५१.३[२]; ७; ५५.२[२]; ४; ५; ५६.१; ४;
६०.१३; ६१.५; ११[३]; ६२.१२; ६३.२;
९; ६६.१; २[२]; ९; ११; ६७.१९; ६८.८;
१९; ६९.८; १५; ७०.२; ३; ५[२]; ७;
१२; १५; ७१.४; ७२.५; १४; ७३.१८;
७४.२; १०; १४; १५; ७५.८; ९; ७६.१;

७८.४[३]; ५; ८१.३[२]; ४; ८३.३; ५;
८४.१; ८७.१; ८८.१–३; ५; ८९.७;
९१.३; ९२.१२; १४; २२; ९३.५; ९;
११[३]; ९५.१; ९६.२[२]; ११; १४; २१;
९७.९[३]; १५; ९८.४; ८; ९९.३; ४; ६;
१००.३; ७; १०१.२; ४[३]; १०२.१२[२];
१९; १०३.२; ६; ७; ११; ९.२.६; ५.६;
६.४; १०.१; ३[२]; १२.२; १३.६; ७;
१४.५[२]; १६.१; ६; ७; १७.५[२]; २०.७;
२१.४; ६; २२.४; २४.२; ३२.३; ४;
३३.१; ३८.४[२]; ४१.१; ५; ४३.५; ४४.१;
४५.४; ५२.३[२]; ५३.३; ५४.३; ५५.४;
५६.३; ५७.१; ३; ६१.१६; २१[२]; २७;
६२.४; ६; १९; २८; ६३.१३; १९;
६४.३; ७; ९; ६५.१८; १९; २६;
६६.१०; १२; २२; ६७.११; १२; १५;
६८.१; ६९.१[२]; ३; ४; ६; ७०.६; १०[३];
७१.५; ६[२]; ७; ७२.१; ५; ७३.४;
६; ८; ७४.१; ७६.१–३; ७७.३; ५;
७९.३; ८०.१; ८१.२; ८२.१; २;
८३.१; ८४.२; ८५.५; ८६.२; ३; ९;
१६; २६; ३४; ३५; ४४[३]; ८७.१; ५;
७[३]; ८; ८८.२; ३; ४[२]; ५[२]; ६[२]; ७[३]; ८;
८९.१; ९०.१; २; ९२.१; ६[२]; ९३.१;
२[२]; ३; ९४.१[२]; २; ३; ९५.४; ९६.७;
९; १५[३]; २०[२]; २२; २३[२]; ९७.९; १८[२];
२०; २६; २८[२]; ३०[३]; ३८[२]; ४५[२]; ४६;
४८; ५२; ५३; ५७; ९८.२; ३; ८;
९९.५; ६; १००.१; ३; ७; १०१.२;
१२; १३[२]; १४[३]; १५; १०३.१; ६;
१०४.१; २; १०५.१; १०६.१२;
१०७.९–११; १२[२]; १३; २६; १०८.२;
७; १०; १०९.१०; ११०.५[२]; ६; ९; १०;
१११.१; २; १०.१.७; २.५; ३.४; ५;
४.३–६; ६.२; ५; ६; १०.२; ४; ८[२]; १२[२];
१३; १२.५; ८; १३.४; १४.२; १५.१३[२];
१६.७; १८.५; २१.१; २२.१; २;
५; १३; २३.६; २५.१; २६.३; २७.३;
५[२]; ७; २४; २८.१; १०; २९.१;

४; ५; ८; ३०.१; ५; १०; ३१.३; ८^{२}; ९^{३}; ३२.४; ३३.२; ३; ६; ९; ३४.२^{२}; ३^{२}; ४; ५; ८; १२; ३५.१४; ३७.३; ३९.१; २; १०; ११^{२}; १४^{३}; ४०.२; ६^{२}; ११; ४२.२; ४; ५; ८; ९; ४३.१; २; ४; ५^{४}; ७^{२}; ८; ९; ४४.६; ४६.२; ५; ७; ४८.१; ५^{३}; ७; ८; ११; ४९.३; ४; १०; ५१.४^{२}; ६; ७; ५४.२; ५५.६; ५६.७; ५९.३^{२}; ६०.८–१०; ६१.२–४; ८^{३}; ९^{२}; ११; १४; १६; २०; ६२.९; ६४.२; ६५.५; ६८.१^{२}; २; ६; ८^{२}; ९; ११; ७१.४^{२}; ५; ६; ९^{४}; ७४.२; ७५.३; ४; ७; ७६.२; ७; ७७.१^{४}; २^{३}; ३^{४}; ४^{३}; ५^{४}; ७; ७८.१^{४}; २^{४}; ३^{४}; ४^{४}; ५^{४}; ६^{४}; ७^{४}; ७९.३^{२}; ४; ८२.४; ७; ८५.३; ४; २५; ३४; ८६.१; ५; ६^{४}; १२; १५–१७; ८७.१९; ८८.१८; १९; ८९.२; ३; ५; ६^{४}; ७^{२}; ८^{२}; १२; १४; ९१.२; ५; ८; ९२.२; ९३.१; ८; ९; १२^{२}; १३; ९४.१०; १२–१४; ९५.१; ३^{४}; ६^{३}; ८^{२}; ९^{३}; १०–१३; १५; ९६.१; २; ४^{२}; १०; ९७.१७; ९९.२; ८; १०; १००.७^{२}; १०२.१०^{२}; १०३.१; १०५.२; ३; ५–८; १०६.७^{२}; ८; ११; १०७.३; ८^{४}; १०८.४^{२}; ६; १०; १०९.३; ५; ११०.५; १११.७; ९; ११२.४; ९; ११३.८; ११५.१; २; ३^{३}; ४^{२}; ७^{२}; ११७.१^{३}; २; ४^{३}; ६; ९^{४}; १२१.१०; १२२.१; १२३.१; ७; १२४.७; ८; १२६.१^{२}; १२७.४; ८; १२९.१^{२}; २^{४}; ७^{२}; १३०.७; १३१.२; ३; १३२.४; ६; ७; १३४.४; १३९.३; ५; १४३.१^{२}; २^{२}; ३; ६; १४४.१; २; १४६.१^{२}; ५^{२}; १४७.५^{२}; १४८.२; ५; १५२.१^{२}; १६०.३; ४; १६५.३; १६८.२–४; १७२.३; १७६.१; ३; १७८.२; ३^{२}; १७९.२; १८०.२; १८५.२

नडद्वल ६.१६१.८

नांशी ६.५१.१२

नंशी १.१२२.५; १२

नंसन्ते ७.५८.५

नंसै ३.३३.१०

नः १.१.९^{२}; २.९; ३.६; १०; ४.२; ३; ५; ६; ५.३^{२}; ८; १०; ७.४; ६; १०.३–६; ११; १२.३; १०^{२}; ११; १२; १३.१; २; ७; ८; १४.११; १५.३; ८; १०; १६.४; ५; ९; १७.१; १८.२; ३^{२}; २०.७; २२.८; ११; १३^{२}; १५; १६; २३.६; ९; १२^{२}; १७; १८; २४.१; २; ११; २५.२; १२^{२}; २१; २६.१; २; ४; ५; ७–९; २७.२; ३; ५; ११; १२; २८.८; २९.१–७; ३०.४; ६; ८; १३; १६^{३}; ३१.८^{२}; ९; १०; १२; १६; १८; ३३.१; ३४.१; ५^{२}; ६; ७; १२^{२}; ३५.११^{२}; ३६.२; ६; १२; १३; १४^{३}; १५; १६; ३८.६; ३९.७–९; ४०.३; ४२.१; २; ६; ७^{२}; ४३.२; ३; ६; ८^{२}; ४६.६; ७; १५; ४७.७; ४८.१; १०; १३–१६; ५४.१; ११^{२}; ५७.४; ५८.८; ६२.२; १२; १३; ६३.८; ९; ७०.५; ७१.२; ७; १०; ७३.९; ७५.५; ७६.२; ७७.४; ७९.७–९; ११; ८१.१; ७–९; ८२.१; ८४.८; २०; ८५.१२; ८८.१; ८९.१^{२}; २^{२}; ३–५; ६^{४}; ७; ९^{२}; ९०.१; ४; ५^{२}; ६; ७; ८^{२}; ९^{४}; ९१.१; ४; ६; ८–१३; १५^{२}; १७; २३; ९२.१५; १७; ९३.११^{२}; १२^{२}; ९४.१; १२; १६; ९५.११^{२}; ९६.८; ९^{२}; ९७.१^{२}; २–६; ७^{२}; ८^{२}; ९८.२; ३; ९९.१; १००.१–१५; १९^{२}; १०१.८; १०; ११; १०२.३^{२}; ९–११; १०३.८; १०४.२; ५^{२}; ६^{२}; ७; ८^{४}; ९; १०५.१३; १९; १०६.१; २; ३^{२}; ४; ५^{२}; ६; ७^{२}; १०७.२^{२}; ३^{२}; १०८.६; १३; १०९.७; ८; ११०.७; ९^{२}; १११.२^{२}; ३–५; ११२.२४^{२}; २५; ११३.४^{२}; १६; १९^{२}; २०; ११४.२^{२}; ६; ७^{६}; ८^{५}; १०^{२}; ११^{२}; ११५.६; ११८.२; १०; १२०.३; ४; ७^{२}; ८^{२}; ९^{२}; १२१.१४^{२}; १५; १२२.३^{२};

६; १४; १२३.३; १३; १२४.१; १२७.११[२]; १२८.२; ५; ७; १२९.५[२]; ८; ९[३]; १०; ११; १३०.१; १०; १३१.६; ७; १३२.६; १३३.६; १३४.६; १३५.१; ३; ५; १३७.१; ३; १३८.४; १३९.१; ५–७; १४०.१२[२]; १३; १४१.१२[२]; १४२.८; १०[२]; १४३.६; ७; ८[२]; १४७.४; ५; १५३.४; १५७.२; ३; ४[२]; १५८.१; १६०.५; १६१.१; ४; १३; १६२.१; ६; १२; २२[३]; १६४.२६; १६५.३–५; १६६.६; १६७.१[२]; २; १०[२]; १६९.१; ४; ५; १७०.२[२]; ३; १७१.३[२]; ४; ५; १७२.३; १७३.९; १२; १३[२]; १७४.१; १०; १७५.२; १७६.१; १७८.१; २[२]; ५; १८१.६; १८५.२–८; १८६.१[२]; २[२]; ३; ५; ६[२]; ७; ८; १८७.३; ७; १८८.३; ७–९; १८९.२; ४; ५[२]; १९०.६; ८; **२**.१.२; २.६[२]; ७; ९; ११; १२; ३.३; ६; ८; ६.५[३]; ६; ७.२; ५; ९.२[२]; ६; ११.१४; २१; १५.१०; १६.७–९; १७.८[२]; ९; १८.९; १९.९; २०.१–३; ९; २३.१; ६[२]; ७[२]; ९; १०; १२; १६; २४.१[२]; १२; १५; २७.१; ६[२]; ७; १०; १४; २८.३; ७[२]; ९; १०; २९.२; ३; ६; ३०.९; १०; ३१.२; ३; ३२.२[४]; ४–६; ३३.१[२]; ३–५; १३–१५; ३४.६; ७; ९; १२; ३६.३; ३८.१०; ३९.३; ४[२]; ५; ६[२]; ७[२]; ४१.९; ११[२]; १६; १७; २०; ४२.३; ४३.२[२]; ३; **३**.१.१५; १९[२]; २२[२]; २३; ३.७; ४.२; ६; ९; ११; ५.११; ६.११; ७.११; ८.७; ९; १०; ९.८; १३.१; ४[२]; ६[२]; ७; १४.६; १५.२; ३; ५; ६[२]; ७; १६.३; ५; १७.५; १८.१; १९.१; ५[२]; २०.१; २; २१.१; २; २२.५; २३.२; ५; २४.२; ५; २५.२; २६.३; २८.१; २९.१०; ३०.११; १९; २१; ३१.८; १८; १९; २०[३]; ३२.१४; ३३.८[२]; ३५.१; ३७.८; ११; ३८.९; ४०.३; ६; ८[२]; ४१.१; २; ४; ४२.१; ७; ४३.२; ३;

४४.१; ४५.४; ५; ४७.२; ३; ५१.८; ५२.१; ३[२]; ४; ६; ५३.१३; १४[२]; १७; १८[२]; १९; २१[२]; ५४.१; ३; ९; १२; १५–१७; १८[३]; १९[२]; २०[३]; २२; ५५.२; ९; २१; ५६.६; ६०.६; ६२.४; ९; १०; १६; **४**.१.४; ५[३]; १०; २.२; ११; १६; २०; ३.४; ५; १४; ४.३; ४; ११; १२; ५.१२[३]; १३; ६.१; १०.३[२]; ८[२]; ११.२; १२.६; १४.१; १५.१; १६.१; २; ८; १७; २०[२]; १७.१७; २०; २०.१[२]; २[२]; ३; ४; १०[२]; २१.१; ३; ६; १०; २२.१[२]; २३.७; २४.१; २९.१; ३; ३१.१; ३; ४; ३२.१; ५; ७; १६[२]; २०; २१; ३३.३; ८; ३४.१; ५; ३६.८; ९[२]; ३७.१; ७; ८; ३९.५; ६[२]; ४१.४–६; ११; ४२.१; १०; ४३.४[२]; ४४.५; ६; ४६.२; ४७.३; ४९.३; ५०.२; ११; ५३.१; ५; ६; ७[२]; ५४.१[२]; ३; ६; ५५.१; ३; ४; ५[२]; ७; १०[२]; ५६.४; ५७.१; २; ३[२]; ६[२]; ७; ८; ५८.८; १०; **५**.१.८; २.५; ३.७[२]; ९; १२; ४.२; ४; ५; ८; ९; ५.४; ५; ७; ९; ६.८; ९; ८.४; ९.७[२]; १०.१–३; ६; ७[३]; ११.४; १२.३; १३.३; ५; १४.१; १६.५[२]; १७.५[२]; १९.५; २०.१; २२.४; २३.४; २४.१; २[२]; २५.१; ३[२]; ४; ९; ३०.३; ३१.२; ११; ३३.२; ६; ७; ३५.२; ८; ३६.५; ३८.१; ४; ३९.१; ४१.१; २; ६; ९[२]; ११; १२; १५; १६; १८–२०; ४२.३–५; ९; १३; १६; १८; ४३.१–३; ६; ११[२]; १५; १७; ४६.४[२]; ५[२]; ६; ७[३]; ४९.४; ५०.३; ५१.११[२]; १२; १३[२]; १४[२]; ५४.६; ५५.९; १०; ५७.७[२]; ८; ५८.८; ५९.६; ८; ६०.१; ६; ६१.१६; ६२.९; ६३.५; ६४.५; ६[२]; ६५.१; ६; ६८.३; ७०.३; ७१.१; ३; ७२.३; ७५.३; ७६.४; ५; ७७.५; ७९.१[२]; ३; ६–८; ८०.५; ८२.४; ५; ८३.५; ६[२]; ८७.६; ८; ९; **६**.२.७; ११; ४.१; ९; ४; ७; ८; ५.४; ८.७; ९.७[२]; १०.१;

५; ११.१; २; ६; १२.६; १३.२; ६^{२}; १४.६; १५.६; ९; १२; १५; १९^{२}; १६.२; १२; २८; ३०^{२}; ३१^{२}; ३२; ४४; १७.१४^{२}; १८.५; १९.६–८; २०.१; २१.९; १२^{२}; २२.२; ४; ७; १०; ११; २३.५; ७; ९; २४.५; ९; २५.१^{२}; ७; ९; २६.१^{२}; ३३.१; ४; ५^{२}; ३६.५; ३७.२; ३८.१; ३९.१; ४०.३–५; ४४.११; १८^{२}; ४५.१; ४; १४; १७; २१; २४; ३३; ४६.२; ३; ५; ६; १०; ११; ४७.७^{३}; ८; ९^{२}; ११; २८; ३०; ३१; ४८.७; ९^{२}; १०; १५; १९; ४९.८; १४; १५; ५०.३; ४; ८; ९; ११; १२^{२}; १३; १४; ५१.५; ६^{२}; १०; ११^{२}; १४; १५; ५२.२; ३^{२}; ६; ९^{२}; ११; १२; १६; १७; ५३.२; ४; १०; ५४.५^{२}; १०; ५५.१; ५; ५६.४; ५; ५९.७; ९; ६०.५; १२; १४; ६१.४; ६; ७; ९; १०; १४^{३}; ६३.८; ६४.४; ६५.१; ६^{२}; ६७.२; ६८.७; ८; ६९.१; ५; ७०.५; ६; ७१.३^{२}; ७३.१; ७४.१–३; ४^{३}; ७५.१०^{३}; १२^{३}; १७; १९; ७.१.३; ५; ८; ९; १२; १३; १८; १९^{४}; २०; २२; २४; २५; २.१; ६; ७; ९; ११; ३.७; ८; १०^{२}; ४.४; ८; ९; १०^{२}; ५.९^{२}; ७.१; ७; ८.३; ७; ९.२; ३; ६; १०.४; ११.३; ५; १२.२^{२}; ३; १३.३; १४.३^{२}; १५.१; ३; ४; ६; ११; १३–१५; १६.५; ६; ८; ९; १७.५; ७; १८.१; ४; १९.७; ११^{२}; २०.१; ७; ९; १०^{२}; २१.१; ५^{२}; १०^{२}; २२.९; २३.४; ६^{२}; २४.१; ३–५; ६^{२}; २५.२^{२}; ६^{२}; २६.१; ५^{२}; २७.१; ४^{२}; ५^{२}; २८.१; ४^{२}; ५^{२}; २९.२; ४; ५^{२}; ३०.१; ५^{२}; ३१.३–५; ३२.१; ५; १९; २५; २६^{२}; २७; ३४.१४; १५; १७; १८; २०; २१; २२^{३}; २३^{३}; २५^{२}; ३५.१^{३}; २^{५}; ३^{५}; ४^{४}; ५^{४}; ६^{३}; ७^{५}; ८^{४}; ९^{५}; १०^{४}; ११^{३}; १२^{४}; १३^{४}; १४; १५^{२}; ३६.७^{३}; ८; ९; ३७.२; ५; ६^{३}; ८^{३}; ३८.३; ५–८; ३९.१; ३; ७^{२}; ४०.२; ४; ६; ७^{२}; ४१.३^{२}; ५; ६; ७^{२}; ४२.५^{२}; ६; ४३.३; ५^{२}; ४४.५^{२}; ४५.३^{२}; ४; ४६.१; २^{२}; ३^{२}; ४^{३}; ४७.४^{२}; ४८.४^{३}; ५०.१; ५१.२; ३; ५२.२; ३; ५३.२; ३; ५४.१^{३}; २^{२}; ३^{२}; ५५.१; ६; ५६.९; १७; २१; २२; २४^{२}; ५७.५^{२}; ६; ७^{२}; ५८.३^{२}; ५; ६; ५९.६^{२}; ८; ६०.७. १०; १२^{२}; ६१.७^{२}; ६२.२^{२}; ३^{३}; ४; ५^{३}; ६^{३}; ६३.६^{३}; ६४.१; २; ३^{२}; ५; ६५.२; ४; ५; ६६.१; ३; ५; ६७.५; ६^{२}; १०; ६८.१; २; ९; ६९.५; ८; ७०.१; ७; ७१.२; ४; ६; ७२.२^{२}; ५; ७३.४^{२}; ५; ७४.३; ७५.२; ८^{३}; ७६.६; ७; ७७.४; ५^{२}; ६; ७८.५; ७९.५^{२}; ८०.३^{२}; ८२.१; ८३.२; ५; ८४.२^{२}; ३^{३}; ५; ८५.१; ५; ८६.५; ८^{३}; ८७.७; ८८.७; ८९.५; ९०.६; ७; ९१.७; ९२.१; ३; ५; ९३.४; ६; ८^{२}; ९४.३^{२}; ७; ८; ९५.४; ६; ९६.२; ५; ९७.२^{२}; ४^{२}; ५; १०; ९८.७; ९९.७; १००.२; ७; १०१.६; १०२.१; ३; १०३.१०; १०४.७; १०; ११; २३^{२}; ८.१.९; २१; २.१५; ३.१^{२}; २^{२}; ११; १२; १८; ४.३; १५; १६^{२}; ५.४; ७; ९; १०; २०; २१; ३०; ३२; ३६; ६.२३; २५; ३६; ७.११; १३; २७; ३२; ८.१; ४; ५; ७; ९; १३^{२}; १७^{२}; १९; २०; २२; ९.११^{२}; १०.३; १२.६; ३३; १३.३; ५^{२}; १३; १६; १८; २२; २५; १५.१३; १६.११; १२^{२}; १७.२; ४; १८.३; ६–१०; १२; १३; १७; १८; २१; २२; १९.४; १९; २७; २०.२; ८; १०; १८; २२–२४; २६^{२}; २१.२; ६; ८–१०; १२; २२.७; १०; १४; १७; २३.१०; १२^{२}; २७; २९; २४.३; ७; ११^{२}; २६; २५.१०; ११; १४; २६.७; २०; २५; २७.२–६; ९; १०; १४^{२}; २८.३; ३०.३^{२}; ३१.१३; ३२.७–९; १२; ३३.१०; ३४.६^{२}; ७; ११; १२; १४; १५; ३५.४–६; १०–१२;

३९.१; ९; १०; ४०.१; २; ९; ४२.२[२]; ४३.२२; ४४.२; ५; ११; १४; १९; २२; ३०; ४५.८; १५; १८; १९; ३३; ३४; ४६.९–११; १३; २५; ४७.५; ८; ९; ११; ४८.४[२]; ६; ७; ८[२]; ९[२]; १२; १४[२]; १५[२]; ४९.४; ५; ७; ५०.५; ५१.५; ५२.५[३]; ५३.३; ५४.३[३]; ५; ६; ५९.७; ६०.८–१०; ११[२]; १२; १४[२]; १८; २०; ६१.१; १३[२]; १५[३]; १६; १७[२]; ६५.५; ६; ६६.८; १४[२]; ६७.२; ५; ६; ८[२]; ९; ११; १२; १४; १५; १८; २०; ६८.१२[३]; ७०.९; १०; १२; १५; ७१.१; ३; ६; ७; ९; १०; १३; १५; ७३.१४; १५; ७५.२; ८; ९; ११[२]; १२; १३; ७८.१–३; ७९.७[२]; ८[२]; ८०.१; २[२]; ३–६; ९; ८१.१; ४; ६[२]; ८३.२–४; ७; ८४.६; ८६.१–५; ९०.१; ६; ९१.४; ६; ९२.३; ९[२]; १०; १५; १९; २१; २६; २७; ३१; ९३.३; १०; १८; १९; २१; २८[२]; २९[२]; ३०; ३१[२]; ३२–३४; ९४.३; ९५.८; ९; ९६.८; २०; ९७.६; ७[५]; १३; १५; ९८.४; १०–१२; १००.११; १०१.४[२]; ९; १०; १०२.२; ८; ९; १०३.१; ९; १२; ९.१.५; ४.१–४; ५[२]; ६–९; १०[२]; ५.८; ८.२; ७; ८; ९.७; १०.८; ११.३; ९[२]; १३.४; ५; १९.१; २०.३; २३.३; २९.५; ३०.३; ३२.१; ३५.१[२]; २; ३; ३६.३[२] ४०.३; ५; ६; ४१.६; ४२.६; ४३.२; ४४.१; ४–६; ४५.२; ३; ४९.१; २; ४; ५२.१; ५; ५४.४; ५५.१; ३; ५७.४; ६१.३; ५; ६; ९; १२; १४; १५; २३; २६; २८; ३०; ६२.२१; २४; ६४.३; १२; १८[२]; ६५.१३; १७; १८; २१; २४; ६६.१३; १९; ३०; ६७.६; १०[२]; ११; १२; २२[२]; २३; २४[२]; २६; ६८.१०; ६९.७; ८; १०; ७०.९; १०; ७२.८; ९[२]; ७६.३; ७७.३; ४; ७८.४; ५; ७९.१[३]; २; ८१.३[२]; ४; ८४.१; ८५.२; ४; ८; ८६.१८[२];

३८; ४८; ८८.७; ९०.६; ९१.६[२]; ९३.४; ५; ९६.३[२]; ११[२]; १४; ९७.३; ४; ६; १५–१७; २१; २५; २६; २८; ३६; ३९[२]; ४४[२]; ४८; ५०; ५१[२]; ५३; ९८.१; १००.५; १०४.५; ६; १०५.४; ५; १०६.७; ९; १०७.६; १०८.१४; १०९.९; ११०.१; ७; ११२.१; ११४.३; ४[३]; १०.३.७; ४.१; ७[२]; ५.७; ७.१[२]; ७[४]; ९.१–३; ४[२]; १०.४; ११.२[२]; ८; ९[२]; १२.२; ४; ५; ८; ९[२]; १३.२; १४.२[२]; ६; ७; १४; १५.१; ४; ६; ८; १७.१०; १८.१; ३; १९.६; ७; २०.१; २१.४; २२.६–९; १५; २३.७; २४.२; ३; ६; २५.१; ३; ४; ६; ७[२]; ८[२]; ९; २६.३; ९; २८.५; १२; २९.४; ३०.११; ३१.१; ५; ३३.३[२]; ३४.१४[२]; ३५.२–७; १०–१३; ३६.२[२]; ३; १४[२]; ३७.५; ६[२]; ९; १०[२]; १२; ३८.१–३; ३९.२; ४२.३; ११[२]; ४३.११[२]; ४४.११[२]; ४७.८; ५२.४; ५३.१; ३[२]; ५; ५७.१; ५; ५९.२; ३; ४[२]; ५[२]; ६[२]; ७[२]; ६१.१४; १८; २१; २२; २७; ६३.१; ६–८; ११; १२; १५[२]; १६; ६४.१; ६; ९; १०[२]; १३[२]; ६५.३; १५[२]; ६६.३[४]; ५; ७; १०; १२; १५[२]; ६७.१; १२; ६८.१२; ६९.४; १२; ७०.११; ७४.३; ७६.१; ४; ६; ७७.८; ७८.८; ८१.१; ७; ८२.३; ८३.२; ३; ८४.२; ६; ८५.२३[२]; ३७; ४३[२]; ४४; ८६.८; ८७.१; २०; २१; ८९.१५; ९१.१०; १३; ९२.१२; १३; ९३.१[३]; ५–७; ९[२]; ९७.१५; ९८.४; ९; १०; १२[२]; ९९.१; ८; १००.१[२]; ३–५; ७; ९; १०१.३; ९; १०२.१; १०५.८; १०६.९; ११; १०७.७; १०८.२; ३; ११०.२; ८; ११२.१०; ११३.१०; ११५.५; १२१.९; १०; १२२.८; १२४.१[२]; १२६.३[२]; ६; ८; १२७.४; ६; १२८.४–६; ८[२]; ९; १३०.६; १३२.७; १३३.३[२]; ४–७; १३५.१; ५; १३९.५[२]; १४१.१[४]; २[२]; ४;

नमस्यत ३.२.८
नमस्यत १.८४.५; ३.६२.५
नमस्यन् १.३३.२
नमस्यन्तः १.११५.३; १२७.७; ४.६.११
नमस्यन्ति १.३६.१९; ३.६२.१२
नमस्यन्तीः ३.५७.३; ९.९५.३
नमस्यन्निति नमस्यन् १.७२.५
नमस्यम् १.७२.५
नमस्याः १०.१०४.७
नमस्यानि १०.६३.२
नमस्यामः ३.१७.४
नमस्युः ८.२७.११
नमस्युऽभिः १.५५.४
नमस्येभिः ६.६८.३
नमस्यैः ७.९५.४
नमस्व ८.७५.५
नमस्वत् १.१८५.३
नमस्वन्तः १.१६४.८
नमस्वन्ता ५.६२.५
नमस्वान् १.१७१.२; ४.४१.१; ६.६३.१; ७.६६.१; ८५.४; १०.६१.२५
नमस्विनः १.३६.७; ७.१४.१; ३६.५; ८.१३.१०; ६९.१७; ७५.१४; १०.४८.६
नमस्विनम् १.१६६.२
नमी १०.४८.९
नमीम् ६.२०.६
नमुचिम् १.५३.७; २.१४.५; ७.१९.५; १०.७३.७
नमुचेः ५.३०.७; ८; ६.२०.६; ८.१४.१३
नमुचौ १०.१३१.४
नमे ३.३९.६
नमे १.१३९.९[२]; ६.५१.९; ७.३२.२०
नमेते इति २.१२.१३
नम्नते १.१४०.६
नम्नमाने इति १०.८२.१
नम्या १.५३.७
नम्रम् १०.४९.५
नय १.१८९.१
नय १.४२.७; ८; ६.१५.१६; ४७.७; ५३.२; ५४.१; ८.४४.८; ७१.६; १०.४५.९; ८७.९; १३३.६
नयः ४.३०.१९
नयत् १.३६.१८; ३.९.५; ३१.६; ६.४.६; ८.१७.१५
नयत १०.३४.४
नयत ३.६.१; ४.५८.१०; ५.५५.१०; १०.६६.१२; १०१.२
नयतम् २.३९.५
नयति ४.२१.४
नयति १.१५५.३; २.२६.४; ५.३४.६; ६.७५.६
नयतु १.९०.१; २.३.१०; ४.१.१०; १०.८५.२६; १८२.१
नयथ १.४१.५; ७.५९.१; ८.१९.३४; १०.१३.१४
नयथ १०.१३७.१
नयथः ५.६५.६; ६.७२.२
नयध्वम् २.१४.९; १०.१६५.५
नयन् १.७९.३; ९.८६.३२
नयन्त १.१४८.३
नयन्तः १०.४६.५
नयन्ति १.४१.३; १६२.२; ४; ६.५१.१०; १०.१२६.१
नयन्ति १.६४.६; ८३.२; ९५.२; १२६.४; १४६.४; ३.८.४; ५३.२३[२]; २४; ४.१.९; ७.६०.६; ७; ९.८७.१; १०.११४.७
नयन्ती ७.७७.३; १०.५६.२
नयन्तीः ६.६५.२
नयन्तु १०.८५.३१
नयन्तु १.४०.३; ७.६४.३
नयमानः १.१७३.३; ९
नयसि १.१२९.१; ६.४५.६
नयसि २.२३.४; १०.७५.४
नयसे १०.८४.३
नयस्व ३.३५.३
नयाति १०.१६१.३

नयामसि ८.४७.१७

नयिंष्ठाः १०.१२६.३

नरः १.८.६; ३९.३; ६२.३; ६३.६; ६४.४; १०; ६७.२; ७०.५; ७३.४; ८३.४; ८५.८; १००.८; १०४.२; ११५.२; १२१.२; १२४.१२; १२७.६; १५४.५; १६६.१३; २.१.९; १९.१; ३६.१; ३.२.६; ३.८; ८.६; ३५.८; ५४.४; ६२.१२; ४.१.१५; ३.११; २४.३[२]; २५.८; ३३.६; ३४.९; ३६.५; ४२.५; ४४.६; ५७.४; ५.७.२; ९.७; १०.३; ४; ११.२; ४; २९.१२; ३०.२; ३३.५; ५२.५; ६; ८; ११; ५३.३; ६; ५४.३; ८; ५५.३; ५७.८; ५८.८; ५९.२; ५; ६१.३; ६.१.२; २.३; २९.१; ४; ४०.२; ४६.१; ४७.३१; ५९.७; ६४.६; ६८.४; ७५.११; ७.१.१; ४; ९; १०; ३.५; ८.१; १५.९; १६.३; १९.८; ९; २७.१; ३१.२; ५६.१; ५७.६; ५९.७; ७४.६; ८२.९; ८३.२; ९१.३; ४; ९३.३; ९४.१०; ९७.१; १०३.९; ८.१.१७; ७.२९; २०.६; ७; २५.१५; २७.६; ३३.२; ३८.३; ६५.८; ६८.५; १४; ७१.१४; ९९.१; ९.१७.७; ७२.२; ७४.४; ८०.४; १०१.३; १०.२०.८; २९.५; ४०.१०; ५०.३; ६३.१७; ६४.१७; ७६.६; ७; ८०.५; ८४.१; १०७.३; १४७.२

नरः १.२१.२; २३.११; ३७.६; ४०.६; ४१.५; ८६.८; ११०.८; १११.३; १६१.११; १६५.११; २.३.३; १४.८; ३६.२; ३.१६.२; २९.५[२]; ६०.१; ४.३४.४; ५; ५.५३.१५; ५४.१०; ५९.३; ६१.१; ६.४९.११; ७.१८.२५; ३३.४; ४८.१; ५९.४; ६६.१३; ८.२०.१०; १६; ९.११.१; १०.७६.८; १०१.१२; १०३.२; १३

नरम् १.२५.५; ३०.९; ३१.६; १५; १००.८; ११२.२२; ३.५१.२; ६.४४.४; ८.१६.१; २४.११; ४०.२; ९२.८; ९७.१०; ९.९७.४९; ५२; १०.३८.४

नरा १.३.२; ११७.१८; १५१.९; ५.७३.६; ६.६२.१; ६३.५; ७.६९.६; ८.१०१.२; १४३.३

नरा १.२.६; ४६.४; ४७.८; ११२.३; १६; ११६.७; ११; १२; १४; ११७.२; ४; ६; ७; २४; ११८.५; १०; १८२.८; १८३.३; १८४.२; २.३९.८; ४१.३; ३.५८.६; ४.४७.४; ५.४९.१; ६४.७; ७३.७; ७५.६; ६.४९.५; ५०.१०; ६०.८; ९; ७.६६.१९; ७४.२; ४; ८२.८; ८३.१; ९१.६; ९४.३; ९९.४; ८.५.१६; २२; ८.५; ६; १७; २०; २१; २२.८; १२; १७; २६.४; ११; १६; ३५.२३; ३८.४–६; ४०.३. ८५.४; ५; ८७.१; २; १०१.८; १०.४०.१; ३–५; ४१.२; १४३.३; ४; ६

नराम् १.१२२.१०; १४९.२; १६७.१०; १७३.९; १०; १७४.१०; १८०.८; १८६.६; ७; २.१.५; २०.३; ३४.६; ६.२४.२; ६८.४; ७.१९.१०; १०.४५.१२

नराशंसः १.१४२.३; २.३.२; ३८.१०; ३.२९.११; ५.५.२; १०.७०.२; ९२.११; १८२.२

नराशंसम् १.१३.३; १८.९; १०६.४; ९.८६.४२; १०.६४.३

नराशंसस्य ७.२.२

नरि १.८५.९; ८.९६.१९

नरे १.६२.१; ४.२५.४; ६.४२.१; ९.९८.१०; १०.५०.२

नरेऽस्थाम् ४.३३.८

नरौ १.११७.३; १८०.४

नर्तयन् १.५१.३

नर्यः १.६३.३; १२१.१२; ४.२५.१; २९.२; ५.४१.९; ६.२४.२; ७.१.२१; २०.१; ९५.३; ९.१०५.५; १०७.१; १०.२९.१; ७; ५०.२; ६१.५; ९५.१०

नर्यऽअपसम् ८.९३.१

नर्यम् १.४०.३; ५४.६; ११२.९; २.२२.४;

नवीयसी ७.५९.४; ८.१२.१०; ७२.९; १०३.९
नवीयसीः ९.८६.३२
नवीयसीम् १.१३८.३; ८.५१.५; ९५.५; १०.९१.१३
नवीयसे १.१५६.२; ९.९.८
नवीयान् १.११०.७; ३.३६.३; ६.४४.७; १०.२७.१९
नवे ४.३२.२३
नवेदसः ५.५५.८; १०.३१.३
नवेदसा १.३४.१
नवेदाः १.७९.१; १६५.१३; ४.२३.४; ५.१२.३
नवेन १.३१.८; २.१८.३; ६.५०.६
नवेभिः ४.२०.५
नव्यः १.६१.१३; ६२.११; १०५.१५; १८९.२; ५.१२.३; ६.२०.१०; ७.४.८; १८.५; ८.३.१३; ११.१०; ९.९४.३; १०.४.५
नव्यम् १.१०.११; ६२.१३; १०५.१२; १०९.२; १३९.८; १४१.१०; १८०.१०; १९०.१; २.१७.१; ३.३१.१९; ५३.१६; ४.१६.२१; १७.२१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११; ६.१.७; १७.१३; ७.८०.२; ९१.२; ८.१६.१; २४.२६; ६७.१८; १०.८९.३
नव्यम्ऽनव्यम् १.१५९.४; १०.९६.११
नव्यसः ६.६२.४; ८.२४.८; ५०.९
नव्यसा २.३१.५[२]; ६.६.१; ४८.११; ६२.५; ८.३९.२
नव्यसि ३.६१.३
नव्यसी १.६०.३; १३९.१; ३.६२.७; ६.८.१; ८.७४.७; १०.४.६
नव्यसी इति ३.५.७
नव्यसीः १.१२४.९
नव्यसीनाम् ५.५३.१०; ५८.१
नव्यसीभिः ४.४१.१०; ६.४९.१; ७.५३.२; ८.५.२४
नव्यसीम् १.१४३.१; ५.४२.१३; ६.८.५
नव्यसीषु १.१४१.५
नव्यसे २.३१.७; ३.२.१३; ३२.१३; ५.११.१; ६.७१.३; ८.७.३३; २७.१०; ९.९.८; ८२.५; ९१.५
नव्यस्या ६.२२.७; ८.५१.३
नव्या ५.२९.१३
नव्यांसम् १.२७.४
नव्यांसि १.३८.३
नव्याः १.१७४.८; ५.२९.१५
नव्याःऽनव्याः ३.५५.१६
नव्ये ४.२०.१०
नव्येभिः १.१३०.१०; ७.९३.४
नव्येषु १.१३४.४
नव्यौ १०.३९.५
नशत् ४.२३.४; ६.२.५; ८.६१.१२
नशत् १.४१.५; १६४.२२; २.४१.११; ७.३२.२१; ८.१९.६; २०.१६; ३१.१७; ४७.१; ६८.८; ७०.३
नशते १.१६५.९
नशते ५.४.११; ६.३.१; २; ७.८२.७
नशथ २.१४.८
नशन् ९.७९.१
नशन् २.२३.८; २७.१४; ३५.६
नशन्त १.१२३.११; ७.१.२२; ९.७९.१; १०.११५.४; १३३.३
नशन्ति ६.२८.३; १०.२७.२०
नशामहै २.३०.११; १०.३६.११
नशायथः १०.४०.६
नशीमहि ८.६.९; १०.३६.३; ५७.२
नश्य १०.९७.१३
नश्यतः १.१२०.१२
नश्यति १.१७०.१; १०.९७.११
नश्यतु ८.२७.१८
नश्यसि १०.१४६.१
नष्टम् १.२३.१३; ६.५४.१०; ८.७९.६; १०.४६.२
नष्टम्ऽइव १.११६.२३
नसते ९.६८.४; ७१.३; ८
नसते ९.८२.३

७; ५६.११; ५९.७; ६८.५; ६९.५; ६; ७०.३; ४; ७१.५^{२}; ७३.२; ७४.२; ८२.८; ९२.३^{२}; १०४.१^{३}; ५; १०; ८.२.२६; ४.५; ५.१३; ६.१४; १६; ७.२; ५^{२}; ३४^{२}; १२.१; ९; १३.२४; १७.१३; १९.३३; २१.१५; २३.१४; १७; २६; २४.२५; २५.८; ९^{२}; ११; २७.१२; ३२.३; ३३.८; ३५.२२; ३९.२^{२}; ४१.३; ८; ४४.११; ४६.२३; ४८.१०; ५०.८; ५२.७; ५४.८; ६१.२; १६; १८; ६४.२; ७०.१०^{२}; ७२.२; ७५.१; ७८.६; ८३.४; ८४.२; ८७.२; ९५.८; ९६.११; ९७.८; १००.७; १०१.१४; १०२.१४; १८; ९.६.८; १९.७^{३}; ३६.१; ५२.४; ५५.२; ५९.३; ६३.२; २३; ६८.२; ७०.७; ८; ७१.२; ७३.४; ७९.५; ८६.६; ८७.१; ८९.१; ९८.५; ९९.८; १०४.१; १०७.१९; १०९.२२; १०.५.२; ७.५; ८.३; १०.३; ८; ११.२; १६.१२; १८.११; १९.१; २^{३}; ३^{२}; ५; ६; ८^{२}; २१.७; २२.१४; २४.१; २७.२; १४; २८.६; ८; २९.१; ३०.१४; १५; ३३.२; ३४.१४; ३७.२; ३; ९; १२; ३९.७; १४; ४०.४; १२; १४; ४२.१; ५; ६; ८^{२}; ४३.२; ४४.६; ४५.७; ४६.६; ४८.४; ४९.८; ५२.२; ६; ५३.१; ५६.४; ५; ६०.६; ६१.७; ६३.१६; ६५.७; ६६.९; ७०.३; ६; ७३.६; ८१.१; ८४.७; ८७.७; ११; १२; ८९.९; ९३.९; ९४.३; ५; ९५.१७; ९६.३; ९८.४; १०१.१; ११; १०२.५; ११०.६; १११.४; ११२.९; ११४.२; ३; ९; ११६.५; ११८.१; ११९.९; १२०.१; ७; १२२.८; १२४.९; १२७.४; ५^{४}; १२८.४; १४२.२; ६; १४६.५; १४९.४; १६०.१; १६६.३; १६८.३; १७७.१

निऽअङ्ग्रनम् ८.२७.१८

निऽअयनम् १०.१९.४; १४२.७

निऽअर्थम् ७.१८.९; १०.१०७.८

निऽअर्थात् १०.१२८.७

निऽअर्थानि ६.२७.६

निऽइतः १०.१६१.२

निऽईक्षणम् १.१६२.१३

निऽउसाः १०.२७.१७; ३४.५; ९

निऽऊहतुः १.११६.१

निऽऊहथुः १.११२.१९

निऽऋञ्जते १.५४.२

निऽऋञ्जसे ८.९०.४

निऽऋषन्ति १.५२.७

निऽऋष्टः १०.१०८.७

निऽऋष्टम् ४.१८.५; २०.६; १०.४२.२

निऽएरिरे ४.१.१^{२}; ८.१९.१८; २१

निऽओकसे १.९.१०

निऽओकाः ५.४४.१४; १५

निऽओचनी १०.८५.६

निंसत १०.७४.२

निंसते १.१४४.१

निंसते ९.८५.३; १०.९२.२; ९४.९

निंसानम् ८.४३.१०

निः १.४.५; ३३.५; ९; १०; ३४.११; ५१.११; ५६.५; ८०.१; २; ४^{२}; १०; ८५.९; ९५.४; १०३.२; १०४.८; १०६.१–६; ११०.८; ११५.६^{२}; ११६.२१; ११७.१४; १५; ११८.६; ८; १२०.१२; १४१.३; १३; १५७.४; १६१.७; १६२.१२; १६३.२; १७९.४; २.११.९; २३.१८; ३.३१.४; ८; ४.१८.२^{२}; १९.१; ९; २७.१; ३६.४; ५८.४; ५.१.२; ३१.९^{२}; ३२.३; ५५.१०; ८७.४; ६.१६.१३; ३५.५; ४७.३०; ६२.६; ६६.४; ७.१.४; ३.९; ५०.३; ५६.२१; ६८.७; ७१.५; ८.१.१७; ३३; ३.१९^{३}; २०^{४}; ४.२०; २१.१६; ४८.११; ७७.६; ७९.२; ८१.६; ९.७२.८; ९४.४; १०८.६; ११०.८; १०.८.८; १६.१३; २४.४; २८.४; ३४.९; ३९.४; ५५.८; ६०.७; ६१.७; ६२.७; ६५.१२; ६७.५; ६८.३; ८; ९; ७६.७; ८०.३; ९७.९; १०१.५; १०३.१२; १०७.१; १२४.७; १२६.२;

निऽदिता ८.१०३.११
निदे २.२३.१४; ३४.१०; ३.१६.५; ४१.६; ६.४५.२७; ७.३१.५; ७५.८; ९४.३; ८.८.१३
निघमानान् ६.५२.३
निऽद्रा ८.४८.१४
निऽधर्यः १.१८३.४; ३.५८.५
निऽधर्या ९.८३.४
निधयाऽइव १०.७३.११
निऽधातुः ५.३०.२
निऽधातोः १.४१.९
निऽधानम् ३.३१.२; ५३.५; ६
निऽधाना १.१६३.५
निऽधान्यम् ८.७२.१८
निधाऽपतिः ९.८३.४
निऽधायि ४.२.१; ५.३.३
निऽधारयः ८.४१.४
निऽधारयन्तः ४.२.१२
निऽधिः ७.६७.७; १०.१०८.७; १८६.३
निधिऽमिः १०.१७९.२
निऽधिम् १.१३०.३; २.२४.६; ५.४३.८; ७.६९.३
निधिऽमत् १०.५९.२
निधिऽमन्तम् २.३९.१
निधिम्ऽइव १.११६.११
निऽधिषु १०.१५.५
निऽधीन् १०.६८.६; १०८.२; १३८.४
निऽधीनाम् ८.२९.६
निऽधीयमानम् १०.३२.६
निऽध्रुवि ८.२०.२२
निऽध्रुविः ७.३.१; ८.२९.३
निऽनद्धः ६.७५.५
निऽनमे ३.५६.१
निनाय १०.६८.२; १०९.२
निनिक्त १०.१३२.६
निनित्सात् ६.५२.२
निनित्सुः ८.६८.१९
निनित्सोः १.१८९.६; ७.२५.२; ३४.१२
निनिदुः १०.२७.६

निनीयात् ७.८८.२; १०.८५.२३
निनीषसि ८.१०३.४
निनेथ ७.२८.३
निनेथ ६.१८.१३
निन्दत ४.५.२
निन्दन्ति १०.४८.७
निन्दात् ५.४२.१०
निन्दितऽअश्वः ८.१.३०
निन्दिता ३.३९.४
निन्दितारः ५.२.६
निन्दिम १.१६१.१
निन्यासः ५.२.६
निन्यथुः १.११६.८; २४
निऽपद्यते १०.१६२.५; ६
निऽपातः ४.५५.३
निऽपाति १.७३.२; ७.१.१५
निऽपादाः ५.८३.७
निऽपासि ४.११.६
निऽपूतः ८.१७.११
निऽपूतम् २.१४.९
निऽबर्हयः १.५३.७
निऽबाळ्हः १.१०६.६
निऽबाधितम् १.११९.८; ७.८३.६
निऽबोधात् २.३०.७
निऽबोधिषत् २.१६.७
निऽभृतम् १.१०२.५; २.१४.१०
निऽमिता ५.६२.७
निमिताऽइव ३.३०.४
निऽमितासः ३.८.७
निऽमिम्युः ३.८.६
निऽमिश्लः ६.२३.१; ८.९६.३
निऽमिश्लाम् १.१६७.६
निऽमिषः २.२८.६; ८.७३.२
निऽमिषतः १०.१२१.३
निऽमिषि १.७२.५; २.३८.८
निऽमृग्राः २.३८.२
निऽमृजन्तः १०.१२२.७
निऽमेघमानः ८.४.१०
निऽमेघमानाः २.३४.१३

८.३.१३; १०.३; १२.४; २०.८; २१.७; २४.११; १९; २५.२३; २७.९; १८; ४०.८–११; ४५.३७; ४६.११; २८; ५१.७^{2}; ६१.११; ६३.५; ६६.९^{2}; ६७.१; २०; ७२.६; १८; ७६.१; ७७.१; ८०.५; ८१.४; ८; ८५.९; ९३.११; ९४.६; १०–१२; ९५.७; १०१.१५; ९.९.८; ११.४; २३.७; ४०.३; ८८.८; ९२.५; ९३.५; ९७.४८; १०.१०.५; ११.३; १८.४; २३.२; ४; २७.६^{2}; ७^{2}; २९.६; ३०.१०; ३४.१४^{2}; ३९.५; ५०.२; ५^{2}; ५४.३; ५७.३; ५९.२^{2}; ४; ६१.५; ८; १३; २४^{2}; ६२.६; ६९.५; ७२.१; ७९.६; ८६.३–५; ८८.३; ९२.७; ९३.१५; ९५.१; ९६.११; ९७.१; ९९.६; १००.६; १०२.१०; १११.७; ११५.१; १३२.३; १४७.४; १५७.१; १६८.१; १७५.४

नुत्थाः ६.१७.५

नुदत १०.१६५.५

नुदन्तु १.१६७.४

नुदस्व ९.५३.१; ६३.२४

नुदस्व ३.४७.२; ६.२१.७; ७.३२.२५; १०.८४.२; १३१.१; १८०.२

नुदेथाम् ७.१०४.१

नुनुदे ३.३४.१०

नुनुदे ७.१८.१६; ८६.१; ८.१४.८

नुनुद्रे १.८५.१०. ११; ८८.४

नुवन्तम् १.२९.५

नूतनः १.१०५.४; ५.४२.६; १०.४३.५

नूतनम् ५.५५.८

नूतनस्य २.२०.४; ३.५१.६; ६.२१.८; २७.३

नूतना २.११.६; ५.३१.६; ७.९८.५

नूतनानि ३.१.२०

नूतनाभिः ६.४४.१३

नूतनाय ३.४७.५; ६.१९.११

नूतनासः ६.२१.५; २७.१; २

नूतनेन १.११८.११; ५.४२.१८; ४३.१७; ७६.५; ७७.५; ७८.४; ७.५१.१

नूतनेभिः ३.३२.१३

नूतनैः १.१.२

नूत्नाः ७.१८.२०; २२.९; ८.२१.७

नूनम् १.१३.६; २४.१; ३८.१; २; ३९.७; ४०.५; ८२.३; ८४.५; १११.४; ११३.१०; १२४.९; ११; १६५.१२; १७०.१; १७४.३; १८९.४; २.११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; २८.८; ३८.१; ३; ३.४७.४; ४.३०.२३; ३३.११; ५१.१; ५.२४.२; ४२.१; १४; ५६.५; ५८.१; ६१.१४; ६४.३; ७०.१; ७६.१; २; ६.१९.४; २५.९; ३३.५; ३४.१; ३५.५; ३८.५; ४५.११; ४८.१९; ६०.२; ७.२६.३; २९.३; ३८.१; ४५.२; ६३.४; ६७.३; ४; १०४.२०; ८.४.११; ७.२०; ३१; ८.२; ९.१; ७; ८; १४; १५; २१; १३.५; १८.१; २०.१५; २३.२४; २४.१४; २३; २६; ३२.१६; ४६.१५; १६; ४८.३; ४९.७; ५०.७; ६६.७; ६७.१६; ७५.६; ८४.७; ८६.२; ८७.५; ९०.६; ९२.१६^{2}; १००.७; १०१.१; ९.९९.३; १०७.२; १०.१०.४; १५.२; ५३.९; १०; ६१.२६; ६२.८; ८९.१७; १०६.१; १११.८; ११२.८; १२६.३; १८८.१

नूनोत् ६.३.७

नूषत ९.१०३.३

नृऽघ्ने ४.३.६

नृऽचक्षः १०.८७.९; १७

नृऽचक्षसः २.२४.८; ८.४३.३०; ९.७३.७; ८०.१; ८३.३; ८५.९; १०.६३.४; ८७.८; १०७.४; १५८.५

नृऽचक्षसः ३.५३.१०

नृऽचक्षसम् १.२२.७; ८.१९.१७; ९.८.९; ८६.३६

नृऽचक्षसा ९.५.७

नृऽचक्षसे ४.३.३; ९.६६.१५

नृऽचक्षसौ १०.१४.११

नृऽचक्षाः १.९१.२; ३.१५.३; २२.२; ५३.९; ५४.६; ७.६०.२; ८.४८.९; १५;

प

पतात् १.४६.३; ८.५.२२
पताात् १०.१६५.५
पताति १.२९.६; ४.१६.१७; ७.२५.१
पतान् १०.२७.२२
पतामि १.३३.२
पतिः १.१८.४; ४०.३; ५; ४४.९; ५२.१३; ५३.२; ६६.४; ६८.४; १०१.५; ११६.२५; १४५.१; १४९.१; १५३.४; २.२३.१७; २४.२; ४; ५; ८; ९; ११; १३; २५.१–५; २६.४; ३.७.३; ३१.४; १८; ४.१६.७; ५५.४; ५; ५७.३; ५.४१.१२; ५१.१२; ६.३६.४; ४५.१६; ५८.४; ७५.१७; ७.२६.३; ३५.५; १०; ८.१३.८; ९; १९.३७; ४४.१६; ७५.४; ८०.९; ९५.३; ९८.४–६; ९.५.१; ११.८; १५.५; २८.१; ३१.२; ७२.४; ७५.२; ८६.५; ११; ३२; ३३; ९९.६; १०१.५–७; ११४.२; १०.१०.३; २२.३; २३.३; २४.३; २६.६; ७; ४८.१; ५३.९; ६५.१; ६७.७; ७२.२; ७४.६; ८५.२८; ३०; ३९; ४०; ८६.११; ९९.६; १०५.२; १११.३; १२१.१; १२८.७; १५२.२; १५९.२; १६२.५; १७३.३; १८०.१
पतिःऽइव १०.१४९.४
पतिंजुष्टाऽइव १.७३.३
पतिऽत्वनम् १०.४०.९
पतिऽत्वम् १.११९.५
पतिऽद्विषः ८.९१.४
पतिना ४.५७.१
पतिऽभ्यः १०.४०.१०; ८५.३८; ११०.५
पतिम् १.९.४; ११.१; १८.६; ३८.१३; ५६.२; ६०.५; ६२.११; ७१.१; ८९.५; १०५.२; ११६.१०; ११७.७; १२७.८; २.९.५; २६.३; ३.३९.१; ४१.५; ५.१२.३; ३७.३; ४१.८; ४२.१४; ४६.३; ६.१५.१; ४४.४; ५; ७.५.५; ४१.१; ४४.१; ६६.१५; ९७.३; ८.२४.१४; १८; २७.१; ६८.४; ६९.२; ९.१४.७; २६.४; ६५.१; ८९.३; ९७.२२; १०.१०.१०; ३२.३; ४३.१; ४४.४; ६१.७; ६६.१३; ८१.७; ८५.७; १२; २९; ४५; ९२.१४; १०२.७; १४५.१; २; १५९.१
पतिऽरिपः ४.५.५
पतिऽलोकम् १०.८५.४३
पतिऽवती १०.८५.२१
पतिऽविद्यम् १०.१०२.११
पतिष्ठः १०.१६५.५
पती इति १.२३.३; ५; ११९.५; १३६.३; २.३१.४; ४१.६. ४.४३.६; ५.६३.३; ६८.५; ८६.४; ८.५.५; २२.१४; २६.६; १०.४०.१४; ९३.६
पती इति १.३.१; ३४.६; ४७.५; १२०.६; ४.४७.३; ५.७५.८; ८.५.११; ८.१६; २२.४; ६; ५९.३; ५; ८७.५; १०.४०.४; १२; १३; ८५.१५; १३१.४
पते १.११.२; १८.१; ३; ५; २६.१; २९.२; ३०.५; ४०.१; १३१.४; २.१.३; २३.१; ५; ९; ११; १९; २४.१५; १६; ३.५१.१०; ४.५७.२; ५.६.५; ९; ३५.५; ६.४५.१०; ५३.१; ७.५४.१–३; ५५.१; ९७.९; ८.६.२१; १७.१४; १९.७; २३.१२; ४५.२०; ६०.९; ९०.५; ९२.३०; ९३.३१; ९७.६; ९.३१.६; ३६.६; ८३.१; १०४.५; १०५.५; १०८.९; ११३.२; १०.१४१.१; १५५.२; १६४.१; ४; १६६.३; १७४.१
पतेः २.२४.१४; २६.२; ९.३५.६
पत्तः १०.२७.१३
पत्तवे ४.१८.१
पत्नी ३.६१.४; ४.२४.८; ७.७५.४
पत्नीऽइव १.१२२.२
पत्नीः १.२२.९; ६२.१०; ११; १०३.७; ११२.१९; १४०.६; १७९.१; २; १८६.७; ४.५.१३; ५.४१.६; ४२.१२; ४४.५; ४६.७; ५०.३; ७.३४.२०; १०.३०.१०; १२
पत्नीभिः २.१६.८
पत्नीम् १०.८५.३९
पत्नीऽवतः १.१४.७; ३.६.९

पत्नीवत्ऽभिः ४.५६.४
पत्नीऽवन्तः १.७२.५; ८.२८.२; ९३.२२
पत्न्या १.८२.६; १०.३९.११
पुत्ऽभ्याम् १०.९०.१२; १४
पत्म १०.५६.३
पत्मन् १.१४१.७; ५.५.७; ४१.३; ६.४.६; ७.३४.५; १०.८.३
पत्मना ६.३.७
पत्मऽभिः ८.८.२३
पत्यते २.३७.२; ६.१३.४; २२.१; ४५.२०; १०.१४४.१
पत्यते १.८४.९; १२८.७; ३.३६.४; ५४.८; ५६.३; ६.२५.६; ८.१.२६; १०२.९; ९.४५.४; १०.२३.२
पत्यमानः ३.५४.११; १५; ६.४९.४; ७.१८.८; १६
पत्यमानम् ६.६६.१
पत्यमानाः ३.५६.५; ६.२७.६; ६५.३; १०.१३२.३
पत्यमानान् १०.२७.६
पत्यसे ६.२.१
पत्यसे २.१.८
पत्या १०.८५.२२; २४; २७; ३६
पत्युः १०.१८.८
पत्ये १.६१.२; १२४.७; ४.३.२; १०.१०.७; ७१.४; ८५.९; २०; ९१.१३
पत्यौ ९.८२.४; १०.१५९.३
पुत्ऽवत् १.४८.५; ३.३९.६
पुत्ऽवती १०.८५.२९
पुत्ऽवतीनाम् १.१५२.३
पुत्ऽवतीभ्यः ६.५९.६
पुत्ऽवतीम् १.१४०.१२
पुत्ऽवते १.१४०.९; १०.१६९.१
पुत्ऽवन्तः १०.१२७.५
पुत्ऽवन्तम् १.१८५.२
पत्वऽभिः ५.६.७
पत्वा ९.९६.२३
पुत्ऽसु ५.५४.११
पुत्सुतः ८.४३.६
पुत्सुतःऽशीः १.३२.८
पथः १.४२.२; ८३.५; ९०.४; १०५.११; २.१३.५; २३.७; २४.७; ३०.२; ३.३०.१०; ४.३७.७; ४५.३; ६; ५.४६.१; ८०.२; ३; ६.१६.३; ५३.४; ७.४.७; १८.१६; ३९.३; ८७.१; ८.५.९; २९.६; ३०.३; ५५.५; ९.९.८; २२.४; ९१.५; १०१.८; १०.५१.५; ५३.६; ५७.१; ७३.७; ७५.२; ९८.११; ११०.२
पथः ६.५३.१
पथःऽपथः ६.४९.८
पथा १.३८.५; ४१.५; ८७.२; १०५.६; १८; १२८.२; १२९.९; २.४.६; ४.२६.५; ५.४५.८; ४७.६; ६४.३: ७.६५.३; ८.५.३९; ९.७.१; १५.३; ८६.१६; १०.१४.१०; २२.४; ३१.२; ५०.७; ५२.१; ७०.२; ८६.२१; ९३.१४; ११४.७; १३३.६; १४५.६
पथाऽइव १.१३९.४
पथाम् ४.४०.४; ७.७३.३; १०.५.६; १७.६
पथि ३.५४.९; ६.४४.८; ४६.१३
पथिऽकृत् २.२३.६; ६.२१.१२; ९.१०६.५; १०.१११.३
पथिकृत्ऽभ्यः १०.१४.१५
पथिऽभिः १.३५.११; ५८.१; ७९.३; १६२.२१; १६३.६; १६४.३१; १८३.६; १८४.६; २.१५.३; ३४.५; ३.५८.५; ४.३७.१; ५.४३.६; ६.४.८; १८.११; ६९.१; ७.३८.८; ६४.३; ८.२२.७; १०१.१०; ९.८६.३३; ९१.३; ९७.२८; १०६.६; १०.१४.७; ८७.६; १६८.३; १७७.३
पथिरक्षी इति पथिऽरक्षी १०.१४.११
पथिषु ५.७.५
पथीनाम् ५.१.११
पथेऽस्थाम् ५.५०.३; १०.४०.१३
पथ्या ३.५४.५; ५५.१५; ७.१८.३; ७९.१
पथ्याऽइव १०.१३.१

पथ्याः ३.१२.७; ३५.८; ५.५४.९; ६.१९.५; ६६.७; ७.७.२; ७५.१; १०.१४.२
पथ्याभिः ३.१४.३; ७.६७.३; ९.८९.१
पथ्याम् ३.३१.५; ७.४४.५; ९.९५.२; १०.५९.७; ८०.६
पथ्यासु १०.६३.१५
पथ्ये ५.५१.१४
पदः १.१४६.२
पदऽज्ञाः १.६२.२; ३.५५.२; ९.९७.३९
पदम् १.२२.५; १७; २०; २१; २५.७; ४८.६; १०५.१; १४६.४; १५४.६; १५९.३; १६४.७; २३; ३.५.५; ६; ७.७; ४.५.३; ५; ८; १२; ५.३.३; १५.५; ३०.२; ६.१.४; ८.१३.२९; ४१.४; ७२.१८; १०२.१४; १५; ९.१०.७; ९; २३.२; ६४.१९; ६८.४; ७१.५; ८३.४; ८६.१५; १०२.२; १०.५.१; २; १८.२; ३२.५; ६७.२; १०८.७; १६५.३; ४; १७७.१
पदऽवीः ३.५.१; ३१.८; ५६.४; ७.३६.२; ९.९६.६; १८
पदऽवीयम् १०.७१.३
पदऽव्यः १.७२.२
पदस्य ७.८७.४
पदा १.२२.१८; ४२.४; ५१.६; ७२.६; ८४.८; १३३.२[2]; १६४.७; १७; ६.५९.६; ८.१२.२७; ४१.८; ५२.३; ६४.२; ८२.९; ९.१२.८; ९७.७; १०.५३.१०; ६१.८; १३४.६; १४४.५
पदाऽइव ४.३१.५; ५.६७.३; ८.१२.३१
पदाति ९.७३.९
पदानि १.६७.३; १५४.४; १६४.५; ४५; ८.८.२३; १०.८.४; १३.३
पदाय ७.४१.६
पदि ४.१२.६; १०.१२६.८
पदिम् १.१२५.२
पदीष्ट १.३८.६; ७९.११
पदीष्ट ३.५३.२१; ७.१०४.१६; १७
पदे १.२१.६; २२.१४; ४६.९; ७२.२; ४; १२८.१[2]; १४९.१; १५४.५; १५८.२; १६३.७; २.१०.१; २३.१६; ३५.१४; ३.२३.४; २९.४; ५४.७; ५५.१; ४.५.९; १०; ५.४३.१४; ७४.४; ६.१.२; ८.२३.९; ५१.४; ६९.७; ९.८३.२; ९७.५७; १०.१.६; ७०.१; ९१.१; ४; १७७.२; १९१.१
पदे इवेति पदेऽइव ३.५५.१५
पदेन १.१३९.९
पदेऽपदे ५.४१.१५; ९.७३.४
पदेभिः १.१५४.३
पदेभ्यः ८.२.३९
पदैः १.६५.१; १०.४६.२
पदोः १०.१६६.२
पद्यते ४.१३.५; १४.५; ६.५४.३; १०.१४६.५
पद्यस्व ६.७५.१६
पद्या ३.५५.१४
पद्याभिः २.३१.२; ३२.३; १०.१०२.७
पद्यासु ८.६.१६
पद्येन ७.५०.१–३
पनन्त २.४.५
पनन्त १०.७४.४; १०४.७
पनय ५.२०.१
पनयत् ४.३३.५
पनयन्त ३.६.७; ७.१.१०
पनयन्त १.८७.३
पनयन्ति ६.४.३
पनयन्ति ३.३४.६; ४.३८.९; ६.१२.५
पनयाय्यम् ६.६९.५
पनस्यते १०.७५.९
पनस्यते १.५५.२; ३.५१.३; ८.१०१.११
पनस्यवः १०.७७.३
पनस्यवे ८.९८.१
पनस्युम् १.३८.५; ५.५६.९
पनस्युवः ९.८६.१७
पनायत ६.७५.६
पनाय्यम् १.१६०.५; ८.५७.३
पनितः ५.४१.९

पप्रथुः ६.७२.३
पप्रथे ५.३८.२; ६.७.७
पप्रथे १.५५.१; २.२४.११; ३.३०.१९; ६१.४; ५.८७.७; ८.३.४; १२.१२; ५१.१०; ८६.५; ९.८०.३; १०.६२.९; ६९.२; १७०.३
पप्रा १.६९.१
पप्राथ ६.१७.७
पप्राथ ७.२०.४; ९८.३; ८.६८.२; ७०.६
पप्रिः १.५२.३; ६.५०.१३; ८.१६.११
पप्रिणा २.२३.१०
पप्रिम् १.९१.२१
पप्रिषे १०.७३.८
पप्रुः १०.६५.२; ६६.९
पप्रौ ६.१०.४; ४८.६; १०.८९.१
पप्रौ १.८१.५; ३.३०.११; ५४.१५; ४.१६.५; ८.२५.१८
पयः १.२२.१४; २३.१६; ६२.९; ६४.६; ६६.१; १०४.४; १०५.२; १२१.५[2]; १६०.३; १६४.२७; १८०.३; २.१३.१; २; ३.३१.१०; ४.५७.२; ५; ५.४४.१३; ८५.२; ६.४८.२२; ५२.१०; ६७.७; ७.७४.३; ९५.२; १०१.३; ८.९३.१३; ९.६.७; ११.२; १९.५; ३१.५; ३४.३; ४२.४; ५४.१; ६२.९; २०; ६६.३०; ७१.१; ७४.४; ८६.३७; ९१.३; ९६.१५; ९७.४३; ११०.३; १०.१.३; १७.१४; ६१.११; ६३.३; ६४.९; ६५.६; ८; ७३.९; ८७.१७; ११४.१
पयःऽधाः ७.५६.१६
पयःऽपाः १.१८१.२
पयःऽभिः १.१६४.२८; ४.२१.८; ५७.८; ७.६८.९; ९.६२.५
पयःऽवृधः १.६४.११
पयःऽवृधम् ९.८४.५; १०८.८
पयःऽवृधा ८.२.४२; ९.७४.१
पयते १.१६४.२८
पयसः १.१५३.४; १०.६१.२६; १००.२
पयसा १.६४.५; ७९.३; १६६.३; २.१४.१०; ३.३३.१; ४; ५५.१३; ४.३.९; १०; ४१.५; ५.४३.१; ६३.५; ६.६१.१४; ७.३६.६; ५०.४; ९.६८.३; ८४.५; ८६.२; ४; १७; ९३.३; ९७.१४; ४३; १०७.१२; १०.१९.७; १०१.९; १३२.६; १३३.७; १६९.३
पयसाऽइव ९.७७.१; १०.६४.१२; ७५.४
पयसि १.१८६.४
पयस्वत् १०.१७.१४[2]
पयस्वती ४.५७.७
पयस्वती इति २.३.६; ६.७०.२
पयस्वतीः १०.१७.१४
पयस्वान् १.२३.२३; १०.९.९
पयांसि १.९१.१८; ८.१००.१०; १०.११.१; ३०.१३; १०८.१; २
परः १.१६४.३५; २.४१.८; ६.६३.२; १०.८८.१७
पुरः १.८.५; १९.२; ८०.१५; १६४.१७; १८; ४३; २.१३.१०; २३.१६; ३५.६; ५.३.५; १७.२; ३०.५; ४४.२; ६.९.२; ३; ४८.१९; ७.९९.१; १०४.११; ८.२.४१; ६.३०; ८.२३; २२.१४; २७.१८; २८.१; ६९.१४; ७२.३; ९.६८.५; १०७.२०; १०.१७.१३; २७.२१; ३१.८; ५६.१; ६७.४; ७१.९; ८२.२; ५[2]; १२५.८[2]; १२९.१; २; १६४.१[2]
पुरःऽगव्यूति ८.६०.२०
पुरःऽतरम् १०.१५५.३
पुरःऽपा ५.६२.६; ८.९.११
पुरःऽपाः २.९.२; ६; ८.६१.१५
पुरःऽमात्रम् ८.६८.६
परःऽतरे १०.९५.१
परम् १.३३.१; १४०.८; १५५.३; १६४.३४; १६८.६; ७.९९.२; १०.१८.१; ८७.३; १२०.७
परमः ५.३०.५; ६.२७.४; ९.७९.४
परमऽज्याः ८.१.३०; ९०.१
परमम् १.२२.२०; २१; ३१.१४; १०३.१; १५४.६; १६३.४; १३; १६४.३४; ३५;

२.२४.६; ३.५५.१०; ४.५.१२; ८.१००.१०; १०.१.३; १०.४; ४५.२; १८१.२

परमया ६.३८.३

परमस्य ४.१२.३; ७.३२.१६; ९०.११; ९९.१

परमस्याः ५.६१.१

परमस्याम् १.१०८.९; १०

परमा २.२७.३; ३.३०.२; ४.१.७; ५०.३; ६.२५.१; १०.६१.१८; ८२.२

परमाः १.१६७.२; ५.४७.४

परमाणि ४.१.१६; १०.८१.५

परमात् १.१४१.४; ८.११.७; ९.८७.८

परमाभिः ६.६२.११

परमाम् १०.९५.१४

परमे १.६२.७; ७२.२; ४; १०१.८; १४३.२; १५४.५; १६४.३९; ४१; २.९.३; ३५.१४; ३.३२.१०; ४.५.१०; ५०.४; ५.१५.२; ४३.१४; ४५.८; ६३.१; ६.८.२; ७.५.७; ८२.२; ९.८६.१५; १०.५.७; १४.८; १६.१०; ५६.१; १०९.४; १२३.५; १२९.७

परमे इति ४.२३.१०

परमेषु १.२७.५

परशुः १.१२७.३; ६.३.४; ७.१०४.२१; ९.६७.३०; १०.४३.९

परशुम् ३.५३.२२; ४.६.८; १०.५३.९

परशुमान्ऽइव ८.७३.१७

परशून् १०.२८.८

परशोःऽइव ५.४८.४

परश्वाऽइव १.१३०.४

परस्तात् ३.२२.३; ५५.६; ६.५४.१०; १०.८८.१४; १२९.५

परस्मात् ७.६.७

परस्मिन् १.४३.९

परस्य ३.१८.२; ६.१५.३; १०.८.७; ११५.५

परस्याः ८.७५.१५; १०.५५.४; १८०.२; १८७.२

परस्वन्तम् १०.८६.१८

परा १.४.४; २५.४; १६; ३३.५; ३९.३; १०४.५; ८; ११६.९; १२३.१२; १२६.७; १६४.१७; ३१; १६७.४; १८९.५; २.२८.९; ३.५३.२; ५; ४.१६.७; ३८.९; ५.३.१२; ६१.४; १७; ८२.४; ५; ६.२०.११; २६.३; २७.७; ४७.१७; ५९.७; ६९.८[२]; ७५.१६; ७.१.१९; १८.१६; ३२.२५; ४६.४; १०४.१; ८.१.५; २.१५; ४.१८; ४७.१४; ४८.८; ७१.७; ७५.१२; ९७.७[२]; ९.७१.७; ८१.३; १०.८.९; १७.६; १८.१; ३०.५; ४८.५; ५९.४; ६१.८; २१; २३; ७२.८; ८५.२९; ३३; ८६.२; ८७.१४[४]; १५; १८[२]; ९५.२; १३; ९९.९; १०३.१२; १२८.८; १३७.२; ४; १४५.२; १६०.३; १७७.३

पराऽअयनम् १०.१९.४; ५; २४.६

पराऽअयने १०.१४२.८

पराऽआस ४.१८.८

पराऽइतः १०.८३.५; १६१.२

पराऽइतौ १०.१७८.२

पराऽईयुः १०.१४.२; ७

पराः १०.५८.११

पराकात् १.३०.२१; ७.७५.४; ८.५.३१; १०.२२.६; ७७.६; १०८.३; ४

पराकात्तात् ८.९२.२७

पराके १.१२९.९; ७.१००.५; ८.९.१५

पराऽगताः १०.९७.२१

पराचः १.१६४.१९; ३.३०.६; ६.२५.३; ४४.१७; ७.८५.२

पराचीः १.१९१.१५

पराचैः १.२४.९; ६३.४; १०३.१; ६.७४.२; १०.५५.१; १०८.१

पराऽजितासः १०.८४.७

पराञ्चः १.१६४.१९

पराणि ३.३८.१; ६.२१.६; १०.५.२

पराऽतरम् १०.५९.१–४

पराऽददः ८.७०.१४

पराऽददाति १.८१.६

पराऽददिः १.८१.२

पराऽदै ७.१९.७

पराऽनुदे १.३९.२; ८.१४.९

पराऽपरा १.३८.६

पराऽभृतम् ८.४५.४१

पराम् १०.१४५.४

पराऽयतिः ९.७१.७

पराऽयती १.१९१.२

पराऽयतीनाम् १.११३.८

पराऽयतीम् ४.१८.३

परायत्ऽअर्थः १०.३४.५

पराऽयन् १०.४५.६

पराऽवत् ४.५०.३

पराऽवतः १.३४.७; ३५.३; ३६.१८; ३९.१; ४८.७; ७३.६; ९२.३; १२८.२^{२}; १३०.१; ९; ३.९.५; ३७.११; ४०.८; ४.२१.३; २६.६; ३०.११; ५.५३.८; ६१.१; ६.८.४; ४४.१५; ४५.१; ७.९७.२; ८.३.१७; ५.८; ३०; ६.३६; ७.२६; १२.६; ३०.३; ३२.२२; ८२.१; ९.३९.५; ६८.६; १११.२; १०.५८.११; ६३.१; ७८.७; १३७.२; १४४.४; १८०.२; १८७.२

पराऽवतम् ३.४०.९; १०.९५.१४; १४५.४

पराऽवति १.४७.७; ५३.७; ११२.१३; ११९.८; १३४.४; ५.३०.५; ७३.१; ८.८.१४; १२.१७; १३.१५; ३३.१०; ४५.२५; ५०.७; ५३.३; ९३.६; ९७.४; ९.४४.२; ६५.२२

पराऽवृक् २.१५.७; १०.६१.८

पराऽवृक्तम् ४.३०.१६

पराऽवृजम् १.११२.८; २.१३.१२

पराऽशरः ७.१८.२१; १०४.२१

परासः ४.२.१६; १०.१५.१

पराऽहता ५.५६.३

परि १.६.१; ७.१०; १०.१२; १५.४; २३.१२; २५.१३; ३०.१९; ३१.२; ४; ५; १५; ३२.१५; ३३.८; ९; ३४.७; ४७.६; ४९.३; ५०.१०; ५२.६; ५४.५; ६१.८^{२}; ९; ११; ६२.८; ६८.१; ६९.१; ७२.२; ७६.१; ८०.९; ८८.४; ९३.६; ९५.२; ३; ८; ९; १०५.३; १०८.७–१२; ११२.२५; ११५.३; ११८.५; १२१.२; ७; १०; १२३.८; १२४.६; १२७.९; १२८.३; १३२.६; १३३.१; १३५.२; १३६.५; १४०.९; १४१.४; १४३.८; १४६.४; ५; १५२.४; १६२.१; ४; १३; १६४.११; २०; २५; ३६; १६७.९; १६८.९; १७२.३; १७३.३; १७८.१; १८०.१; १०; १८३.४; २.१.१; २.५; ५.३; ६.५; १३.१; २; १०; १७.६; २३.१७; २७.५; ३०.९; ३१.१; ३३.१४^{२}; ३५.३; ४; ९; १०; १२; १४; ४१.१२; ३.१.५; २.६; ७; १२; ३.२; ९; ५.१०; ७.२; ६; ९.३; ५; ११.८; १२.७; ९; १५.६; २६.८; २९.६; ३१.१७; ३२.६; १६; ३६.९; ३८.४; ६; ९; ४८.२; ५१.८; ५३.८^{२}; २४; ५६.४; ५८.८^{२}; ४.१.१५; २.९; ३.११; ६.४; ५; ९.३; ८; १५.१–३; ३०.१२; ३१.८; ३३.१; ३६.१; २; ८; ३८.४; ४०.३; ४१.७; ४३.५; ६; ४५.७; ४९.२; ५२.१; ५६.७; ५.१५.३; ४; १६.४; १८.४; २९.१३; ३१.७; ३७.३; ४१.१२; ४४.७; ४७.२; ४; ५१.४; ५३.९; ५५.७; ५९.७; ६४.१; ६५.६; ७३.३; ५; ७५.७; ७९.५; ८१.४; ८३.७; ६.१.९; ४.६; ७.७; १६.३२; १७.५^{२}; २८.७; ३९.२; ४७.२७^{२}; ४८.२१; ५१.१६; ५३.५; ५४.१०; ६२.१; ३; ६३.२; ६७.५; ७०.३; ७१.३; ७५.१२; १४^{२}; ७.१.११; १५; १६; ३.७; ४.६; ५.७; १८.२२; २०.७; ३१.८; ३२.१०; ३३.१; १०; १२; ३४.२३; ३६.७; ४६.३^{२}; ५०.२; ३; ६०.९; ६७.८; ६९.४^{२}; ७५.४; ७६.३; ८४.१; २; ८७.३; ९३.८; १०३.७; १०४.५; ६; ८.१.२७; ६.१०; २०; ८.३; ४; ८; २३; ९.४; २२.४; ५; २५.१८; २६.१४; २७.१६; ३३.१; ३४.१०; ३९.१०; ४१.३^{२}; ७; ४५.१०; ४०; ४७.५; १५. ६६.९; ६७.८. ६८.३; ६९.९^{२}; ७२.९; १८; ७६.१२; ८०.६; ८८.५; ९१.३; ९२.१९; १०१.१६; ९.७.४; ६;

४.४५.१; ५.४१.१२; ७.१३.३; ४०.६;
१०.३९.१; ९२.५; ९३.४; ७
परिज्माऽइव ६.२.८; १३.२
परिऽज्मानः ५.१०.५
परिऽज्मानम् १.२०.३; ८.७२.१०; १०.४०.१
परिज्मानम्ऽइव १.१२७.२
परिज्मानाऽइव १०.१०६.३
परिऽज्रयः १.६४.५; ५.५४.२[२]
परिऽतंसयध्यै १.१७३.७; ६.२२.७
परिऽतक्म्या ५.३०.१४; १०.१०८.१
परिऽतक्म्यायाः ५.३०.१३
परिऽतक्म्यायाम् १.११६.१५; ४.४१.६;
४३.३; ५.३१.११; ६.२४.९; ७.६९.४
परिऽतक्म्ये १.३१.६
परिऽतप्तम् १.११९.६
परिऽतप्य १०.१६७.१
परिऽदाय १.१०५.२
परिऽदीयथः ८.५.८; २६.६
परिऽद्वेषसः ८.७५.९
परिऽधयः १०.९०.१५
परिऽधावसि ९.२४.५
परिऽधिः १.१२५.७; १०.१३०.३
परिऽधिम् ३.३३.६; ४.१८.६; ७.३३.९;
१२; १०.१८.४
परिऽधीन् ९.९६.११; १०७.१९; १०.१३९.४
परिधीन्ऽइव १.५२.५
परिऽनशे १.५४.१
परिऽनहम् १.३३.८
परिऽपतिम् ६.४९.८
परिऽपदम् १०.२८.१०
परिपदाम्ऽइव ८.२४.२४
परिऽपन्थिनः १०.८५.३२
परिऽपन्थिनम् १.४२.३
परिपन्थीऽइव १.१०३.६
परिऽपश्यन्ति १.१६२.१२
परिऽपानम् ५.४४.११
परिऽपूतः १.१३५.२; ८.२.२
परिऽप्रयन्तम् ९.६८.६
परिऽप्रयाथ ४.५१.५
परिऽप्रस्यन्दते ९.१०१.२
परिऽप्रियः ९.७२.१
परिऽप्रीतः १.१९०.६
परिऽप्रीता १०.२७.१२
परिऽप्रुषः १०.७७.५
परिऽबभूव १०.८८.१४
परिऽबाधः ५.२.१०; ८.२४.५
परिऽबाधमानः ६.७५.१४
परिऽभुजत् १.१००.१४
परिऽभुवः १.१६४.३६
परिऽभूः १.१.४; ५२.१२; ९१.१९; ९७.६;
१४१.९; २.२४.११; ३.३.१०; ४.५३.५;
५.१३.६; १०.१२.२
परिऽभूतमम् १०.९१.८
परिभूतिऽभिः ७.६६.१०
परिऽभूषति १.१३६.५
परिऽभ्वे २.१६.३
परिऽमंसते ७.५९.३
परिऽमन्यवे १.३९.१०
परिऽममृशुः ८.९.३
परिमन्नाथे इति परिऽमन्नाथे ७.९३.६
परिऽमर्धिषत् ८.६१.६
परिऽमिता १.१६४.४५
परिऽयत्ताय ७.८३.८
परिऽयन् १.१७३.११; ९.६८.२; ७१.९;
१०.९२.५; १२२.३; ६
परिऽयन्तम् ९.६८.६
परिऽयाति ७.६९.५; ९.१११.१
परिऽयाथः १.११२.१३
परिऽयासि १.१२१.९; ६.३७.४
परिऽरपः २.२३.३; १४
परिवत्सरीणम् ७.१०३.८
परिवत्सरे १०.६२.२
परिऽवर्गे १.१२९.८
परिऽवर्तमाने १.१६४.१३
परिऽविषे १०.६२.१०
परिऽविष्टम् १.११६.२०; १०.६८.६
परिऽविष्टी ४.३३.२

परि॑ऽवीतः १.१२८.१; १६४.३२; ३.८.४; ४.१.७; ३.२; १०.६.१; ४६.६
परि॑ऽवीतम् १.१३०.३
प॒रि॒वृ॒क्ताऽइ॑व १०.१०२.११
प॒रि॒ऽवृज॑म् ८.२४.२४
प॒रि॒ऽवृ॒ण॒क्षि॒ १.१२९.३
परि॑ऽवृतम् २.२३.१८; ४.४५.२; ७.२७.२; १०.११३.६
परि॑ऽवृता २.१७.१
परि॑ऽवृताः १.१३०.३[२]; १४४.२
प॒रि॒ऽव्यत॑ २.१७.२
परि॑ऽशक्तवे ८.७८.५
प॒रि॒ऽशया॑नम् ३.३२.११; ४.१९.२; ६.३०.४
परि॑ष्टिः १.६५.२; ८.८८.६
परि॑ष्टिषु १०.१४७.३
परि॑ष्टौ ७.१९.७
प॒रि॒ऽसद॑ः ३.३३.७
प॒रि॒ऽसद॑न्तः ४.२.१७
प॒रि॒ऽसद्य॑म् ७.४.७
प॒रि॒ऽसद्वा॑नः १०.६१.१३
प॒रि॒ऽसु॒स्व॒जा॒ना ६.७५.३
परि॑ऽसिक्तः २.१८.६
परि॑ऽसिक्तम् ४.१.१९; ३५.९; ६.६८.११; १०.११६.४
परि॑ऽसिक्ता १.१७७.३; ७.२४.२
परि॑ऽसिक्तेभिः १.१०८.४
प॒रि॒ऽसि॒च्यमा॑नः ९.६८.१०; ९७.१४; ३६
प॒रि॒ऽसि॒च्यमा॑नाः ९.९७.२६
प॒रि॒ऽसि॒च्यसे॑ ९.६५.६
परि॑ऽसूताः १.५३.८
परि॑ऽसूतिः ९.८५.८
परि॑ऽसूतेः १.११९.६
परि॑ऽस्तुतिः ५.८१.१
प॒रि॒ऽस्तु॒भ॑ः १.१६६.११; ९.६२.२४
प॒रि॒ऽस्तो॒भ॑न्त्या ९.६४.२८
प॒रि॒ऽस्थाः १०.९७.१०
प॒रि॒ऽस्थाम् ६.७२.३
परि॑ऽस्थितम् ६.१७.१२
परि॑ऽस्थिताः २.११.२; ४.१९.८; ७.२१.३
प॒रि॒ऽस्पृध॑ः ९.५३.१
प॒रि॒ऽस्रुत॑ः ८.३९.१०
प॒रि॒ऽस्रुत॑म् ९.१.६; ६८.१
प॒रि॒ऽस्वज॑त् ६.६०.१०
प॒रि॒ऽस्वजे॑ १०.४०.१०
परि॑ऽहितम् १.१२१.१०
प॒रि॒ऽह्नि॒नोमि॑ ७.१०४.६
प॒रि॒ऽह्रुत् ६.४.५
प॒रि॒ऽता ८.४७.६
परि॑ऽह्वृतिः ७.८२.७
परि॑ऽह्वृतिम् ९.७९.२
परी॑णसः १.५६.२; १३३.७; ८.२१.७; ८४.७
परी॑णसम् ३.२४.५
प॒री॒ण॒सम् ९.९७.९
परी॑णसा १.१२९.९; १६६.१४; ४.३१.१२; ५.१०.१; ८.७७.९; ९७.६
परी॑मणि ९.७१.३
परु॑ः १०.१००.५
परु॑ःऽपरुः १.१६२.१८; १०.९७.१२
परु॑षः १०.५३.१
परु॑षा ९.१५.६
प॒रु॒षाः ५.२७.५
परु॑षि ७.५०.२
प॒रु॒षे ६.५६.३
परु॑ष्णि ८.७४.१५; १०.७५.५
परु॑ष्णीम् ४.२२.२; ७.१८.८; ९
परु॑ष्णीषु ८.९३.१३
परु॑ष्ण्याम् ५.५२.९
परे॑ १.१६४.१२; १६६.१३; २.१२.८; ४.२५.८
प॒रे ८.६१.१७
परे॑ण १.१६४.१७; १८
प॒रे॒यि॒ऽवांस॑म् १०.१४.१
परे॑षाम् १०.१२८.६
परे॑षु १.१२८.३; ३.५४.५; १०.५६.७; ११४.२
परैः॑ १०.१५.१०
पर्षि॑ः ७.१००.२
पर्ज॑न्य ५.६३.४

४४; १०३.६; १०६.१०; १०७.११; १५; २२; ११०.१०

पवमानम् ९.१३.२; २६.३; ४६.६; ५०.३; ६०.१; ६७.९; ७८.३; ८१.५; ८६.२४; ९७.८

पवमानस्य ९.५.८; ११; ४१.३; ५१.३; ५३.३; ६१.४; १७; ६४.७; २४; ६६.१०; २५; ८१.१; ८६.६; ९२.५; ९६.२४; ११४.१

पवमानाः ९.१३.९; ६३.२५; २७; ८५.७; ८७.५; १०७.२५

पवमानाय ९.११.१; ६५.७; ८६.४४

पवमानासः ९.२१.४; २४.१; ३१.१; ६३.२६; ६७.७; ६९.९; १०१.८

पवमानेन ९.५.५; ९७.५८

पवयः १.३४.२; १३९.३; १८०.१; ५.३१.५; १०.२७.६

पवया ९.९७.५३

पवसे ९.२०.३; ९७.३१

पवसे ९.२३.६; ६३.२४; ६६.१९; ७६.५; ८०.२; ८५.३; ८६.५; २३; ९७.३२

पवस्ते इति १०.२७.७

पवस्व ९.१.१; २.१; ११.७; १३.४; २४.४; ६; २५.१; २९.४; ३०.३; ३५.२; ३६.२; ४२.६; ४३.६; ४९.१; ५२.५; ५५.३; ५९.१; २[३]; ६१.२८; ६२.२५; २६; ६३.२२; ६४.२२; ३०; ६५.१३; ६६.१; ४; २१; ६७.१; १३; १६; ७०.९; ८४.१; ८६.१८; २२; ४८; ९६.१३; २१; १००.५; ६; १०६.५; ७; १०७.२३; १०८.१; १५; १०९.४; ७; १०

पवस्व ९.२.१; ६.१; ८.७; ११.३; २५.६; २९.६; ३३.६; ३५.१; ४०.३; ४१.४; ५; ४४.४; ४५.१; ६; ४६.५; ४९.२; ३; ५०.४; ५; ५५.४; ६०.४; ६१.९; १९; २२; ६२.१२; ६३.१; ७; १८; ६४.१३; ६५.३; ५; १०; १२; १५; २१; २७; ६६.१५; ६७.३०; ६८.१०; ६९.८; १०; ७०.१०; ७२.८; ८०.४; ८२.५; ८५.६; ८६.३८; ३९; ८८.७; ८९.७; ९०.३; ४; ६; ९६.३; ४; १२; १४; ९७.१५; १६; २७–३०; ३६; ४३; ४४[३]; ५२; ५३; १०६.१४; १०७.२४; १०८.१०; १०९.५; ६; ११०.१२; ११३.२

पवा ९.९७.५२

पवाते ९.९७.४

पविः ५.६२.२; ६.५४.३

पवितारः ९.४.४

पवितारम् ९.८३.२

पवित्रम् १.१३५.६; ८.१.१५; ९.२.१; २०.७; २४.५; २५.६; ४५.४; ४९.४; ५०.४; ५१.५; ६१.४; ५; ६२.१; ७; ३०; ६३.१५; ६६.५; २८; ६७.७; १९; २०; २३; २४; ६८.२; ६९.९; ८३.१; २; ८५.९; ८६.७; ९६.६; १७; ९७.१; १०६.१४; १०७.२५; १०९.१६; १९; १०.३१.८

पवित्रऽरथः ९.८३.५; ८६.४०

पवित्रऽवन्तः ९.७३.३; १०१.४

पवित्रऽवन्ता १०.२७.१७

पवित्रऽवान् १.१६०.३

पवित्रस्य ८.३३.१

पवित्रा ९.७३.८; ९७.५५

पवित्रात् १०.१७.१२

पवित्रे १.२८.९; ८.१०१.९; ९.२.५; ३.९; ६.३; १२.५; १६.३; ४; ७; १७.३; ४; १८.१; २७.१; २; ५; २८.२; ३०.१; ३६.१; ३७.१; २; ३९.३; ४; ४२.४; ४३.५; ४४.३; ५१.१; ५२.१; ५६.१; ६१.८; ६२.२१; ६३.१६; ६४.११; १२; ७३.७; ९; ८५.१०; ८६.३; ६; २२; २३; ३०; ८७.४; ७; ९२.१; २; ९७.४०; ९८.११; ९९.८; १००.६; ७; १०१.१५; १०९.१२

पवित्रेण ९.६७.२२; २५

पवित्रेभिः ९.८७.५; ९७.२४

पवित्रैः ३.१.५; २६.८; ३१.१६; ३६.७

पविऽभिः १.६४.११; ७.६९.१

२६.५; २७.५; २८.५; २९.५; ३०.५; ३४.२५; ३५.१५; ३६.९; ३७.८; ३९.७; ४०.७; ४१.७; ४२.६; ४३.५; ४५.४; ४६.४; ४७.४; ४८.४; ५१.३; ५३.३; ५४.३; ५६.२५; ५७.७; ५८.६; ६०.१२; ६१.७; ६२.६; ६३.६; ६४.५; ६५.५; ६७.१०; ६८.९; ६९.८; ७०.७; ७१.६; ७२.५; ७३.५; ७५.८; ७६.७; ७७.६; ७८.५; ७९.५; ८०.३; ८४.५; ८५.५; ८६.८; ८७.७; ८८.७; ९०.७; ९१.७; ९२.५; ९३.८; ९५.६; ९७.१०; ९८.७; ९९.७; १००.७; १०१.६; ९.९०.६; ९७.३; ६; १०.६५.१५; ६६.१५; १२२.८

पातः १.१३६.५

पातम् १.४६.५; ४७.३; ५; ९३.८; १२०.४; ७; १५३.४; ३.६२.१८; ५.७०.३; ७.६६.१९; ९१.६; ८.४२.२; ५७.२; ८७.१; ५

पातम् १.११२.२५; २.३९.४; ३.१२.१; २; ५८.९; ४.५६.४; ७.९१.४; ८.४०.१२; ८७.२; १०.९३.१[२]

पातयति १.४८.५

पातयन्ते ८.४६.१८

पातल्ये ३ इति ३.५३.१७

पातवे १.२८.६; १०८.२; ११६.२२; २.१६.५; ६.५७.२; ८.६९.१०; ९.१.१; ९; ४.४; ११.८; १६.३; २४.३; ५१.१; ९८.१०; १००.५; १०८.१५

पातवै ३.४६.५

पाता ६.२३.३; ४४.१५; ८.२.२६

पाता २.२०.३; ८.९३.३३

पाताम् १.१८५.१०

पाति ३.५.५[४]; ४.५.८; ८.५९.३; ९.८३.४

पाति ३.५५.१०; ४.१३.५; १४.५; ५.१२.६; ४७.३; ९.६.८; ७१.१; ८९.३; १०.१.३

पातु १.१८.५; ९८.२; १०६.७; ४.५५.७; ५.१५.५; ५१.१३; ६.६१.११; ७५.१०; १४; ७.१५.३; ३८.३; ५; १०१.६; १०४.२३[२]; ८.१८.६; ६१.१५; ९७.१५; १०.११.२; १७.४; १८.१०; ३६.३; ३७.२; ४२.११; ४३.११; ४४.११; ५३.५[२]; ६३.१६; ६४.१०; ६६.३; ८७.१; ११५.५; १५८.१; १६४.४

पात्रम् १.८२.४; ११०.५; १२१.१; १७५.३; २.३७.४; ६.७.१; ४४.१६; १०.५०.६; ११२.६

पात्रस्यऽइव १.१७५.१

पात्रा १.१०४.८; ६.२७.६; ८.१०३.६; १०.५३.९

पात्राऽइव ७.१०४.२१

पात्राणि १.१६२.१३; १०.४४.५

पात्रे १०.१०५.१०

पात्रेण १०.१३६.७

पाथ १.८६.१; १०.१२६.२

पाथ १०.१२६.४

पाथः १.११३.८; १५४.५; १६२.२; १८८.१०; २.३.९; ३.८.९; ३१.६; ५५.१०; ६.१५.१२; ७.४.९; ५.७; ३४.१०; ४७.३; ६३.५; १०.७०.९; १०; ९२.१५; ११०.१०

पाथः १.१८०.७; २.२.४; ७.९१.२

पाथः १.१५९.३

पाथन् १.१६६.८

पाथ्यः ६.१६.१५

पादः १०.९०.३; ४

पादुकौ ८.३३.१९

पादऽगृह्य ४.१८.१२; १०.२७.४

पादम् ७.३२.२

पादा १.२४.८; ६.२९.३; १०.७३.३

पादाऽइव २.३९.५; १०.१०६.९

पादाः १.१६३.९; ४.५८.३

पादि ६.२०.५

पादि १.१०५.३

पादुः १०.२७.२४

पादौ १०.९०.११

पादौऽइव ६.४७.१५

पानः ९.७०.४

पान्तः ९.९८.८

पान्तम् १.१२२.१; १५५.१; ७.३३.२; ८.९२.१; ९.६५.२८–३०; १०.८८.१
पान्ता १.१२२.४
पान्ति १.४१.२; १६७.८; ५.१८.४; ५२.४; ६७.३; ८.२५.१३; ४६.४
पान्ति २.११.१४; ५.१२.४; १९.२; ५२.२; ७.५६.१९; १०.५.२; १७७.२
पान्तु २.३.८; ४.४.१२; ७.४०.६; १०.१२८.७
पापः १०.१६४.५
पापजे १०.१०५.३
पापतन् ८.२०.४
पापतीति ६.६.५
पापऽत्वाय ७.३२.१८; ९४.३; ८.१९.२६
पापम् १०.१०.१२
पापया १.२९.५; ८.१९.२६; १०.७१.९; ८५.३०; १३५.२
पापस्य १.१२९.११
पापाः १.१९०.५
पापासः ४.५.५; ८.६१.११
पापीः १०.१०८.६
पामि १०.२८.२
पाथनाय १.११६.९
पायय ३.५७.५
पायय १.१४.७; १२५.३; २.३७.६
पाययते १.५६.१
पायवः १.१४७.३; ४.४.१२; १३; ५.१२.४; ८.१८.२
पायवे ६.४७.२४
पायुः १.३१.१३; ८९.५; २.१.७; ४.२.६; ४.३; ६.४४.७; ७.३७.८; ८.६०.१९; १०.१००.९
पायुऽभिः १.३१.१२; ९५.९; १३०.१०; १४३.८; १८९.४; ५.४१.१५; ७०.३; ६.७१.३; ७.३८.३; ८.२५.११; २७.४; ६०.८
पायुम् २.२.४; ६.१५.८
पायोः ३.१५.४
पारः ५.३१.८
पारतः ४.३०.१८
पारम् १.४६.११; ९२.६; १२१.१३; १८३.६; १८४.६; २.३३.३; ३.३१.२०; ५.५४.१०; ७.६०.७; ७३.१; ८.१९.३४; ९६.११; १०.२९.५; १६१.३
पारय १.१७४.९; ६.२०.१२
पारय १.९७.७; १८९.२; ९.७०.९
पारयतम् २.३९.४
पारयथ २.३४.१५
पारयथः १.११८.६
पारयन्ता ६.६९.१; ७.६९.७
पारयन्ति १.१८२.६
पारयन्ती ६.७५.३
पारयात् १.१४०.१२
पारयाति ८.१६.११
पारयामसि १०.९७.२२
पारयिष्णवः १०.९७.३
पाराय १.४६.७
पारावतऽघ्नीम् ६.६१.२
पारावतम् ८.१००.६
पारावतस्य ८.३४.१८
पारावताः ५.५२.११
पारिषत् १०.९६.८
पारिषत् १.१००.१४
पारे १.३३.७; ५२.१२; ११६.४; १६७.२; २.११.८; ६.६९.१; ८.५९.२; १०.२७.७; ४९.६; १४३.५; १५५.३; १८७.५
पार्थवानाम् ६.२७.८
पार्थिवः ७.३२.१७; २३; ८.५१.८; १०.८५.४
पार्थिवम् १.३८.१०; ८१.५; ९०.७; १२८.३; ५.८७.७; ८.८८.५; ९.१९.१; २९.६; ७२.८; १०७.२४
पार्थिवस्य १.११३.७; १४४.६; २.१४.११; ५.४१.१; ६८.३; ६९.४; ६.२२.९; ७.९७.१०; ९८.७
पार्थिवा १.६४.३; ४.५३.३; ५.८.७; ६.१६.२०; ४५.२०; ५९.९; ९.१४.८; ३६.५; ६३.३०; ६४.६; ९७.५१; १००.३; १०.१११.१०

पार्थिवाः ५.५२.७; ७.३५.११
पार्थिवात् १.६.१०; ७.१०४.२३; १०.५३.५
पार्थिवानाम् १.९५.३
पार्थिवानि १.३४.६; १५४.१; १५५.४; ५.४१.१४; ८१.३; ६.६.६; २२.८; ३१.२; ४९.१३; ६१.११; ८.९४.९; १०.३२.२
पार्थिवाय १०.७६.८
पार्थिवासः ५.४६.७; ६.३६.१; ५०.११; ७.३५.१४; १०.६५.९
पार्थिवीः ८.२५.६
पार्थिवे १.१६९.६; ८.९७.५; १०.१५.२
पार्थिवेभ्यः १०.१५८.१
पार्थिवेषु १०.११६.३
पार्थ्यः १०.९३.१५
पार्यम् १.१२१.१२
पार्याः ७.२७.१
पार्यात् ३.३२.१४
पार्याय ४.१६.११; २५.१; १०.२७.१६
पार्ये ६.१७.१४; २३.२; २६.१; ३३.५; ४०.५; ६६.८; ७.३२.१४; २१; ८३.५; ८.९२.९; ९.१.७
पार्श्वात् ४.१८.२
पार्षद्वाणः ८.५१.२
पार्ष्णिऽभ्याम् १०.१६३.४
पार्ष्ण्या १.१६२.१७
पावक ७.१.८
पावक १.१२.९; १०; १३.१; ५०.६; ९५.११; ९६.९; २.७.४; ३.१०.८; २१.२; ४.५.६; ५.४.७; २३.४; २६.१; ६.२.६; ४८.७; ८.४४.२८; ६०.३; ११; ७४.११
पावकः १.६०.४; १४२.३; २.३.१; ३.५.७; १७.१; २७.४; ४.६.७; ५.७.४; ६.४.३; ६.२; १०.४; ७.३.१; ९; ९.१; १५.१०; ८.१३.१९; ९.२४.६; ७; ९७.७; १०.४५.७
पावकम् १.६४.१२; ५.४.३; ६.१.८; १५.७; ८.२३.१९; १०.३६.७; ४६.४; ८
पावकया ६.११.२; १५.५; ९.१०१.२
पावकऽवर्चाः १०.१४०.२
पावकऽवर्णाः ८.३.३
पावकऽशोचिषः ३.११.७
पावकऽशोचिषम् ३.९.८; ४.७.५; ८.४३.३१; ४४.१३; १०२.११; १०.२१.१
पावकऽशोचिषे ५.२२.१
पावकऽशोचे ३.२.६; ६.१५.१४
पावका १.३.१०
पावकाः ३.३१.२०; ४.५१.२; ७.४९.२; ३; ५६.१२; ५७.५; १०.४६.७
पावकान् ६.५१.३; ८.२०.१९
पावकासः १.६४.२; १४२.६
पावके ६.५.२
पावके इति ६.४९.३
पावकेभिः ५.६०.८
पावमानीः ९.६७.३१; ३२
पावीरवी ६.४९.७; १०.६५.१३
पाशऽद्युम्नस्य ७.३३.२
पाशम् १.२४.१५; २५.२१; ७.८८.७
पाशाः २.२७.१६; २९.५
पाशात् ६.७४.४; १०.८५.२४
पाशान् १.२४.१३; ५.२.७; ७.५९.८
पाशिनः ३.४५.१; ९.७३.४
पाश्या १.५६.६
पाश्योः ९.१०२.२
पासतः ७.३४.२३
पासति १०.१७.४
पासि ६.३.१; ७.२८.२
पासि १.३१.१५; १३४.५[२]; २.१.६; ९; ५.३.३; ६.१५.११; ७.५.७; ८.५२.७
पास्त्यस्य ४.२१.६
पाहि १.२७.३; ३६.१५[३]; ५४.११; १२१.१४; १२९.९; ११; १७४.१; १८९.४; ३.४०.६; ४.४.१५; ५.१७.५; ३३.७; ७.१.१३[२]; ५४.३; ८.३३.४; ४८.१५; ६०.९[४]; १०; ७१.१; ९.६४.१८; १०.६१.२२; ८३.२; ११५.९; १५८.२
पाहि १.२.१; ३६.१४; ६७.३; ७०.३; ७२.६; ९१.१५; ९५.९; १२९.९;

१३०.१०; १४३.८^{2}; १४७.५; १७१.६; २.११.१५; १७; २८.१०; ३५.६; ३.१.१०; २०.२; ३१.२०; ३५.६; ८; १०; ३६.३; ३७.८; ४०.१; ४७.३; ५१.७; ८; ४.३४.७; ५.४.६; ८; ४३.३; ६.८.७; १५.१२; १६.३०; ३१; १७.२; ३; २४.१०^{2}; ४०.५; ४१.२; ४८.८; ७१.३; ७.३.७; ८; ४.९; १५.१५; ९८.२; ८.१३.२१; ४४.११; ६०.८; ६१.१६; ८४.३; ९.५६.४; ८८.१; १०.१२.६; २४.३; २५.८; ८७.२१; ९३.११; १२८.६; १६०.१; २

पिंशत १०.५३.७

पिंशति १.१६१.१०

पिंशतु १०.१८४.१

पिंशते ८.१९.२२

पिंषती १.१९१.२

पिङ्गा ८.६९.९

पिठींनसे ६.२६.६

पिणक् ३.३०.८; ४.१८.९; ३०.९; ६.१७.१०; ८.१.२८

पिण्डानाम् १.१६२.१९

पितः १.१८५.११

पितुः १.११४.९; २.३३.१

पितरः ६.७५.१०

पितरः १.६२.२; ७१.२; ८९.९; ९१.१; १०६.३; १०९.७; ३.३९.४; ५५.२; ४.१.१३; २.१६; ४२.८; ६.२२.२; ५२.४; ५९.१; ७५.९; ७.१८.१; ३५.१२; ७६.४; ९.६९.८; ८३.३; ९६.११; ९७.३९; १०.१४.२; ६; ७; ९; १५.१^{2}; ५; ८; १३; १७.९; १८.१३; ५६.४; ६; ६२.२; ६८.११; ९४.१२; १३०.१; ६

पितरः ८.४८.१२; १०.१५.४; ६; ७; ११; ५७.५; ८८.१८

पितरम् १.२४.१; २; ११४.७; १३०.१; १६३.१३; १६४.८; १२; १८; २२; २.१.९; २६.३; ३३.१२; ३.२६.९; २७.९; ४.१८.१२; ५.३.९; ३४.४; ५२.१६; ६.४९.१०; ७.१८.२५; २६.२; ३२.३; १०३.३; ९.८६.१४; १०.७.३; ४८.१; ५४.३; ८८.१५; ९५.१२; १२४.४; १२५.७; १८९.१

पितरा १.२०.४; ११०.८; १५९.२; १६१.१२; ३.३.११; ७.१; ५४.१६; ४.३३.३; ३४.९; ३५.५; ३६.३; ७.५३.२; ६७.१; १०.११.६; १२.४; ३९.६; ६१.१; ६५.८

पितराऽइव ३.१८.१; ५८.२; ४.४१.७; १०.१०६.४

पितरि १०.६१.६

पितरिति ६.५१.५

पितरौ १.१२१.५; १६१.१०; १०.८५.१४; १३१.५

पिता १.२६.३; ३०.९; ३१.१०; १४; १६; ३८.१; ४६.४; ६९.१; ८०.१६; ८९.४; १०; ९०.७; ११४.२; ११६.१६; १६०.२^{2}; १६४.१६; ३३^{2}; १८५.१०; १९१.६; २.५.१; १७.६; ३३.१३; ३.३.४; ३१.१; ४.१.१०; १७.१७; ५.३.१०; ४.२; ४३.२; ६०.५; ८३.६; ६.१.५; १६.३५; ७०.६; ७३.१; ७५.५; ७.३२.१९; २६; ५२.३; ५५.५; १०१.३; ८.५२.५; ६३.१; ९८.११; ९.७३.३; ७६.४; ८२.३; ८६.१०; ८७.२; ८९.२; १०९.४; १०.१४.५; २२.३; ३४.४; ६०.७; ६१.७; ६४.१०; ६७.१; ८१.१; ८२.१; ३; १००.५; १३५.१; १३८.६; १८६.२

पिताऽइव १.१.९; १०४.९; २.१०.१; २९.५; ३.४९.३; ६.१२.४; ५२.६; ७.२९.४; ५४.२; ९७.२; ८.२१.१४; २२.१५; ४८.४; १०.२३.५; २५.३; ३३.३; ४९.४; ६९.१०

पितुः १.३१.११; ६८.५; ७०.५; ८७.५; ११०.६; ११९.८; १२७.८; १४०.३; १४१.४; १५५.३; १५९.२; १६४.१६; २.१३.४; ३.१.९; १०; ४८.२; ५३.२; ५४.९; ४.४.११; १७.१२; ५.४३.७; ४७.३; ६.१६.३५; ४४.२२; ७.१०१.३;

पिप्रोः १.५१.५; ६.२०.७; १०.९९.११; १३८.३
पिब १.१४.१०; १५.१; ३–५; १३०.२; १६४.४०; १७७.४; २.१६.४; ३६.१; ४; ३७.१–३; ३.३२.१–३; ५; ३५.१०; ३६.२; ३; ४०.२; ४३.७; ४७.१; ४; ५०.२; ५१.१०; ५.५१.५; ६.१७.१; २३.७; ४०.१; ४३.१–४; ७.२२.१; २९.१; ९०.१; ८.१.२६; २.१; ३.१; ४.३; ८; १०; १२; १७.१; ४; ११; ३२.१९; २०; ३६.१–६; ३७.१–६; ६४.१०; १२; ६५.५; ७६.७; ९; ८२.२; ७–९; ९५.२; ३; ९.८५.२; १०.९६.१२; १०४.१; २; ११२.१; ६; ११६.१[४]; ७; १७९.३
पिब १.४.२; १०.११; १६.५–७; २३.१; ८४.४; १०४.९; २.३६.५; ३.३५.९; ४२.७; ४७.२; ४८.१; ५२.७; ४.४६.१; ५.४०.१; ६०.८; ६.४०.२; ४१.३; ४७.६; ८.६.३६; २१.३; २६.२०; ३२.२१; ४५.२४; ४९.४; ६५.८; ९१.२; १०१.१०; १०.२४.१; ११६.२
पिबत् ८.२.२३; १०.३७.११
पिबत् ५.२९.७
पिबत १.१५.२; ४.३४.४
पिबत १.१६१.८[२]; २.३६.२; ४१.१४; ५.५१.२; ७.३८.८; ५९.३
पिबतः ८.१०.४
पिबतम् १.१५.११; १३५.४; २.४१.३; ४.४६.६; ४९.६; ६.६०.७; १५; ६९.७; ७.६६.१८; ७४.२; ८.५.११; ८.१; २२.८; ३५.१०; २२; ५७.४; ८७.२; ४
पिबतम् १.३४.१०; ४६.१५; ४७.१; १०८.१; ५–१२; १३५.५; २.३६.६; ३७.५; ३.५८.७; ४.४५.३; ५०.१०; ६.६८.१०; ७.७४.३; ८.५.१४; १९; ३५.१–३
पिबति ५.३७.४
पिबतु १.४४.१४
पिबतु २.३७.४; ३.५०.१; ५१.९; ५.३६.१; ९.११३.१; १०.१७०.१
पिबध्यै १.८८.४; ३.३२.१५; ४.२७.५[२]; ६.४४.१४; ७.९२.२; ८.५७.३; ५८.३; ९.९७.२०
पिबध्वम् ३.५३.१०; ४.३५.९; ७.३७.२
पिबन् ४.२३.१
पिबन्तः ५.६१.११
पिबन्तम् ८.३३.७
पिबन्ति १.२३.१८; ८.९४.४; ५; ९.६४.२४; १०९.१५
पिबन्ति १.८४.१०; ४.२५.३
पिबन्तीः ६.२८.७
पिबन्तु ७.५१.२
पिबन्तु १.१४.८; १०.८७.१८; १६९.१
पिबन्तौ १.१८०.१
पिबऽपिब २.११.११; १०.२२.१५
पिबसि ६.४१.२; १०.२८.३
पिबस्व ४.३५.७
पिबात् ९.१०८.१४
पिबातः ५.७७.१
पिबाति ८.२४.१३
पिबाथः ४.४४.४; ६.६३.२; ७.६७.४; ८.८.३
पिबाथः ७.६९.३; ८.५७.१
पिबामि १०.८६.१९
पिबाव १०.८३.७
पिबासि ३.३५.१
पिब्दना ६.४६.६; ९.१५.६
पियानः १.७९.३
पियारुम् १.१९०.५; ३.३०.८
पिशङ्गा ७.५५.२
पिशङ्गऽअश्वाः ५.५७.४
पिशङ्गऽभृष्टिम् १.१३३.५
पिशङ्गम् ४.५३.२; ९.२१.५; ७२.८; १०७.२१
पिशङ्गऽराते ५.३१.२
पिशङ्गऽरूपः १.१८१.५; २.३.९

पिशङ्गऽरूपम् ८.३३.३
पिशङ्गऽसंदृशम् २.४१.९
पिशङ्गा १०.१३६.२
पिशङ्गैः १.८८.२
पिशा ७.१८.२
पिशाःऽइव १.६४.८
पिशाचिम् १.१३३.५
पिशानाः ७.५७.३
पिशुनेभ्यः ७.१०४.२०
पिष्टम् ५.५६.१
पिस्पृशः ६.१५.१८
पिस्पृशति ६.४९.१२
पीतः ६.४७.३; ८.४८.४; १०; १२; ९६.२१; ९.४५.६; ८६.४१
पीतम् १.१७९.५
पीतयः ४.३४.५
पीतये १.५.६; १६.३; २२.१; २३.२; ४७.९; ५५.२; १३७.२[२]; ३; १६६.७; ३.४२.४; ८; ९; ४.३६.२; ४८.१–४; ४९.२; ५; ५.५१.१; ७१.३; ७५.६; ६.४०.२; ५९.१०; ६८.१०; ७.३२.४; ५९.५; ८.१.२५; १२.१२; १७.१५; ३२.२४; ३३.१३; ३४.१०; ३५.२३; ४५.२२; ६५.३; ६८.७; ७६.६; ८५.१–९; ९२.५; ९४.१०–१२; ९७.८; ११; ९.१२.२; १७.८; २५.१; ३०.५; ३२.२; ३७.१; ३८.२; ६; ४३.२; ४५.१; ५०.५; ६२.८; ६४.१२; ६५.८; १४; ७४.९; ७८.४; १०.९.४; २९.६; १०४.६
पीताः ४.३७.२; ६.१७.४; ८.४८.५; ९.१०८.२; १०.११९.२; ३
पीतासः १.१६८.३; ८.२.१२
पीतिः ४.३५.२; ५.७६.३
पीतिम् १.१३४.६[२]; २.११.१७; १४.१; २; ४.३३.११; ३४.१; ४७.२; ५.५१.६; ७.९८.२; ८.८२.६; ९.१८.३; १०.१००.२; १०४.३
पीती ६.२७.१; २
पीत्या १.४६.१३
पीत्वा १.४.८; ८.६९.७; ९२.६; ९.२३.७; १०८.२; १०.४४.८; ९६.९
पीत्वी ३.४०.७; ८.७६.१०; १०.५५.८; ११३.१
पीपय ३.१५.६
पीपयः १.६३.८
पीपयत् ३.५७.६; ९.६.७; १०.१३३.७
पीपयत् १.७७.५; ८.१.१९
पीपयत १०.६४.१२
पीपयतः २.२७.१५
पीपयन् ७.६५.२
पीपयन् १.१५२.६
पीपयन्त १.७३.६; १८१.५; ६
पीपयन्त १.१५३.४; १६९.४; ५.३४.९
पीपरः १.१३८.२; ४.२.८
पीपरत् १.४६.६
पीपरत् ३.३२.१४
पीपरत् २.२०.४; ५.७७.४
पीपाय १.१५३.३; ६.१०.३; ६६.१; ७.२७.४
पीपाय १.१८१.८; २.२.९; ३५.७; ४.३.९; ६.४४.२१; ८.२९.६
पीपिऽवांसम् ५.७६.१; ७.९६.६
पीपिहि ६.१७.३; ३५.४
पीपेथ ८.५०.६
पीपेरिति पीपेः ४.१६.२१; १७.२१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११
पीप्याना १०.१०२.११
पीप्यानाऽइव ३.३३.१०
पीप्यानाः ३.१.१०; ७.३६.६
पीयतः १०.६८.६
पीयति १.१४७.२
पीयत्नवे ८.२.१५
पीयन्ति ८.२१.१४
पीयूषः ९.१०९.३; ६
पीयूषम् २.१३.१; ३५.५; ३.४८.२; ६.४७.४; ९.५१.२; ८५.९; ११०.८; १०.६३.३; ८७.१७; ९४.८

१९.१३; २१.५; २२.११; २४.३; २७.६; ७.२४.१; २७.२; ३२.१७; २६; ८.४.१५; २१.१२; २४.८; ९; ४६.१५; ६६.६; ११; १३; ९८.१२; १०.४२.७; १०; ४३.२; १०; ४४.१०; ८४.६; ९८.९; १०२.१; १०४.१; १४७.३; १८०.१

पुरुऽहूतः १.१००.६; ११; १८; १७७.१; ४.१७.५; ५.३०.१; ६.१८.१; ३४.२; ८.२.३२; १६.७; ११; ९.८७.६; १०.१२८.८

पुरुऽहूतम् १.५१.१; ३.३०.१०; ३७.५; ५१.१; ४.२०.५; ६.२३.८; ४७.११; ७.३२.२०; ८.१५.१; ९२.२; १०.४१.१; १०४.१०

पुरुऽहूता ६.६३.१

पुरुऽहूताय ३.३५.२; ६.४५.२२

पुरुहूते इति पुरुऽहूते ७.२.६

पुरूचीः ३.५८.८; १०.१८.४

पुरूणाम् १.५.२; ३६.१; ५.७४.७; ६.४५.२९

पुरूणि १.७२.१; ८४.१२; १२७.४; १४८.४; २.१९.४; २५.५; ३.१५.५; ३०.१३; ३२.८; ३४.५; ६; ३६.८; ३८.६; ४.१६.१६; २३.९; २९.१; ५.८.५; ६.१.१३[२]; ६.२; ४७.२; १४; ७२.३; ७.४५.१; ५३.३; ७०.४; ५; ८.७८.३; ९५.६; ९६.२१; ९.८८.२; १०७.१९; १०.४४.७; ८०.२; ८९.१६; ९६.६; १११.४; ११३.१०; १२०.७; १२४.३

पुरूरवः १०.९५.२; ५; १५

पुरूरवः १०.९५.७; ११

पुरूरवसे १.३१.४

पुरोळाः ३.२८.२; ७.१८.६

पुरोळाशम् १.१६२.३; ३.२८.१; ३–६; ४१.३; ५२.२–६; ८; ४.२४.५; ३२.१६; ६.२३.७; ८.२.११; ३१.२; ७८.१

पुरोहिते इति पुरःऽहिते ६.७०.४

पुर्थम् १०.१३८.४

पुलुऽकामः १.१७९.५

पुल्वघः १०.८६.२२

पुषेम १०.१२८.१

पुष्करऽस्रजा १०.१८४.२

पुष्करात् ६.१६.१३

पुष्करिणीःऽइव १०.१०७.१०

पुष्करिणीम् ५.७८.७

पुष्करे ७.३३.११; ८.७२.११

पुष्टम् १.१०३.५; ११४.१; १०.५५.४

पुष्टम्ऽपुष्टम् ९.५५.१

पुष्टयः २.२७.१२

पुष्टऽवन्तः ८.४५.१६

पुष्टस्य १०.५५.४

पुष्टानि २.१२.४

पुष्टिः १.६५.३; २.४.४; ४.१६.१५

पुष्टिऽगौ ८.५१.१

पुष्टिम् १.७७.५; १२२.७; २.१३.४; ४.३३.२; ५.१०.३; ६.२.१; ६३.६; ८.४८.६; ५९.७

पुष्टिऽमत् ३.१३.७; १०.८६.३

पुष्टिम्ऽभराय ४.३.७

पुष्टिऽवर्धनः १.१८.२; ३१.५; ९१.१२

पुष्टिऽवर्धनम् ७.५९.१२

पुष्टिषु १.१६६.८

पुष्टीः २.१२.५

पुष्टीनाम् १०.२६.७

पुष्टे १.१६२.७

पुष्टेः ४.४१.१०; ५.४१.२०

पुष्टेषु १०.८६.१

पुष्टौ ५.४१.३; १०.६१.२४

पुष्ट्यै १०.१०५.५; १०६.४

पुष्पऽवतीः १०.९७.३

पुष्पिणीः २.१३.७; १०.९७.१५; १४२.८

पुष्यत् १.९४.८

पुष्यतः १०.९१.३

पुष्यतः १०.१३.५

पुष्यता ५.३४.५

पुष्यति १.६४.१३; ८३.३; ७.३२.९; १०.७९.५; ११७.६; १३२.३

पुष्यति ३.१०.३; ६.२.५; ८.३९.७; ४१.५; १०.८३.१

पुष्यते १०.११.५

पौरुऽकुत्स्यः ८.१९.३६

पौरुऽकुत्स्यस्य ५.३३.८

पौरुषेयः ८.७१.१

पौरुषेयीम् ७.४.३

पौरुषेयेण १०.८७.१६

पौरे ८.५०.५

प्यायन्ताम् १.९३.१२

प्यायसे १०.८५.५

प्यायस्व १.९१.१६; १७; ९.३१.४; ६७.२८

प्र १.३.१२; ४.८; ५.१; १०.११; ११.२; १३.११; १४.४; १५.९; १७.९; १९.१; २१.२; २३.२२; २४.९; ११; २५.१; ६; १२; २७.४; ३१.८; १४[२]; १८; ३२.१[२]; ४; ३३.५; ७; १३; १४; ३४.११; ३६.१; ३; ११; १७; ३७.१; ४; ५; ११; १४; ३८.१०; ३९.१; ५; ४०.१; ३[२]; ५; ४१.५; ४२.१; ९; ४७.५; ४८.४; १५[२]; ४९.२; ३; ५१.५[२]; ५३.१; ५४.८; ५५.३; ५६.१; ५७.१; ५९.५; ६; ६०.५; ६१.१; २; ९; १२; १३; १५; ६२.१; २; ६४.१; ३; १३; ६६.५; ६७.४; ७१.१; १०; ७२.४; १०; ७४.८; ७६.३; ७८.१–५; ७९.१०; ८०.३; ८१.१; ८२.३; ६; ८३.२; ८४.१९; ८५.१; ५; ६; ८७.३; ५; ८९.२; ९१.१; १९; २३; ९४.१६; ९५.३; ९६.८; ९७.३[२]; ४[२]; ५; १०१.१; १०२.१; ३; ४; १०४.४; ८; १०९.५; ६[५]; ११०.२; ११२.५; ८; १३; २३[२]; ११३.१६; ११४.१; ११६.१; १०[२]; १२; २५; ११७.२२; २३; २५; ११९.६; ७; १२०.३; ५[२]; १२१.१; ६[२]; १४; १२२.१; ४[२]; ५; १२४.१[२]; ५; १०; ११; १२५.६; १२६.१; १२७.२; ४; १०; १२९.१; ६; १३०.८; ९; १३२.५; १३४.३[२]; १३५.१; १३६.१; १३८.२; १३९.१; १४०.१; ५; ८; १४१.४; १४३.१; २; १४४.१; १४८.३; १४९.२; १५१.२–४; १५२.५; १५४.१–३; १५५.१; १५७.१; ४; १५८.१; ४; १५९.१; १६१.९; १२; १६२.७; १९; १६३.१२; १३; १६४.१८; २५; २६; १६५.१३; १६६.४; ५; ७; १६७.७; १६९.६; १७०.५; १७३.२; ४; ६; १७४.५; ६; ९; १७६.५; १७७.४; १८०.९[२]; १८१.५; ६; १८६.९[२]; १०; १८७.५; १९०.३; १९१.१५; २.१.१५; १६; २.१३; ३.१०; ९.३; ११.३; १४; १३.२; ११; १२; १५.१; ५; ९; १६.१; ७; १७.३; १९.२; ३; २०.१; २१.३; २२.२[२]; ४; २३.१०; २४.२; ८; १२; २५.१; २६.२; ४; २८.४; २९.५; ३०.२; ३; ६; ३१.१; ३३.१; ८; ३५.८; ३८.२; ४१.१९; ३.१.२०; २२; ३.८; ४.३; ५; ५.२; ६.१; २; ७.१[२]; ३; १०.५; १२.५; ७; ९; १३.१; १५.६; १७.२; ५; १९.१; २; २१.१; ५; २६.४[२]; २७.१; ८; २८.४; २९.१४; ३०.२; ६[२]; १०; ३१.८; १६; २१; ३२.६; ३३.१; ५; १२; ३४.२–५; ९; ३६.५; ६; ९; १०; ४०.३; ४; ४३.६; ७; ४५.३; ४६.३[४]; ५१.४; १२[३]; ५२.५; ५३.६; ७; ११[२]; ५४.१; ३; ५; १०; ५५.७; १८; ५७.१; २; ५८.४; ५९.२; ६१.५[२]; ४.१.४; ९; १२; १३; २.२०; ३.१२; ४.५; ५.३; ४[२]; ६.१; १०.४; १२.६; १६.७[२]; १२[२]; १७.५; १०; १८.१२; १९.२; ५[२]; ७; १०; २०.१०[२]; २१.४; ७[२]; २२.३; ६[२]; ७; २३.६; २४.९; २६.४[२]; २९.३; ३०.६; १३; ३२.९; १०; २२; ३३.१; ३४.३; ३७.२; ३९.६; ४१.२; ४२.७; ४५.७; ५३.३; ४; ५५.२; ३; ५६.५; ५८.२; ५.१.१[२]; ७–९; २.८–१०; ४.१; ६; ७.४; ६; ८; १०.१; ३; १२.१; १५.१; १७.४; १९.१[२]; २२.१; २; २६.८; २९.१०; १३; ३०.३; ६; ८; ९; ३१.२; ३; ६[२]; ३३.२; ६; ३६.४[२]; ४१.३–५; ६[२]; ७; ४२.१; ६; १३; १४[२]; १६; ४३.३; ९; ४४.४; ४५.५; ४६.२; ७; ४८.२; ४९.५; ५२.१; ५; ८; १६; ५३.७; १०; १२; ५४.१; २; ५६.४;

७; ५८.६; ५९.१^{२}; ४; ५^{२}; ७; ६०.१; ६४.२; ६५.३; ६८.१; ७४.५; ७६.२; ७७.१; ८१.२; ८२.९; ८३.४; ६; ८४.१; २; ८५.१; ३; ५; ८६.१; ८७.१^{२}; २^{२}; ३^{२}; ६.६.१; ५; ८.१; ७; ११.३; १४.१; १५.१०; १३; १६.८; २२; ४१; १७.१२; १८.७; ९; १२; १३; २०.४; ६^{२}; १०; १२; २१.९^{२}; २३.८^{२}; २४.३; ९; २६.४; ५^{२}; ३०.१; ३१.५; ३२.४; ३६.२; ४०.१; ४१.२; ५^{२}; ४२.४; ४४.११; १३; १४; १७; २०; ४५.४; २४; २५; ४७.७^{२}; २०; ४९.४; ८; १२^{२}; १४; ५४.६; ५७.५; ५९.१; ९; ६१.४; १३; ६३.४^{२}; ५–७; ६६.९; ६७.२; ४; ९; ६८.४; ६; ७; ९; ६९.२^{२}; ७०.३; ७२.३; ७४.१; ४; ७५.१६; ७.१.४; ७; २२; २.४; ४.१; ५.१; ६.१^{२}; ७.१; ६; ११.३; १३.१; १८.१७; १९; २१; १९.१; ३^{२}; २०.२; ५; २१.२; २४.१; ६; २५.६; २९.१; ३१.१; ४; १०^{३}; ३३.३; १४; ३४.१; ५; ९; १८; ३६.१; ४; ८^{२}; ३९.२; ४१.३^{२}; ४२.१^{३}; ३; ४३.१; २; ५३.१; २; ५६.१४^{२}; ५७.१; ५^{२}; ५८.१–४; ६; ५९.२; ६१.२; ३^{२}; ४; ६; ६२.२; ५; ६४.१; ३; ६६.१; ५; ६७.९; ६८.२; ३; ७०.१; ५; ६; ७२.४; ७४.६; ७५.२; ७६.२; ८०.२; ८२.६; ८३.४; ६; ८४.१; ३–५; ८५.५; ८६.१; ४; ८७.१; ८८.१; ३^{२}; ९०.१; ९२.२^{२}; ३; ९३.४; ९५.१; ९८.३; ५^{२}; १००.१; ३; ५; ६; १०१.१; १०२.१; १०३.१; ९; १०; १०४.३; १७; १९; २२; ८.१.७; ८; १६; २.१३; १९; ३.१२; ४.५; १२; १५; ६.२; ७; ८; ९^{२}; ३२^{२}; ७.१; ४; ८.५; १०; १६; २१; २२; ९.१; १६; १७^{४}; १९; २०^{४}; १०.३; ४; १२.८; ९; २३; ३१–३३; १३.१४; १५.१; १६.१; १७.७; ९; १२; १८.२२; १९.२; २७; ३०; २०.४; २१.९; १२; १६; २२.६;

२३.१२; २४.१३; २७.३^{२}; ८; १०; १५; १६^{२}; २९.८; ३१.१७; ३२.१; २७; ३५.११^{२}; ३६.२; ७; ३७.१^{२}; ७; ३९.३; ४०.५; ४४.३०; ४५.२५; २८; ३१; ४६.१८; २८; ४८.२; ४; ६^{२}; ७; ४९.१; २^{२}; ४; ९; ५०.१; ६; ९; ५१.८; ५२.५; ७; ५३.६; ५६.४; ५७.४; ५९.१; ७; ६०.१०; १६; ६१.९; ६२.२; ६३.८; ६४.४; १०; ६६.८; ११; ६७.९; ६९.४; ८; ७१.६; ७३.९; ७९.२; ६; ८०.४; ८१.५; ६; ८२.१; ५; ८३.८; ८५.९; ८८.५; ८९.३; ४; ९०.६; ९२.१; ५; ९३.१६; १९; ९६.५^{२}; १०; १००.३; ७; १०१.३; ५^{२}; १५; १०३.२; ४; ६; ८; ९.७.२; ३; १०.१; १२.६; १३.२; १४.१; १६.१; ४; ५; १७.१; १८.२; २०.१; २१.७; २२.१; २४.१; ३; २९.१; ३०.१; ४; ३१.१; ३२.१; ३३.१; ३४.१; ३५.४; ४१.१; ४४.१; ५७.१; ६०.१; ६२.२८; ६३.१६; ६४.४; ७; १६; १९; ६५.७; २६; ६६.७; १३; २८; ६७.१५; २८^{२}; ६८.१; ४; ६९.९; १०; ७०.४; ७१.२; ७५.५; ७६.३; ७७.१; ७८.१; ७९.१; २; ८१.१; ८२.४; ८५.७; १२; ८६.१; २; ४^{२}; १६; १७; ३१; ४२; ४७; ८७.१; ९०.१; ९१.२; ९२.३; ५; ९३.३; ५; ९५.३; ९६.१; ७; २२; ९७.४; ७; ८^{२}; २३^{२}; ३०; ३१; ३४; ३८; ५२; ९९.२; १०१.१३; १०२.८; १०३.१; १०४.१; १०६.४; १०७.१२; १५; १०९.१; १६; १८; ११०.१; २; १०.१.२; ७; ४.१^{२}; ५; ८.१; ९.८; १०.५; ६; ११.७; १३.२; ४; १४.७^{२}; १४^{२}; १५.७; १२; १६.१; ७; ९; ११; १७.३; २०.४; २३.१; २५.३; ४; ११; २६.१^{२}; ७; २७.३; ४; १९; २०; २२; २९.२^{२}; ५; ३०.१; ७–९; ३१.११; ३२.१; ५–८; ३३.१; ३५.५; ३७.९; ३८.१; ५; ३९.५; ४०.११; ४२.१; २; ८; ४३.४; ४४.६; ४५.९; ४६.१; ५;

८^{२}; १०; ४७.६; ४८.८–१०; ४९.४; ७; ८; ११; ५०.१; ७; ५२.१; ५३.८; ५४.१; ५६.५; ५७.१; ५९.१; ५; ६१.१८; ६२.८; ११; ६३.१३; ६४.७; ६६.१०; १२; ६७.३; १२; ६९.५; ९; ७०.९; ७१.१; ७२.१; ८; ९; ७३.३; ५; ७५.१^{३}; २; ३; ७६.३; ७७.३; ६; ७९.३; ४; ८०.७; ८३.७; ८४.१; ३; ८५.१३; १९; २४–२६; ८६.२; ८७.५; ८; ९; ८८.११; ८९.१; ४; ८; ९^{४}; ११^{८}; १२; ९०.७; ९२.५; ७; ११; १३; ९३.१४^{२}; ९४.१^{२}; ३; ९५.२; १०; १३; १५; ९६.१^{२}; ९; ११; ९७.१०; १३; १४; ९८.८; ११; १००.१; २; १०१.२; १०२.१; ४; १०३.७; १२; १३; १०४.३; १०५.६; ११; १०६.१; १०७.२; ४; १०८.१; १०९.२; १११.१; ९; ११२.१; २; ८^{२}; ११३.४; ९; ११४.६; ७^{२}; ११५.४; ११६.९^{२}; ११७.४; ११९.२; १२०.६; १२५.८; १२६.८; १२९.६; १३०.१; १३५.४^{२}; १३८.५; १३९.६; १४१.१; २^{५}; १४२.२^{२}; ४; १४५.६; १४६.६; १५०.५; १६१.१; १६५.५; १६८.२; १७१.१; १७५.१; १७६.१–३; १७९.२; १८०.१; १८३.१; २; १८५.३; १८६.१; १८७.१; १८८.१; २

प्रऽअध्वने ४.५८.७

प्रऽअर्पणः १०.४५.५

प्रऽअर्प्यै १.११३.४

प्रऽअविता १.१२.८; २३.६; ८७.४; ३.२१.३; ८.९६.२०

प्रऽअवितारः ८.२७.२

प्रऽअवीः ४.९.२

प्रऽअस्य १.१२१.१३

प्रऽईतिम् १.३३.४

प्रऽइद्धः ७.१.३; १०.६९.१२

प्रऽइव १.१०३.७; १०.१४६.१

प्रऽइषितः ७.७३.३; १०.३७.५

प्रऽइषिताः १०.९८.६

प्रऽइङ्खम् ७.८७.५

प्रऽइङ्खे ७.८८.३

प्रऽउगम् १०.१३०.३

प्रऽऊळ्हः १.११७.१५

प्रऽकङ्कताः १.१९१.७

प्रकलऽवित् ७.१८.१५

प्रऽकाशः १०.१२४.६

प्रऽकुपितान् २.१२.२

प्रऽकेतः १.९४.५; ११३.१; ३.३०.१; ७.११.१; ३३.१२; १०.१०४.६; १२९.२

प्रऽकेतम् २.१७.७

प्रऽकेतैः ७.३३.९; १०.७.१

प्रऽक्रीळान् ४.४१.११

प्रऽक्रीळिनः ७.५६.१६

प्रऽखादः १.१७८.४

प्रऽख्यै ७.८१.४

प्रऽगर्धिनः ४.४०.३

प्रगर्धिनीऽइव १०.१४२.४

प्रघ्नताम्ऽइव ९.६९.२

प्रऽचक्राणम् ९.१५.७

प्रऽचता १०.१२४.२

प्रऽचरन् ५.४८.३

प्रऽचाकशत् ४.५३.४

प्रचेत इति प्रऽचेतः १.२४.१४; ७.१७.५; १०.८३.५; ८७.९

प्रऽचेतः ६.१३.३

प्रऽचेतयन् ९.९७.१३

प्रऽचेतसः १.४१.१; ४४.७; ६४.८; ८४.१२; २.२३.२; ४.५३.१; ६.७५.१३; ७.८७.३; ८.७.१२; ४७.४; ८३.२; ९.६४.२१; १०.६३.८. ६६.१; ८५.१७

प्रऽचेतसः १.३९.९; ५.८७.९; ८.६७.१७; ८३.५

प्रऽचेतसम् १.४४.११; ३.२९.५; ४.१.१^{२}; ७.१६.१२; ८.८४.२; ९०.६; १०२.१८; १४०.५

प्रऽचेतसा १.१५९.१; ८.१०.४; १०.३६.२

प्रऽचेतसा ५.७१.२; ८.९.१५; २०

प्रऽचेतसे १.५.७; ४३.१; ७.३१.१०; ८.२७.२१

प्रऽचेताः २.१०.३; ३.२५.१; ६१.१; ४.६.२; ६.५.१; ५; १४.२; ७.४.४; १६.५; १०.७९.४; ११०.१; १६४.४

प्रऽचेतुने १.२१.६

प्रऽचोदयः ८.१२.३

प्रऽचोदयन् ३.२७.७

प्रऽचोदयन्ता १०.११०.७

प्रऽचोदयात् ३.६२.१०

प्रऽच्यवयन्तः १.८५.४

प्रऽच्युतः ९.८०.४

प्रजज्ञिऽवान् ३.२.११

प्रऽजज्ञे १०.७३.१०

प्रऽजननम् ३.२९.१

प्रऽजया १.२३.२४; ९३.३; १३६.६; १०.१८.२; ८०.३; ८५.२७; ३८; १२८.५; १६९.४; १८३.१; २

प्रऽजवः ७.३३.८

प्रऽजहितानि ८.१.१३

प्रऽजा १०.९५.१८

प्रऽजाः १.४३.९; ६७.५; ९६.२; ३.५५.१९; ७.३३.७; ८.१०१.१४; ९.८६.२८; ९७.४०; १०.५६.५; १७०.१; १८३.३

प्रऽजातः १.६९.१

प्रऽजातम् १.१६४.१८

प्रजानतीऽइव १.१२४.३; ५.८०.४

प्रऽजानन् २.३.१०; ३.२६.८; २९.१६; ३१.५; ३५.४; ८; ५४.२; ४.१.१०; ७.४४.४; १०.१६.९; १७.५; ६; ८८.६; ९१.४

प्रजाऽपतिः ४.५३.२; ९.५.९; १०.८५.४३; १६९.४; १८४.१

प्रजाऽपते १०.१२१.१०

प्रऽजाभिः २.३३.१; ३५.८; ५.४.१०; ६.७०.३; ८.२७.१६; १०.६३.१३

प्रऽजाभ्यः २.१३.४; ४.५३.४; ५.८३.१०; ७.३५.१०

प्रऽजाम् १.१२५.१; १७९.६; २.३.९; ३२.६; ४१.१७; ४.३६.९; ६.६१.३; ७.९६.६; ८.६.२; २३; ३५.१०–१२; ५९.७; ९.८.९; १०९.९; १०.१८.१; ५६.६; ७; ८५.४३; १५७.२; १६२.५; ६; १८३.१

प्रऽजायाः १.१५९.२; १०.६१.९; ९२.१०

प्रऽजायै ५.४१.१७; ७.३६.९; ५७.६; ९.१०९.५; १०.१३.४; ५४.१; ७२.९; ७३.५; १२८.८

प्रजाऽवत् १.११३.१७; १३२.५; ३.८.६; ५.८२.४; ६.१६.३६; ७.६७.६; ९.५९.१; ६०.४; ८६.४१; १०.१०४.४

प्रजाऽवतः १.२५.८; ९२.७; २.२.१२; ३.१६.३; ६; ८.२३.२७

प्रजाऽवता १.७६.४; ९४.१५

प्रजाऽवती ८.३१.४

प्रजाऽवतीः ६.२८.१; ७; ५२.१६; ९.२३.३; ७४.६; ८६.४१; १०.१६९.३

प्रजाऽवतीषु ७.१.११

प्रजाऽवन्तः १०.३७.७; ५७.६

प्रजाऽवन्तम् ४.५१.१०; ५३.७; ७.१.१२

प्रजाऽवान् ३.३०.१८; ५४.१८; ५६.३; ४.२.५

प्रऽजासु ८.५३.६

प्रऽजिगतः १.१५०.२

प्रऽज्ञातारः १०.७८.२

प्रणक् १.१८.३; २.२३.१२; ७.५६.९; ९४.८

प्रऽतताः ३.३१.२०

प्रतद्वसू इति प्रतत्ऽवसू ८.१३.२७

प्रऽतपन् ९.१०८.१२

प्रऽतरणः १.९१.१९; २.१.१२; ६.४७.२६; ७.५४.२

प्रऽतरणम् ८.४९.४

प्रऽतरणीम् ५.४६.१

प्रऽतरम् १.५३.११; ९४.४; १४१.१३; २.३२.१; ४.१२.६; ५.३४.१; ५५.३; ६.४७.७; १०.१०.१; १८.२; ३; ४२.१; ४५.९; ५९.१; ६६.१; ७९.३; ११५.८; १२६.८

प्रऽतरीता ९.८६.१९; १०.१००.५

प्रऽतवसः १.८७.१

प्रऽतवसे ४.३.६

प्रऽतस्थुः १०.६५.१५; ६६.१५

प्रति १.९.४; ११.६; १२.५; १९.१; २५.२०; ४१.८; ४६.१०; १२; ४८.२; १३; ५२.१५; ५४.७; ५५.१; २; ५७.४; ६३.८; ७९.६; ८८.६; ९१.४; ९२.१; ५; ९३.१; ९५.५; १०१.१०; १०४.५; १०७.१; ११३.७; ११५.२; ११६.१५; ११७.२२; ११८.३; ७; ८; ११९.२[2]; ९; १२१.९; १२४.३; १२७.१०; १४४.७; १५१.१; १५५.६; १६१.३; १६२.१५; १६४.२४; २९; १६५.४; १२; १६८.८; १६९.६; ७; १७१.१; १८०.४; १८३.६; १८४.६; १९१.५; २.१.८; १५; ३.२[2]; ११.२१; १५.७; १०; १६.९; १७.२; ९; १८.९; १९.९; २०.८; ९; २४.११; ३३.१२; ३६.४; ३९.३; ३.१.१७; ४.५; ५.१; १८.१; २१.५; ३०.१७; ३१.४; ३३.८; ३६.२; ५२.८; ५३.३; ५८.२; ३; ४.३.८; १४; ४.३–५; १५; १२.२; १३.१; १४.१; १७.७; १९.३; २४.७; २७.५[2]; ४५.५; ५२.१; ४; ५; ५३.२; ५.१.१; २.११; २९.४; ३०.१२; १५; ४१.१८; ४२.२; ४४.१२; ४८.४; ४९.२; ५५.६; ५७.१; ६१.९; ७५.१[2]; ७६.२; ८०.१; ८१.२; ८३.९; ८४.२; ८६.३; ६.३.५; ६; १३.४; २५.५; ३०.१; ४२.१; ४७.२२; २८; ६८.१०; ७.१.१८; ३.६; ९.४; १५.१३; २८.४; ३१.६; ३४.२१; ४०.१; ५४.१[2]; २; ५९.८; ६२.२; ६३.५; ६५.१; ४; ६६.७; ६७.१; ७०.५; ७३.१; ३; ७५.६; ७; ७६.६; ७८.१; २[2]; ३; ५; ८०.१; ८१.१; ३; ९५.५; १०१.३; १०४.७; ११; २५; ८.३.२३; ५.३; २०.९; १६; २१.११; २३.१३; २२; ३१.६; ३२.४; ४४.२; ११; ४५.५; ५६.१; ६४.२; ७०.२; ८२.१; ९२.३२; ९६.९; १९; ९९.३; १००.५; १०१.७; १०; १३; ९.६९.१; ४; ९२.१; १००.९; ११३.३; १०.१.४[2]; १३.३; १६.३; २७.११; १३; ३०.१३; ३७.७; ८; ४०.१; ४८.७; ६२.१–४; ६४.१३; ७०.१; ८७.४; १०; १२; २०; २३; २४; २५[2]; ९५.१३; ९७.३; ९८.१; २; १०१.१०; १०५.११; ११४.९; ११६.७; ८; ११८.२; ८; ११९.७; १२२.२; १३३.७; १४२.५; १४९.५; १५८.५; १६७.४; १७२.३; १८९.३

प्रतिऽअर्धिः १०.२६.५

प्रतिऽअर्धिम् १०.१.५

प्रतिऽअहन् १.३२.१२

प्रतिऽआवर्तय ६.४७.३१

प्रतिऽइतये १.३६.२०

प्रतिऽइत्य १०.११६.५

प्रतिऽइष्य १०.१२९.४

प्रतिऽईपम् ७.८९.३; १०.२८.४

प्रतिऽएतन ६.४२.२

प्रतिऽकामम् ३.४८.१; १०.१५.८; ११२.१

प्रतिऽक्षियन्तम् २.१०.४

प्रतिऽगृह्य १.१२५.१

प्रतिऽघ्नन्ति ८.२५.१५

प्रतिऽचक्षणाय ६.४७.१८

प्रतिऽचक्षाणः ९.८५.१२

प्रतिऽचक्ष्य २.२४.६; ७

प्रतिचक्ष्यऽइव १.१२४.८

प्रतिऽचक्ष्या १.११३.११

प्रतिऽच्यवीयसी १०.८६.६

प्रतिऽजन्यानि ४.५०.७; ९

प्रतिऽजानते ३.४५.४

प्रतिजूतिऽवर्पसः ३.६०.१

प्रतिऽदीव्ने १०.३४.६

प्रतिऽदोषम् १.३५.१०; ६.७१.४

प्रतिऽधयः १०.८५.८

प्रतिऽधा ८.७७.४

प्रतिऽधातवे १.२४.८

प्रतिऽधीयमानम् १.१५५.२

प्रतिऽधृषे ८.६०.१३; १४

प्रतिऽनुदन् १०.१२८.६

प्रत्नासः ४.२.१६; ५०.१; ५.८.१; ६.२१.५; ९.२३.२; ९८.११
प्रत्ने इति ६.१७.७
प्रत्नेन ६.२१.७; ८.६.११; ४४.१२; ७६.६; ९.३.९; ४२.२; ९७.४७
प्रत्नेभिः ९.५२.२; १०.३.६
प्रत्नेषु ८.१३.२०
प्रत्यक् १०.८७.१५
प्रत्यङ् १.५०.५[३]; १४४.७; २.३.१; ५.२८.१; ९.८०.३; १०.१२.१; ७९.५; ८८.१६; १२३.७; १४१.१
प्रत्यञ्चः १०.१२८.६
प्रत्यञ्चम् २.१०.५; ७.१२.१; १०.२७.१३; २८.४; ९; ८७.१७; १५७.५
प्रऽत्वक्षसः १.८७.१; ५.५७.४
प्रऽत्वक्षसम् १०.४४.३
प्रऽत्वक्षाणः १०.४४.१
प्रथः १०.१८१.१
प्रथताम् १०.७०.४
प्रथते १०.९४.९
प्रथते १.१२४.५; १०.११०.४
प्रथन्त ९.९४.२
प्रथन्ताम् २.३.५
प्रथमः १.३१.१–३; ८३.१; ५; १०१.५; १३४.६; १६२.४; १६३.२; ९; २.१०.१; १२.१; २५.४; २७.१२; ३०.१; ३६.१; ३.२१.१; ४.१.११; ७.१; ३८.६; ५.३१.१; ४३.३; ६.१.१; ९.४; १५.१६; ४१.१; ५४.४; ७.११.१; ४४.४; ८.२३.१८; २७.८; ६१.२; ९०.२; ९.८६.२८; ८९.३; ९१.१; १०७.२३; १०.८.२; ११.२. १२.२; १४.२; ३४.१२; ८५.४०; ८८.४; ९२.१०; १०७.५[२]; ६; १०९.२; १२२.५; १६७.४
प्रथमऽच्छत् १०.८१.१
प्रथमऽजाः १.१६४.३७; ३.२९.१५; ६.७३.१; १०.५.७; ६१.१९; १०९.१; १६८.३
प्रथमऽजाम् १.३२.३; ४
प्रथमऽभाजम् ६.४९.९

प्रथमम् १.३१.११; ३५.१; ७७.३; ८३.४; ९६.३; १०२.९; १०८.६; १४४.१; १४५.२; १६३.१; १६४.४; १८५.१०; २.१३.१–४; १७.३; १८.२; २२.४; २४.१०; ३९.३; ३.४.३; २९.५; ४८.१; ४.१.१२; १६; ११.५; १७.७; ५०.४; ५४.२; ५.११.२; ४२.७; ६.१.२; ७.४४.१; ४७.१; ९७.१; ८.३.११; २३.२२; ७१.१२; ८०.५; ९.६८.५; ७०.६; ८६.१५; १०.४५.१; ४६.९; ५३.४; ६४.१३; ६७.२; ७१.१; ७५.६; ८२.५; ६; ८८.८; १२२.४; १२९.४; १८१.३
प्रथमश्रवःऽतमः ४.३६.५
प्रथमस्य १.२४.२; १२३.९; ३.१५.४; ६.२८.५; १०.१०.६; ९४.८
प्रथमा १.११३.८; १५; १२३.२; ५; १२४.२; १५१.८; १५२.३; १८८.७; २.३.७; ३९.३; ३.४.७; ७.८; १७.१; ३१.६; ३६.८; ५६.१; ४.४२.२; ५.७७.१; ७.७६.६; ९८.५; १०.३५.४; ५५.४; ५६.३; ६६.१३; ८३.७; ११०.७; ११२.८; १२५.३
प्रथमाः १.१५२.२; २.३४.१२; ३.३६.३; ४.२.१५; ७.७८.१; ८०.१; ९.७९.५; ८६.३०; ११०.७; १०.२७.२३; ४२.१०; ४३.१०; ४४.६; १०; १०९.१; १११.८
प्रथमान् १०.१७.११
प्रथमानि १.३२.१; १६४.४३; ५०; १६६.७; ६.७२.१; ८.१०३.६; १०.९०.१६; ११३.७
प्रथमाम् १०.६३.७
प्रथमाय २.१७.२; १०.१४७.१
प्रथमासः १०.६.७
प्रथमे ८.१३.२; ९.९७.४०; १०.७२.३
प्रथमे इति १०.१२.१
प्रथयत् ४.४२.४
प्रथयन् ३.१४.४; ४.५३.२; ८.१२.६; ५१.८
प्रथयन्तः ५.४३.७
प्रथयन्तम् १०.४९.६

प्रथयसे १०.२१.८
प्रथयस्व १०.१४०.४
प्रथसः १०.८९.११
प्रथस्व ५.५.४
प्रथाना १.९२.१२
प्रथानाम् ६.६४.३
प्रथिना १.८.५; ८.५६.१
प्रथिष्ट ५.५८.७; १०.६१.५
प्रथिष्ठम् १०.८७.१
प्रऽदक्षिणित् २.४३.१; ३.१९.२; ३२.१५; ४.६.३; ५.६०.१; १०.२२.१४
प्रऽददातु ७.१०४.९
प्रऽदिवः १.५३.२; १४१.३; २.३.१; ३.३६.२; ३८.५; ४३.१; ४७.१; ५०.२; ५१.४; ४.६.४; ७.८. ३४.३; ५.८.७; ६.५.३; २३.५; ४४.१२; ६२.८; ७.९०.४; ९.७२.४; १०.५.४; ३७.३
प्रऽदिवा ५.६०.८
प्रऽदिवि २.१९.१; ३६.५; ३.४६.४; ५.६२.४; ७६.४; ६.२१.८; ४१.३; ७.९८.१
प्रऽदिशः १.१६४.४२; ६.७५.२; ७.३५.८; ८.१००.४; ९.८६.२९; १०.१९.८; ५१.९; ५६.७; ५८.४; १२१.४; १२८.१
प्रऽदिशम् २.४२.२; ९.१११.३
प्रऽदिशा १.१०१.७; १६४.३६; १०.११०.४; ७
प्रऽदिशि २.१२.७; १०.११०.११
प्रऽदिष्टाः ३.३०.१२
प्रऽदीदयत् ८.६.२४
प्रऽदीध्याना १.११३.१०
प्रऽदृसिः ६.३.२
प्रऽदेदिशत् १०.१०२.१०
प्रऽदोधुवत् २.११.१७
प्रऽद्रोषम् १.१९१.५
प्रऽधनस्य १.१६९.२
प्रऽधने १.११६.२; १०.१०२.५
प्रऽधनेषु १०.१५४.३
प्रऽधन्यासु १०.९९.४
प्रऽधयः १.१६४.४८
प्रऽधावति १०.१५४.१
प्रऽधिम् १०.१०२.७; १३८.६
प्रधी इवेति प्रधीऽइव २.३९.४
प्रधीन्ऽइव ४.३०.१५
प्रनपादिति प्रऽनपात् ८.१७.१३
प्रऽनयन्त १०.४.५
प्रऽनयसि १.१२९.१
प्रऽनियाथ ३.८.११
प्रऽनीतम् १.११७.१७
प्रऽनीतयः ६.४५.३; ८.१२.२१
प्रऽनीतिः ६.४८.२०; ८.६८.११; १०.६९.१
प्रनीतिऽभिः १०.१०४.५
प्रऽनीतिषु १.११४.२; ८.६.२२
प्रऽनीती १.९१.१; ३.५१.७; ४.४.१४; ७.२८.३; ३२.१५
प्रऽनीतौ २.२७.५; १३; ३.१५.१
प्रनेतरिति प्रऽनेतः ७.४१.३
प्रनेतरिति प्रऽनेतः २.२८.३; ३.३०.१८; ८.२४.७; ४६.१
प्रऽनेता २.९.२; ३.२३.१; ८.१९.३७
प्रऽनेतारः १.६९.५; ५.६१.१५; ७.५७.२
प्रऽनेतारम् ८.१६.१०
प्रऽनेनीः ६.२३.३
प्रऽनेषत् २.२०.३
प्रऽनोदम् १०.१६५.५
प्रऽन्यः ३.३८.२
प्रऽपतेत् १०.९५.१४
प्रऽपथिन् ६.३१.५
प्रपथिन्ऽतमम् १.१७३.७
प्रऽपथी ८.१.३०
प्रऽपथे १०.१७.४; ६[२]; ६३.१६
प्रऽपथेषु १.१६६.९
प्रऽपदाभ्याम् १०.१६३.४
प्रऽपदैः ६.७५.७
प्रऽपश्यन्तः १०.१२०.५
प्रऽपश्यमानः १०.१२४.२
प्रऽपा १०.४.१
प्रऽपित्वम् ३.५३.२४; ५.३१.७
प्रऽपित्वात् १०.७३.२
प्रऽपित्वे १.१०४.१; १३०.९; १८९.७;

प्राचीनम् १.१८८.४; २.२७.११; ७.७६.३; ९.५.४; १०.३७.३; ११०.४; ७
प्राचीनऽरश्मिम् १०.३६.६
प्राचीनान् २.१७.५
प्राचीनेन १.५४.५
प्राचीम् ७.६७.५; ९९.२; ८.१०१.६
प्राचैः १.८३.२
प्राञ्चः १.११०.२; ३.७.७; ५.४५.५; १०.१८.३
प्राञ्चम् १.१८.८; ३.१.२; १०.४६.४; ६६.१२; ८७.९; १०१.२; १३५.३
प्राणः १.६६.१; ३.५३.२१
प्राणतः १.१०१.५; १०.१२१.३
प्राणनम् १.४८.१०
प्राणम् १०.५९.६
प्राणात् १०.९०.१३; १८९.२
प्राणिति १०.१२५.४
प्रातः १.१६.३; ५८.९; ६०.५; ६१.१६; ६२.१३; ६३.९; ६४.१५; १२५.३; ३.४१.२; ५२.१; ५.१.२; १८.१; ६९.३; ७६.३; ७७.१; २; ७.४१.१[५]; ८.८०.१०; ९४.६; ९.९३.५; १०.४०.३; ४२.५; ८८.६; १५१.५
प्रातःऽइत्वः १.१२५.२
प्रातःऽइत्वा १.१२५.१
प्रातःऽजितम् ७.४१.२
प्रातःऽयावानः १.४४.१३
प्रातःऽयावानम् १०.४०.१; ४१.२; ६३.१४
प्रातःऽयावाना २.३९.२; ५.७७.१
प्रातःऽयाव्णः १.४५.९
प्रातःऽयुजम् १०.४१.२
प्रातःऽयुजा १.२२.१
प्रातःऽसावः १०.११२.१
प्रातःऽसावे ३.२८.१; ५२.४
प्रातरित्तिं १.१२५.१; २.१८.१; ४.३५.७; ७.४१.१; ८.२२.१५; ९.९८.११
प्रातर्दनिः ६.२६.८
प्रातर्यावऽभिः ५.५१.३; ८.३८.७
प्राता ७.१६.८
प्रायेऽप्राये २.१८.८
प्रायोगाऽइव १०.१०६.२
प्रावर्गम् ८.४.६
प्रावृतस्य १.१६२.२
प्रावृताः १०.८२.७
प्रावृषि ७.१०३.३; ९
प्रावृषीणम् ७.१०३.७
प्रावेपाः १०.३४.१
प्राशव्यान् ८.३१.६
प्राशुषाट् ४.२५.६
प्राशूः १.४०.१
प्राशूनाम् ८.३२.१६
प्रासि १.४२.९
प्रासि ८.१.२३
प्रियऽउस्रियस्य १०.४०.११
प्रियः १.२६.७; ७५.४; ९१.३; १२८.७; १४३.१; १६२.२०; ३.३२.१२; ४.१७.१९; २५.५[४]; ५.१.९; ३७.५[२]; ५१.४; ६.१.६; २.७; ७.२०.८; ६८.५; ७३.२; ८८.६; ८.१९.३१; ६४.११; ८७.१; ९८.४; ९.७.६; २५.३; ५२.२; ६३.२३; ६४.१०; २७; ७२.४; ७९.५; ८५.२; ८८.८; ९६.९; ९७.३; १०७.६; १३; १०.१६.८; २१.५; २५.१०; ४५.१०[२]; ५६.१; १२३.५
प्रियऽक्षत्राः ८.२७.१९
प्रियऽजात ८.७१.२
प्रियऽतमम् ५.७५.१; ९.३४.५
प्रियऽतमस्य ७.६२.४
प्रियऽतमे ७.९५.५
प्रियतमे इति प्रियऽतमे १०.१७.६
प्रियऽधामाय १.१४०.१
प्रियम् १.१३.३; १८.६; २५.१७; ३१.१७; ७१.९; ७५.२; ११२.२१; १२८.८; १४२.४; १५१.१; १५२.४; १५४.५; १६२.२; २.४.३; २०.६; ३.५.५; ७.७; २३.३; ४.२.८; ५.८; ४५.३; ४९.१; ५२.७; ५.५.३; १९.४; २३.३; ४२.२; ८२.२; ८५.१; ६.१६.४२; ४४.१६; ४८.१; ५१.१; ५३.६; ६८.९; ७५.३;

बाहू इति १.९५.७; १०२.६; १६३.१; १९०.३; ३.५१.१२; ४.५३.३; ४; ५.४३.४; ६.४७.८; ७१.१; ५; ७.४५.२; ७९.२; ८.६१.१८; ७७.११; १०.९०.११; १२; १०२.४; १२१.४; १४२.५
बाहून् २.१४.४; १०.८७.४
बाह्वोः १.५१.७; ५२.८; ६३.२; ८०.८; २.११.४; ६; २०.८; ३६.५; ३.४४.४; ४.२२.३; ५.१६.२; ५७.६; ६४.१; ६.२३.१; ४६.१४; ५९.७; ७.२५.१; ८४.१; ८.९६.३; ५; १०.५२.५; १५३.४
बिभय ८.४५.३५
बिभर्ति १.१६४.४; ७.३४.७; ९.१०९.१४
बिभर्ति ४.५०.७
बिभर्ति १.१०५.४; ३.५१.५; ५५.२२; ५६.२; ५९.८; ५.२.१; ७.४.५; ३३.१४; ८७.४; ८.२९.३–५; ९.८३.३; ९५.४; १०.४.३; २७.१६; ३१.८; १२३.५; १३६.१; १४४.२; १७७.२
बिभर्मि १०.३३.९
बिभर्मि १०.४४.९; १२५.१; २
बिभर्षि ६.५३.८; १०.१३४.६
बिभर्षि १.५५.८; २.३३.१०; ५.२.२; ३.२; ८४.१; ८.१.३४; १०.८४.६; १५३.४
बिभाय १.८४.१७; ५.६०.३; ८३.२
बिभित्सन् १०.६१.१३
बिभिदुः ४.१६.६
बिभिदुः १.८५.१०; ६.६५.५
बिभीतन ८.६६.१५
बिभीयात् १.४१.९
बिभीवान् १०.१०५.३
बिभ्रुतः ३.४६.५; ५.४७.५; ८.४०.४
बिभ्रुतः १.१८५.१; १०.६४.१४; ८८.१६
बिभ्रुताम् ६.७५.४
बिभ्रुथ १०.३०.१२
बिभ्रुथ १.३९.१०; ८.२०.२६
बिभ्रुथः ५.६४.६
बिभ्रुथः ५.६२.६
बिभ्रुमसि १०.१४८.२
बिभ्रुयात् १०.१०.९
बिभेद २.१४.६; ३.३४.१०; ८.९३.२; १०.८९.७
बिभेद ८.६.६; १०.६८.४
बिभ्यत् १०.३४.१०; ५१.४
बिभ्यतुः १.९५.५
बिभ्युः १.९४.११
बिभ्युषः ६.२३.२
बिभ्युषा ९.७७.२
बिभ्युषी ४.३०.१०
बिभ्युषे १.३९.७
बिभ्रत् १.२५.१३; १०३.४; ११४.५; १६४.१०; ३.५५.९; ४.१६.१४; २२.१; ५.३०.५; ६.२०.९; २३.१; ७.३३.१४; ९.१४.१; ४४.१; ९६.१९; १०.५३.९; ११३.३; १२३.७
बिभ्रतः १.४५.८; १२२.१३; १६६.२; ६.५५.६; ७.७४.४; १०३.६; ८.६५.४; ९.६७.२९; १०.५७.६; ६०.१; ६७.१०; ९४.६
बिभ्रतम् ३.५७.३; ९.४८.१; १०८.११; १०.३७.८; ११३.६
बिभ्रता १.४७.३; ६; ५.७३.२
बिभ्रति ६.१६.४०
बिभ्रति १.१०२.२; ५.४७.४
बिभ्रती १.१००.१६; ११३.१२; १६४.१७; ३.३०.१४; ५.५६.८; ७.७७.२
बिभ्रती इति ३.५४.८
बिभ्रतीः २.१३.२; ९.९९.४; १०.३०.१३
बिभ्रते ३.१०.५
बिभ्रतौ ५.६४.७; ७५.३
बिभ्रमाणाः १०.३१.६
बिलम् १.११.५; ३२.११
बिलैः २.३५.१२
बिसखाःऽइव ६.६१.२
बीजम् ५.५३.१३; १०.८५.३७; १०१.३
बीजम्ऽइव १०.९४.१३
बीभत्सुः १.१६४.८
बीभत्सुवः १०.१२४.८

बीभत्सूनाम् १०.१२४.९
बीभयत् १.८०.१२
बीभिषथाः ८.७९.८
बीरिटे ७.३९.२
बुद्बुदऽयाशवः १०.१५५.४
बुधन्त १०.६१.१२
बुधन्त ७.९.४; ७८.५
बुधानः ४.२३.८; ७.६८.९
बुधानाः ४.५१.८
बुधि १.१३७.२
बुध्नः १.२४.७; ९६.६; ३.५५.७; १०.१११.८; १३५.६; १३९.३
बुध्नम् १.५२.६; ९५.८; ९; ४.१९.४
बुध्नात् १.१४१.३; १०.८९.४
बुध्ने २.२.३; ३.३९.३; ६१.७; ४.१.११; १७.१४; ७.३४.१६; १०.७७.४
बुध्नेषु १०.९३.५
बुध्न्यः १.१८६.५; २.३१.६; ५.४१.१६; ६.४९.१४; ५०.१४; ७.३४.१७; ३५.१३; ३८.५; १०.६४.४; ६६.११; ९२.१२; ९३.५
बुध्न्या ७.६.७; ५६.१४
बुध्न्येन ४.५५.६
बुध्यध्वम् १०.१०१.१
बुध्यमानाः ५.३.६
बुन्दः ८.७७.११
बुन्दम् ८.४५.४; ७७.६
बुबुधानः ७.४४.३
बुबुधानाः ४.१.१८; ५.३०.२
बुबोधः ७.३७.६
बुबोधति १०.३२.१
बुबोधथ १०.६४.१३
बुभुज्महे ८.६७.१६
बुभुज्रिरे १.१३८.३[२]
बुभूषन् १.३२.७
बुसम् १०.२७.२४
बृबत्ऽउक्थम् ८.३२.१०
बृबुः ६.४५.३१
बृबुम् ६.४५.३३

बृबूकम् १०.२७.२३
बृसयस्य १.९३.४; ६.६१.३
बृहत् १.७.१; ९.७; ८; १०; ४४.२; ४५.८; ४६.१; ५२.९; ५६.४; ७४.९; ७५.५; ९१.३; ९३.१०; १२५.२; १३६.१; २[२]; १५१.४; १६०.५; २.१.१६; २.१३; ७.४; ११.२१; १३.१३; १४.१२; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; २३.१९; २४.१६; २७.७; १७; २८.११; २९.७; ३३.१५; ३५.१५; ३९.८; ४०.६; ४२.३; ४३.३; ३.२.१४; ३.११; १०.५; १८.४; २७.१५; २९.८; ३७.१०; ५३.१५; ४.५.१; ६; ५.१.१०; १०.४; १६.१; १७.३; १८.५; २५.७; ८; २७.६; ३६.४; ३९.३; ४३.१५; ४४.६; ५५.१; २; ५७.८; ५८.८; ६४.६; ६६.५; ६७.१; ६८.१; ७३.१०; ७९.७; ८५.१; ८६.६; ६.१६.११; १२; २१; १७.४; ७; २८.६; ३०.२; ५०.३; ७५.१५; ७.२.१; ८.४; ४५.४; ५८.३; ६२.१; ७२.४; ८४.२; ९४.४; ९६.१; ८.९.१७; १५.२; ७; १८.२०; २०.६; २३.११; २५.४; ३१.७; ५६.५; ६५.९; ११; ६६.१; ७२.६; ७४.९; ८९.१; ४; ७; ९८.१; १०१.१४; १०२.१; ९.५.५; २०.४; ४४.६; ५६.१; ६१.१६; ६२.१०; ६६.२४; ८३.५; ८६.४०; ४८; ८८.८; ९७.४०; ९८.८; १०७.१५[२]; १०८.८; ९; १०.१०.६; १४.१६; २१.८; ३५.६; १०; ६३.४; ६४.१५; ६५.१; ५; ६६.४; ७०.७; ९४.४; ९६.१०; १००.८; १७०.१–३; १७६.१; १८१.२
बृहतः १.२५.९; ५२.१३; ५४.४; ५९.५; ७१.२; १५१.४; २.२.७; १६.२; ३.२.८; ३.७; १५.१; ४; १६.६; ३०.१८; ५३.५; ६; ४.१.१७; १०.२; १२.३; १७.६; २१.४; २७.४; ३०.१४; ५.४३.११; ५९.७; ७६.४; ८१.१; ८७.३; ६.२.४; १३.२; ६५.२; ७.११.४; १८.२०; ६१.३; ८.१.१८; २५.७; ३२.३; ९.७५.१;

११३.५; १०.३.२; ४[२]; ५; ७.३; २७.२१; २८.६; ३४.१; ३७.८; ५८.९; ९८.१२

बृहता १.४८.१; १०; १६; ३.२१.४; २३.२; ५३.१; ४.५.१; २८.२; ५.२.९; ११.१; ६.१.७; १९.१३; ७.३३.४; ७८.१; ८.२३.५; ९.९७.३६; १०.३.१; ८.१

बृहताम् १०.३६.११

बृहती १.५७.५; ११३.१९; १२३.२; ३.३३.५; ५.४३.८; ८०.२; ६.४९.४; ६१.१३; ७.९९.६; १०.१३०.४

बृहती इति १.७२.४; १४४.६; १८५.६; ४.५६.१; ७.३५.३; ५३.१; ८७.२; ९.५.६; १०.३६.१; ११०.६

बृहती इवेति बृहतीऽइव १.५९.४

बृहतीः ३.१.५; २२; ५१.१; ५.४३.१; ६.१.१२; ८.५२.९; १०; ९.१३.४; ४२.६; ४९.१; ७२.९; ८७.९; ९६.२२; ९७.२५; १०.१२१.७; ९; १३४.३

बृहतीः १०.११०.५

बृहतीभिः ४.४१.११

बृहतीभ्यः ८.३.१९

बृहतीम् ५.४३.६; ८०.१; ६.२२.१०; १०.२७.१७; ६७.१; ७४.४

बृहत्ऽउक्थः ५.१९.३; १०.५६.७

बृहत्ऽउक्थात् १०.५४.६

बृहत्ऽउक्षः ३.२६.४

बृहत्ऽउक्षा १०.६९.७

बृहते १.९.१०; ५४.३; ५७.१; १३६.६; ३.३४.४; ४.३.८; ५.१२.१; ४३.५; १५; ४७.७; ६.६८.९; ८.८९.३; ९८.१; १०३.८; ९.१५.२; ६९.१०; ९६.४

बृहत्ऽकेतुम् ५.८.२

बृहत्ऽगिरयः ५.५७.८; ५८.८

बृहत्ऽदिवः ५.४३.१३; १०.१२०.८; ९

बृहत्ऽदिवस्य ४.२१.५

बृहत्ऽदिवा २.३१.४; ५.४१.१९; ४२.१२; १०.६४.१०

बृहत्ऽदिवाः १०.६६.८

बृहत्ऽदिवेषु २.२.९; ४.३७.३; ९.७९.१

बृहत्ऽदिवैः १.१६७.२

बृहत्ऽभानुः १.२७.१२

बृहत्ऽभिः २.११.१५; ४.५६.४; ६.१.११; ४८.७

बृहत्ऽभ्यः ४.५४.५

बृहत्ऽमते ९.३९.१

बृहत्यै ४.३.७

बृहत्ऽरथम् १.३६.१८; १०.४९.६

बृहत्ऽरथा ५.८०.२

बृहत्ऽरयिम् ६.४९.४

बृहत्ऽरये १.५७.१

बृहत्ऽरेणुः ६.१८.२

बृहत्ऽशरीरः १.१५५.६

बृहत्ऽश्रवसः १०.६६.१

बृहत्ऽश्रवाः १.५४.३

बृहत्ऽसुम्नः ४.५३.६

बृहद्भानो इति बृहत्ऽभानो १.३६.१५; ८.८९.२; १०.१४०.१

बृहन् २.१.१२; ३.५२.४; ६.२४.३; ८.१५.९; ४५.२; ७४.४; ९.७५.१; १०.१.१; ३; २७.१४

बृहन्तः २.११.१६; ३.१.१४; ४३.६; ८.४४.४; ८८.३; ९.९१.५

बृहन्तम् १.२.८; ३५.४; ९२.८; ११७.२३; १६४.५२; २.४.८; १०.४; १५.२; ३.३.२; ३२.७; ४.४४.६; ५.२६.३; ४३.१२; ६८.५; ६.१.३; ६.७; १५.१९; १९.२; १०; ४९.१०; ७.१.२४; १०.४; ७७.६; ८६.१; ८८.१; ५; ९९.२; ८.४२.२; ९.९७.२१; १०.२८.९; ४७.३; ८; ८८.३; १३; ९१.१५

बृहन्ता ६.४७.८; ७.४५.२; ९९.६

बृहन्ता ४.४१.११

बृहन्ताऽइव १०.१०६.९

बृहस्पतये ९.८५.६

बृहस्पतिः १.६२.३; ८९.६; ९०.९; १०५.१७; १३९.१०; १६१.६; १९०.२; ७; ८; २.२३.१३; ४.५०.१; ४; ५; ५.४६.५; ६.७३.१; २; ३[१]; ७.९७.२; ४; ७;

ब्रवीमि १.८४.१९; ९.८२.४

ब्रवीमि ३.५४.१०; १०.१८.१; ७९.४; ११७.६

ब्रवीषि ४.४२.७

ब्रवैते इति ६.२५.४

ब्रह्म १.१०.४; ३७.४; ४७.२; ६२.१३; ७५.२; ८०.९; ८८.४; १०५.१५; ११७.१०; २५; १२९.४; १५२.५; ७; १५७.२; १६५.११; २.१२.१४; १८.७; २०.५; ३४.७; ३७.६; ३९.८; ४१.१८; ३.८.२; २९.१५; ४१.३; ५३.१२; १३; ४.६.११; १६.२०; २१; १७.२१; १९.११; २०.११; २१.११; २२.१; ११; २३.११; २४.११; ५.२९.१५; ४२.२; ८५.१; ६.१६.३६; १७.३; १३; २३.५; ३५.१; ३; ३८.३; ४; ५२.२; ७५.१९; ७.२२.३; २४.४; २८.१; २; ३१.११; ३५.७; १४; ३६.१; ३७.४; ६१.६; ९७.९; १०३.८; ८.१.३; ३.९; ५.१३; ६.९; २४.१; ३२.१७; २७; ३३.१३; ३५.१६; ३७.१; ५२.९; ५३.८; ६३.२; ६९.९; ८९;३; ९०.३; ९.६७.२३; ७१.१; ८६.४१; १०.४.७; १३.१; २२.७; ३०.११; ४९.१; ५०.६; ६१.१; ७; ६५.११; १४; ६६.१२; ८०.७; ८९.३; ११४.८; १२०.८; १४१.६; १४८.४

ब्रह्मऽकाराः ६.२९.४

ब्रह्मऽकिल्बिषे १०.१०९.१

ब्रह्मऽकृतः ७.३२.२; १०.५०.७; ५४.६; ६६.५

ब्रह्मऽकृता ३.३२.२; ७.९.५

ब्रह्मऽकृतिम् ७.२८.५; २९.२; ५; ३०.५

ब्रह्मऽकृतै ८.६६.६

ब्रह्मऽचारी १०.१०९.५

ब्रह्मऽचोदनीम् ६.५३.८

ब्रह्मऽजाया १०.१०९.३

ब्रह्मऽजायाम् १०.१०९.२; ६; ७

ब्रह्मऽजूतः ३.३४.१; ७.१९.११

ब्रह्मणः १.१८.४; ३८.१३; ४०.३; ५; २.२३.१७; १९; २४.२; ४; ५; ८; ९; ११; १३–१६; २५.१–५; २६.२–४; ३.२९.१५; ५.४६.३; ६.५२.३; ७५.१७; ७.४१.१; ४४.१; ९७.३[२]; ८.२७.१; ९.९७.३४; १०.५३.९; ६५.१; ६७.७; ७२.२; १७३.३

ब्रह्मणः २.१२.६; १०.२८.११

ब्रह्मणः १.१८.१; ३; ५; ४०.१; २.१.३; २३.१; ५; ९; ११; ६.१६.३०; ७.९७.९; ९.८३.१; १०.१५५.२; १६४.४; १७४.१

ब्रह्मणा १.२४.११; ३१.१८; ८२.६; ८४.३; ९३.६; ११७.११; १२४.१३; १६२.१७; २.२.७; १०; १६.७; १७.३; २४.३; १५; ३.१८.३; ३५.४; ५१.१२; ४.३६.७; ५.४०.६; ४२.४; ६.३५.५; ५०.६; ६५.५; ७.३३.३; ४; ११; ९.११३.५; १०.५०.४; १२०.५; १६२.१; २

ब्रह्मणाम् २.२३.१; २

ब्रह्मणाम् ८.३२.१६

ब्रह्मणि ६.२३.१

ब्रह्मणि १.१०८.७

ब्रह्मणे १.११३.१९; ४.४.६; ७.१३.३; ६०.११; ९७.८; ९.९६.१०; १०.३०.१; ११२.८; १२२.२

ब्रह्मणे १.१०१.५; ४.५०.९

ब्रह्मण्यतः २.२०.४; ६.२१.८

ब्रह्मण्यते ४.२४.२

ब्रह्मण्यन्तः २.१९.१; ८; ३४.११

ब्रह्मण्या ८.६.३३

ब्रह्मऽद्विषः २.२३.४; ५.४२.९; ८.४५.२३; ६४.१; १०.३६.९; १६०.४; १८२.३

ब्रह्मऽद्विषम् ६.५२.२

ब्रह्मऽद्विषे ३.३०.१७; ६.२२.८; ५२.३; ७.१०४.२; १०.१२५.६

ब्रह्मन् ३.१३.६; ७.२९.२

ब्रह्मन् ७.३३.११

ब्रह्मपुत्रःऽइव २.४३.२

ब्रह्मऽप्रियम् १.८३.२; १५२.६

ब्रह्मऽब्रह्म ९.७७.३

ब्रह्मऽभिः ८.४.२
ब्रह्मऽभिः १.३३.९
ब्रह्मऽभ्यः ८.४५.३९; ७७.५; १०.८५.२९
ब्रह्मऽयुजः १.१७७.२; ८.१.२४
ब्रह्मऽयुजा ३.३५.४; ८.२.२७; १७.२
ब्रह्मऽवाहः १.१०१.९; ३.४१.३; ६.२१.६
ब्रह्मवाहःऽतमम् ६.४५.१९
ब्रह्मऽवाहसम् ६.४५.७
ब्रह्मऽवाहसे ५.३४.१; ३९.५; ६.४५.४
ब्रह्मऽसंशिते ६.७५.१६
ब्रह्मऽसवैः ९.६७.२४
ब्रह्मा १.८०.१; १५८.६; १६४.३५; २.१.२; ३; ४.९.४; ५०.८; ५८.२; ५.४०.८; ७.७.५; ८.७.२०; १६.७; ३१.१; ३३.१९; ६४.७; ९.९६.६; ११२.१; ११३.६; १०.५२.२; ७१.११; ८५.३४; ३५; ९१.१०; ११७.७
ब्रह्माऽइव ८.९२.३०
ब्रह्माणः १.१०.१; ५.३१.४; ३२.१२; ७.४२.१; ८.१७.३; ९६.५; १०.८५.३; १६
ब्रह्माणः ५.२९.३
ब्रह्माणम् ६.४५.७; १०.७७.१; १०७.६; १२५.५; १४१.३
ब्रह्माणाऽइव २.३९.१
ब्रह्माणि १.३.५; ६; ५२.७; ६१.१; १६; ६३.९; ८०.१६; १६५.२; ४; १४; १७७.४; ५; २.५.३; ३४.६; ३.५१.६; ४.३.१५; ५.२.६; ३१.१०; ७३.१०; ७४.३; ६.२३.६; ४०.४; ४७.१४; ६९.४; ७; ७.१.२०; २५; १८.४; १९.६; २२.७; ९; २३.१; ३; २९.२; ४३.१; ६१.२; ७०.५–७; ७१.६; ७२.३; ४; ८३.४; ८४.३; १०४.६; ८.१७.२; ३६.७; ४०.५; ६२.४; ६६.११; ९०.१; ९८.८; १०.८९.१६; १०४.६
ब्रह्मीः ९.३३.५
ब्राह्मणः ८.५८.१; १०.८८.१९; ९०.१२; ९७.२२
ब्राह्मणस्य १०.१०९.४
ब्राह्मणाः १.१६४.४५; ७.१०३.१; १०.७१.८
ब्राह्मणात् १.१५.५; २.३६.५
ब्राह्मणान् १०.१६.६
ब्राह्मणासः ६.७५.१०
ब्राह्मणासः ७.१०३.७; ८; १०.७१.९
ब्रुवते ५.८७.२
ब्रुवते १.३७.१३; ७७.३; १३४.२; ८.६.३; २७
ब्रुवन् ९.६३.९
ब्रुवन्तः ५.१२.५; ८.४८.१
ब्रुवन्ति ७.२६.३
ब्रुवन्ति १०.२७.३
ब्रुवन्तु १.४.५; ७४.३; १०.१५.५; ६३.१
ब्रुवाणः ३.५९.१; ६.३८.२; ७.३६.२; ९.९७.७; १०.८.७
ब्रुवाणा ५.४७.१
ब्रुवाते इति ३.५४.७
ब्रुवीत ५.४९.२
ब्रुवीमहि ८.२१.११; ९२.३२
ब्रुवे १.१७९.५; १८५.७; २.३०.११; ३.२.३; ३७.५; ४.५१.११; ५.६१.८; ६५.३; ७.३१.६; ४४.३; ८.२२.१३; २५.२१; ४४.३; ६७.१०; ८३.९; ९८.१२; १०.३५.७; ६६.७; ९७.४
ब्रूत १०.५२.१
ब्रूयात् १०.१३५.५
ब्रूषे १०.९१.११
ब्रूहि १.३५.११; ६१;१३; ११४.१०; १०.८७.८

भ

भंससः १०.१६३.४
भक्तम् १.१२७.५
भक्तये ८.२७.११
भक्तेन ७.८१.२
भक्त्वाय १०.१०९.७
भक्षः ६.२८.५; १०.३४.१
भक्षणम् १.११०.३
भक्षत् ९.६७.१०–१२
भक्षत ८.९९.३

भक्षम् ८.९२.२३; १००.२; ९.८३.४; १०.११६७.४
भक्षार्थ १.१८७.७
भक्षि ७.४१.२
भक्षीमहिं ७.९६.६; ९८.६; ८.४८.७; ९.८.९
भक्षीय १.८१.६; ४.२१.१०; ५.५७.७
भक्षैः १०.१४८.३
भग ३.५६.६; ७.४१.३[५]
भग ७.४१.५[२]
भगः १.२४.४; ६२.७; ९०.४; १४४.३; १६३.८; २.१.७; ११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; २७.१; ३१.४; ३.३०.१८; ३६.५; ४९.३; ५४.२१; ५५.१७; ४.३०.२४; ५५.१०; ५.१६.२; ३३.५; ४१.४; ४२.५; ४६.२; ६; ४८.५; ४९.३; ५१.११; ८२.३; ६.१३.२; २८.५; ४९.१४; ५०.१३; ५१.११; ७.१५.११; १२; ३५.२; ३८.१; ४०.२; ४१.५; ६६.४; ८.१८.३; १९.१६; ३१.११; ५४.५; ९.८१.५; ९७.५५; १०१.७; १०८.१४; १०.३१.४; ३९.३; ६४.१०; ६६.१०; ८५.२३; ३६; ९२.४; ९३.४; ७; १४१.२; १५९.१
भगःऽइव ३.२०.४; १०.६८.२
भगत्तिम् ९.६५.१७
भगऽभक्तस्य १.२४.५
भगम् १.१४.३; ४४.८; ८९.३; ९१.७; १३४.५; १३६.६; १४१.१०; ११; २.१७.७; ३८.१०; ३.२०.५; ३०.१९; ५.७.८; ४२.१; ४६.३; ४९.१; ६.५०.१; ५१.३; ७.३६.८; ३८.६[२]; ३९.४; ४१.१; २[२]; ६; ४४.१; ८.६१.५; ७; ९.७.८; १०.५; ९७.४४; १०.११.६; ३५.१०; ११; ३९.१०; ४२.३; ६३.९; १२५.२
भगम्ऽइव १.१४१.६
भगऽवती १.१६४.४०
भगवत्ऽतरः १०.६०.१२
भगऽवन्तः १.१६४.४०; ७.४१.४; ५
भगऽवान् ७.४१.५; १०.६०.१२
भगस्य १.१२३.५; १३६.२; ३.६२.११; ४.५५.५; ५.८२.१; १०.१५१.१
भगस्यऽइव ३.५४.१४; ८.१०२.६
भगाय ४.३.५; ५.४१.११; ९.४४.५; ६१.९; १०९.१; १३
भगे २.३४.८
भगेऽअविता १०.१०६.८
भङ्गम् ९.६१.१३
भङ्गुरऽवतः ७.१०४.७; १०.७६.४; ८७.२३
भङ्गुरऽवताम् १०.८७.२२
भङ्धि १०.८७.४
भज १.२७.५; ४३.८; ८१.६; १०४.६; १२१.१५; ७.२७.१; ४६.४; ९.४.५; १०.४५.१०[२]; ८५.२९; ११२.१०
भजतन ७.५६.२१
भजतम् १०.१०६.९
भजति ४.५४.१
भजति ५.३४.५; ७
भजते ५.४४.१२
भजते १.१२३.४; ३.३०.७; ९.८६.१२
भजन्त १.६८.२; ५.७९.७; १०.१५.३
भजन्त ८.४.२१[२]; १०.१०८.८
भजन्ति १०.११४.१०
भजन्ते १.१२५.६; १०.१०७.२
भजस्व ४.३२.२१; १०.८४.२
भजाति २.२६.१
भजानि १०.२७.१०
भजाम १०.१०८.९
भजामहे १.१८७.९
भजामहे १.१५६.३
भजामि १०.४८.१
भजेमहि १.१५७.२; ७.३२.७; ८.४०.६
भजेऽरथस्य १०.६०.२
भद्रः १.६७.१; ९१.५; ८.१९.१९[२]; १०.३.३; ३२.३
भद्रऽकृत् ८.१४.११
भद्रऽजानयः ५.६१.४
भद्रम् १.१.६; ८९.८[२]; ९४.१४; १०८.३; ११३.९; २०; ११५.२; १९०.५;

२; ३८.४; ३९.१; २; ६.१६.२९; ३६; १९.६–८; २२.३; ४३.१; ४; ४४.१३; ४६.५; ७; ७.१५.११; २०.७; २५.२; ३२.७; २४; २६; ७७.४; ८१.५; ८.१.४; १३.५; १९.१५; २१.१६; २४.३; ४; २५; ३२.८; ३३.१२; ३४.१५; ४५.१५; ४०–४२; ४६.१९; ६०.१८; ६१.६; ६६.७; ७७.८; ७८.१–३; ८१.६; ७; ८९.४; ९३.१९; २८; २९; ९८.१०; ९.४.१०; १९.१; २०.४; २३.३; २९.६; ४०.४–६; ५७.४; ५९.१; ६०.४; ६१.६; २६; ६३.१८; ६४.२६; ६५.१८; ८७.६; १००.२; १०१.९; १०३.१; १०६.४; १०.२१.४; ४२.१; ३; ८३.३; ११३.१०; १४८.१; १५६.३; १८०.१; १९१.१

भरः ६.२६.४; १०.१७१.२

भरणे १०.३१.६

भरत् १.१२१.१३; १७३.३; २.१९.५; ४.२६.४; ५; ५.३१.११; ४४.१३; ९.५२.१

भरत् १.६०.१; २.२०.६; ४.२६.६; ९.४८.३; ४; ९७.२४; १०६.३

भरत २.१४.१; ६; ७; ६.१६.४१; ८.६२.१; १०.१७६.२

भरत १.१३६.१; २.१४.२; ८; ३७.१; ३.१०.५; ५२.८; ५.४३.३; ७.४६.१; ८.१००.३; १०.४०.६; ७६.४; १००.२

भरतः ६.१६.४

भरतम् १.९६.३

भरतम् १.१०९.७

भरतस्य ३.५३.२४; ७.८.४

भरतस्य २.३६.२

भरताः ३.३३.११; १२; ७.३३.६

भरताम् १०.५९.८–१०

भरताय ५.५४.१४

भरति २.१६.२; ३.५५.४; ४.१६.१६; २२.४; १०.८७.१६

भरति १.१५२.३; ४.१७.९; १०.१३८.६

भरते १.१७३.२; २.२४.९; ८.१९.२३; ९.९४.३

भरते १.६४.१३; १०४.३[२]; २.२४.१३; २६.३; ५.३२.९; ७.२४.२; १०.४६.८; ७५.७; १४७.४

भरतेभ्यः ५.११.१

भरत्ऽवाजः १०.१८१.२

भरत्ऽवाजम् १.११२.१३; १०.१५०.५

भरत्ऽवाजाः ६.२५.९; ५०.१५

भरत्ऽवाजान् ६.४७.२५

भरत्ऽवाजाय १.११६.१८; ६.१५.३; १६.५; ३३; ३१.४; ४८.१३; ६३.१०

भरत्ऽवाजे ६.१७.१४; ४८.७

भरत्ऽवाजेषु १.५९.७; ६.१०.६; २३.१०; ३५.४

भरथ १०.९४.१

भरथः १.१५१.३; ३.६२.१

भरथः १.११२.२१

भरद्वाजऽवत् ६.६५.६

भरध्यै ६.६६.३; ६७.४

भरध्वम् १.६२.२; १२२.१; ३.६१.५; ५.४१.३; ५; ६.६६.९; ७.४.१; ५.१; १३.१; ३१.१०; ८.२०.९; १०.१११.१

भरध्वे ५.५९.४

भरन् १०.१३.२

भरन्त १.७०.५; ८.६.२

भरन्त १.७०.५. २.१३.२; ५.७३.८

भरन्तः १.१.७; ३.३६.७; ८.२१.१; १०.३५.१

भरन्ति १.१५१.८; १५३.१; २.१६.४; ७.९२.२; ८.१००.९

भरन्ति १.११५.५; ५.१.१०; ६.४४.२०; ९.७४.६; १०.७९.२; १०२.१०

भरन्ती २.५.६; ३.६.१; ३१.११; ८.९१.१; १०.९५.१०

भरन्तीः १०.३०.१३; ३५.५

भरन्ते ६.६७.७; १०

भरन्ते १.१०४.४; १७३.४; ३.५५.७; ५.११.४; ७.७२.४

भरम् १.११७.१८; ५.२९.८; ८.६६.१; १०.४४.५

भरमाणः ९.९७.१५; ११०.५

भरमाणस्य १.१४८.२
भरमाणाः १.१३५.३; ६; ७.२.४
भरसे ५.१५.४
भरस्व १.७९.१०
भरस्व ७.८८.१
भरऽहूतये १.१२९.२; ५.४८.४
भरऽहूतौ ८.६३.१२
भराणाम् ८.४०.३
भरात् ४.२.७
भराति १.१८०.२; ५.३.७
भराम १.९४.४
भरामसि ६.१६.४७; ८.६६.५; ११
भरामहे १.५३.१; ११४.१; २.२०.१; ४.५६.५; ८.८३.८; १०.३६.८
भरामि १.६१.२; ३
भरामि ८.१०२.१९
भराय १.१११.५; ३.५१.८; ४.२१.७; ६.१७.८; २३.९; ८.१३.३; ९.६.६; १६.५; ९७.६; १०६.२; १०.१००.२
भरासः ९.१०.२
भरित्रैः ३.३६.७
भरिभ्रत् २.४.४; १०.४५.७
भरिभ्रति १०.१२४.७
भरिषः ४.४०.२
भरीमऽभिः १.२२.१३; १०.६४.१४
भरे १.११२.१; १३२.१[२]; २; ३.३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.११; ३६.११; ३८.१०; ३९.९; ४३.८; ४८.५; ४९.५; ५०.५; ५.३६.५; ६.४५.१३; ७.१३.१; ८.१६.३; ९.९७.५८; १०.४९.१; ४; ५०.४; ८९.१८; १०२.२; १०४.११
भरे १.५७.१; १०२.१; १२६.१; १४३.१; २.१६.१; ५.१२.१; १५.१; ४२.१३; ५९.१; ६०.१
भरेते इति १०.७९.१
भरेऽभरे १.१००.२; १०२.४; ५.४३.२; ७.३२.२४; ८२.९; १०.६७.९
भरेमहि ९.७९.२
भरेरत १०.३६.९

भरेषु १.१००.१; १०९.८; २.२३.१३; ३.३७.५; ४.३८.४; ८.५३.७; ९.४७.५; १०.६३.९; १०७.११
भरेषुऽजाम् १.९१.२१
भर्गः १.१४१.१; ३.६२.१०; १०.६१.१४
भर्तवे ९.९७.५०
भर्ता १०.७४.५
भर्ता १०.२२.३
भर्ताऽइव ५.५८.७
भर्ति १.१७३.६
भर्ति ६.१३.३
भर्मणे १०.८८.१
भर्वति १.१४३.५
भर्वन् ६.६.२
भर्षत् ६.३८.१
भल १०.८६.२३
भलानसः ७.१८.७
भव १.३६.२; ५८.९[२]; ७३.४; ७६.३; ९१.१६; १७; १५६.१; १७१.६; १८९.२; ३.१०.८; १८.१; ४५.५; ४.४.३; १०.३; ५.५.४; ६.३३.५; ४६.३; ४७.७[२]; ७.७.१; ११.३; १७.१; ३०.१; ३२.७; २५; ८.१३.३; ४५.८; ७९.७; ९७.७; ९.३१.२[२]; ४; ८१.३; ९७.२५; १०.७.७[२]; ६९.५
भव १.१.९; १२.८; १५.१०; २२.१५; ३१.३; ४०.१; ५१.८; ७६.२; ७९.११; ८१.८; ९१.९; १०; १२; १३८.३[२]; १८७.२; ८; ९; १०[२]; ३.१७.३; २१.३; ३१.१८; ३७.६; ४.१.५; ३.१५; ४.५; ३२.१४; ५७.६; ५.२४.१; ६.१५.९; २५.७; ४५.२६; ४६.१०; ११; ५५.१; ७.१५.१४; ४१.५; ४६.२; ५४.१[२]; ९६.५; ८.४.१८; ४८.४; ९.१.३; ६१.२१; ८८.७; ९६.११; १०४.५; १०५.५; १०.१८.११; २५.७; ३३.३; ३७.१०; ५३.६; ६९.४; ७०.१; ८३.७; ८४.५; ८५.४३; ४४; ४६[३]; १२७.६; १४१.१; १४८.४

भासा २.४.५; ६.१.११; ४.६; १०.४; ७.५.४; १०.१; ८.२३.५; १०.३.१; ७७.५
भासांसि ६.४.३
भासाऽकेतुम् १०.२०.३
भासि १.५०.४; २.१.१०; २.२; ३.६.७; ६.६४.२; ९.९७.३२
भास्वती १.९२.७; ११३.४
भास्वन्तम् १०.३७.८
भाहि १.४८.९; ९५.११; ९६.९; ११३.१९; ३.१५.३; ६१.२; ६.१.११; १६.४५; ७.७७.५; १०.२.७
भिक्षते ७.३२.१७
भिक्षन्त ३.५६.७
भिक्षमाणः ३.६१.६; ९.७०.२
भिक्षमाणाः १.७३.६; ७; ४.४१.९; ७.६.६; १०.३; ९०.७; ९१.७; १०.३१.५
भिक्षमाणे इति ३.३३.२
भिक्षे १.१७१.१; २.२८.१
भिक्षेत १.१५२.६; ८.७.१५; १८.१
भित्वा १०.६८.७
भिदः १.१७४.८
भिदन्तः ४.३.११
भिनत् १.५२.५; ६२.३; १३०.७; १७४.८; २.११.२०; १५.८; ४.१७.३; ८.१.८; ३२.२५; ६९.१४; १०.६८.११
भिनत् १.५४.४
भिनत्सि ८.६०.१६
भिनदः १०.८९.१४
भिनदत् १०.४५.१०
भिनद्धि १.१९१.१५
भिन्दन् ४.५८.७; ७.१०४.२१
भिन्दन्तः ४.२.१६; ९.५३.१
भिन्दन्ति ५.५२.९
भिन्दानाः ६.२७.६
भिन्दुः १.११.४
भिन्धि ८.४४.११; ४५.४०
भिन्धि १०.८७.५
भिन्नम् १.३२.८
भियम् १०.८४.७
भियसम् २.२८.६; ९.१९.६; १०.१२०.२
भियसा १.५२.९; १०; ५४.१; ८०.११; ४.१७.२; ५.३२.९; ४०.७; ५९.२; ६.१७.९; २७.५; १०.१०८.२
भियसे ५.२९.४
भिया १.३७.८; ६१.१४; ६३.१; ८०.१४; १७१.४; ५.३६.३; ५७.३; ६०.२; ६.१४.४; ३१.२; ७.५.३; ६०.१०; ८.७.२६; १०.५१.६
भियानाः ४.२२.६; ६.९.७
भियाने इति २.११.९
भियै ८.७५.१३
भिषक् ९.११२.१; ३; १०.९७.६
भिषक्ऽतमम् २.३३.४
भिषक्ति ८.७९.२
भिषजः १.२४.९; ६.५०.७
भिषजा १.१५७.६; ८.१८.८; ८६.१; १०.३९.३; ५
भिषजाम् २.३३.४
भिषजौ १.११६.१६
भिषज्यतम् ८.२२.१०
भिषज्यथः ८.९.६
भीः १.३२.१४
भीःऽइव १०.१४६.१
भीतः १.३२.१४
भीताय ५.७८.६
भीते इति १०.५४.१; ५५.१
भीमः १.५५.१; ७०.६; ८१.४; ९५.७; १००.१२; १४०.६; १५४.२; १९०.३; ४.१६.१४; २०.६; ३८.८; ६.६.५; ७.१९.१; २१.४; ९.७०.७; ९७.२८; १०.१०३.१; १८०.२
भीमम् २.२३.३; ३३.११; ६.३१.५; ८.८१.३
भीमऽयुः ५.५६.३
भीमऽसंदृशः ५.५६.२
भीमस्य १०.९२.८
भीमा ६.३.३; १८.१०; १०.१०९.४
भीमाः २.३४.१
भीमानि ९.६१.३०

भृगूणाम् ३.२.४
भुज्जाति ४.२४.७
भुतिम् ८.६६.११; ९.१०३.१
भुत्याम् १.८४.१६
भुत्यै १०.२९.४
भुथे २.१४.४
भुमम् ८.६१.१२
भुमर्यः ३.६२.१
भुमात् ७.१.२२
भृमिः १.३१.१६; ४.३२.२
भृमिम् २.३४.१; ७.५६.२०
भुष्टिः १.५६.३
भुष्टिऽमता १.५२.१५
भेजाते इति ७.३९.१
भेजानासः ४.२९.५; १०.१५३.१
भेजिरे ७.१.९
भेजिरे ५.५७.५; १०.९४.८
भेजे ७.१८.१६
भेत् १०.६८.६
भेत् १.५९.६; १०४.८[२]; ७.१८.२०
भेत्ता ८.१७.१४
भेदति ८.४०.१०; ११
भेदति ५.८६.१
भेदम् ७.१८.१९; ३३.३; ८३.४
भेदस्य ७.१८.१८
भेदौ ९.११२.४
भेम १.११.२; ८.४.७
भेषजः २.३३.७
भेषजम् १.२३.१९; २१; ८९.४; ५.५३.१४; ८.९.१५; २०.२५; ७२.१७; १०.९.५; ७; १००.१०; १३७.३; ६; १७५.२; १८६.१
भेषजस्य ५.४२.११; ८.२०.२३
भेषजा १.२३.२०; ३४.६; ११४.५; २.३३.१२; १३; ७.४६.३; १०.९.६; ५९.९
भेषजानि ६.७४.३
भेषजीः १०.१३७.६[२]
भेषजेभिः १.१५७.६; २.३३.२; ४
भोगम् १.१६३.७; ३.३४.९; १०.७.२; ३४.३; ५९.६
भोगान् ५.२९.६
भोगैः ६.७५.१४
भोजः ८.७०.१३; १०.१०७.११; ११७.३
भोजते १.७२.८
भोजन् १.४४.५
भोजनम् १.८३.४; २.१३.२; ४; ६; २६.१; ३.४४.३; ५.३४.७; ८२.१; ७.६८.५; ७४.२; ८.१.३४; १०.२३.६; ४८.१
भोजना ४.३६.८; ७.१८.१५; १७; ९.८७.६; १०.४४.७
भोजनानि १.१०४.८; ५.४.५; ७.५.३; १९.६; १०.१३१.२
भोजनाय ३.३०.१४; ५.८३.१०
भोजम् २.१४.१०; १७.८; ४.४५.७; ६.२३.९; ८.३.२४; १०.४२.३; १०७.११[२]
भोजम् २.२८.९
भोजसे १.५५.३; ८.५१.३; ६५.३
भोजस्य ७.१८.२१; १०.१०७.१०
भोजाः ३.५३.७; १०.१०७.८[२]; ९[४]
भोजान् ४.५१.३; ५.५३.१६
भोजाय १०.१०७.१०[२]
भोजेषु ८.२५.२१; १०.१५१.२; ३
भोज्यम् ८.२१.८
भोज्या १.१२६.६; १२८.५[२]
भ्रमः ६.६.४
भ्रमाः ९.२२.२
भ्रमासः ४.४.२
भ्रशत् १०.१७३.१
भ्राजः १०.१७०.३
भ्राजत्ऽऋष्टयः १.३१.१; ६४.११; ८७.३; १६८.४; ५.५५.१; १०.७८.७
भ्राजत्ऽऋष्टयः २.३४.५
भ्राजत्ऽऋष्टिम् ६.६६.११
भ्राजते १०.२०.३
भ्राजते १.५६.३; ५.६२.७
भ्राजत्ऽजन्मानः ६.६६.१०
भ्राजन्तः १.५०.३; ५.१०.५; ८.४४.१७

भ्राजन्ती १.१६२.१५
भ्राजन्ते १.८५.४; ७.५७.३; ८.३४.१७
भ्राजन्ते १.४४.१२; ७.५५.२; ८.२०.११; १०.१४०.१
भ्राजमानः ७.६३.४; १०.८८.१६
भ्राजमानम् ९.५.१०
भ्राजसा १०.७८.२
भ्राजसे ९.१७.५
भ्राजा ९.९८.३
भ्राट् १०.१२३.२
भ्रातः १.१६१.१; ३; १७०.३; ३.५३.५; ६.५१.५
भ्रातरः १.१७०.२; ५.६०.५; १०.३४.४; ५१.६
भ्रातरम् ४.१.२; ५.३४.४; ८५.७; १०.७.३
भ्रातरा ६.५९.२
भ्रातुरिति ८.४३.१६
भ्राता १.१६४.१[२]; १९१.६; ६.५५.५; १०.१०.११; १२; ११.२; १६२.५; १८६.२
भ्राताऽइव १.६५.४
भ्रातुः ४.३.१३; ८.१.६; १०.५५.१; ९९.२
भ्रातृऽत्वम् ८.२०.२२; ८३.८; १०.१०८.१०
भ्रात्रम् ४.२३.६; २५.२
भ्रात्रा ४.१०.८
भ्रात्राय २.१.९
भ्राशयन् १०.११६.५
भ्राश्यानि १०.११६.५
भ्रियन्ते १.१४.४; ७.२१.२
भ्रियाते ५.३१.१२
भ्रीणन्ति २.२८.७
भ्रुवोः ४.३८.७
भ्रूणानि १०.१५५.२
भ्रेषते ७.२०.६

म

मँश्चतोः ७.४४.३
मंसते १.८४.१७; १८; ५.४६.४; ८.६२.११
मंसन्ते ७.३४.३
मंससे १०.२७.१०
मंसि ७.८८.२
मंसीमहि १.१३६.७; ६.१९.७; १०.२६.४
मंसीरत १०.३७.५
मंसीष्ट ७.३८.६
मंसीष्ठाः १.१७५.५
मंसै १०.११३.१०
मंहते १.११.३; ६.४५.३२; ८.५०.१; १०.६२.८
मंहते ९.१.१०; १०.६२.६
मंहना ३.३१.१७; ४.१७.१; ५.१०.२; १६.४; १८.२; ६१.१०; ६.६४.५; ६७.५; ७.८१.४; ८.२६.२४; ९.३७.६; ७०.२
मंहनाऽइव ४.१.६
मंहनेऽस्थाः १०.६१.१
मंहमानम् ८.२४.२२
मंहय ५.३८.१
मंहयत्ऽरयिः ९.५२.५; ६७.१
मंहयम् १०.४८.९
मंहयुः ९.२०.७
मंहसे ८.५२.६
मंहसे ४.३१.८; ८.६१.८; ९.८२.४
मंहिष्ठः ४.३१.२; ८.४.१८; १५.१०; १९.३६; ४६.२४; ८८.६; ९७.१३; ९.१.३; १०.१७२.२
मंहिष्ठम् १.३०.१; ५१.१; ६१.३; १३०.१; ५.३९.४; ६.४४.४; ८.१.२; १६.१; ९२.१; ९.१०२.६; १०.३३.४
मंहिष्ठऽरातिम् १.५२.३
मंहिष्ठस्य १.१४७.२
मंहिष्ठा ४.४१.७; ६.६८.२; ८.५.५; २२.१२; १०.१४३.६
मंहिष्ठाः १.१२१.१५
मंहिष्ठाभिः ८.२३.२३
मंहिष्ठाम् १०.१०४.५
मंहिष्ठाय १.५७.१; ८.१०३.८
मंहिष्ठासः ८.१.३०
मंहीयान् ९.६६.१७
मक्षः ४.४५.४; ७.३२.२

मक्षा १०.४०.६

मक्षिका १.११९.९; १६२.९

मक्षु १.२.६; ३९.७; ५८.९; ६०.५; ६१.१६; ६२.१३; ६३.९; ६४.१५; २.१३.१; ४.१६.१६; २१.३; ४३.३; ६.६६.५; ७.५६.१५; ८.२२.१०; २७.१०; ३१.१५; ३३.३; ६१.४; ८०.१०; ८१.९; ८८.२; ९.८८.७; ९३.५; १०.२२.११; ६१.९–११; २०; १४७.४

मक्षुजवःऽतमा ६.४५.१४

मक्षुऽतमस्य ८.१९.१२

मक्षुऽतमेभिः ९.५५.३

मक्षुऽभिः ८.२६.६

मक्षुऽमक्षु ३.३१.२०

मक्षुम्ऽगमाभिः ८.२२.१६

मक्षुयुऽभिः ७.७४.४

मखः १.६.८; १३८.१[2]; ६.७१.१; ९.२०.७; १०.११.६

मखम् ९.१०१.१३

मखस्य १.१३४.१; ३.३४.२; ८.७.२७; १०.१७१.२

मखस्यते ९.१०१.५

मखस्यन् ३.३१.७

मखस्यसे ९.६१.२७

मखस्युम् १०.७३.७

मखस्युवः ९.५०.२

मखस्युवम् ९.६४.२६

मखाः १.६४.११; ११९.३

मखाय ८.४६.२५

मखेभ्यः ६.६६.९

मघत्तये ४.३७.८; ५.७९.५; ८.२४.१०; ४५.१५; ७०.९; १०.१५६.२

मघऽदेयम् ७.६७.९

मघऽदेयाय १०.४२.२

मघम् १.११.३; १५१.९; ३.१३.३; ४.३२.८; ८.१४.४; २१.१७; ९.७५.५; १०.१४७.३

मघवत्ऽतम ८.५४.५

मघवत्ऽत्वस्य ६.२७.३

मघवत्ऽभिः ४.१६.१९

मघवत्ऽभ्यः १.५८.९; १२४.१०; २.३३.१४; ३५.१५; ६.१०.५; ४६.९; ७.१.२०; २५; ५.९; ७.७; ८.७; १६.९; २४.६; २५.६; ५८.३; ६७.९; ७४.५; ९५.३; ८.५.१२; ९.२०.४; ३२.६; ९७.५५

मघवत्ऽसु १.६४.१४; ९३.१२; १२३.१३; १४०.१०; ६.८.६; ७.३७.२; ८.५०.२; १०.३९.२; ९३.१४

मघऽवन् १.८२.१; ३; ४.३०.७; ८.२४.११; ३२.८; ६१.१३; ६२.१०; ६६.१३; ८९.५

मघऽवन् १.३३.१२; १५; ५२.११; ५४.१; ५७.५; ५८.९; ८४.१९; १०२.३[2]; ४; ७; १०; १०४.५; ८; १२१.१५; १२७.११; १३२.१; १३३.३; १६५.९; १७८.५; २.३६.५; ३.३०.५; १६; २१; ३१.१४; १९; ३२.१; ३६.१०; ४३.५; ४७.४; ५३.२; ४; ५; १४; २१; ६०.५; ४.१६.९; १९; १७.७; १८.९; २२.१०; २९.५; ५.२९.५; १३; ३०.७; ३१.६; ३३.२; ३६.३; ४; ४२.६; ६.१५.१५; २३.१; २७.३; ४४.१०; १७; १८; ४६.८; १०; ४७.९; ७.१८.२; १९.८; ९; २०.९; २२.३; ६; २७.२[2]; २९.१; ३; ४; ३२.७; १४; १९; २१; २३–२५; ३७.३; ४१.४; १०४.१९; ८.१.४; ३.१४; १७; १८; ४.४; १०; २४.१०; ३३.३; ११; ३६.२; ४५.६; ४६.११; ४९.९; १०; ५०.१०; ५१.१; ६; ७; ५२.८; ५३.१; ५४.७; ६१.४; ७; १४; ७०.६; ९; ७८.१०; ८८.६; ९०.४; ९३.१०; ९७.१; ८; १००.६; १०.२८.३; ५; ३३.३; ४२.३; ४३.५; ४४.९[2]; ५४.१; ४; ५; ५५.१; १००.१; १०२.३; १०३.१०; १११.६; ११२.९; १०; ११६.७[2]; १३१.५; १३४.६; १४७.३–५; १६७.३

मघऽवा १.३२.३; १३; ५५.४; १०३.२; ४; १४६.५; १५७.३; १७१.३; १७३.५; १७४.१; ७; २.६.४; ३.३०.३; ५३.८; ४.१७.८; ९; ११; १३[2]; १९; २०;

२०.२; २२.१; २४.२; २७.५; ४२.५; ५.२९.६; ८; ३०.३; ३१.१; ३४.२; ३; ८; ६१.१९; ६.२४.१; २७.८; ४७.११; १५; ५८.४; ७.२७.४; ९८.५; ८.१.१२; २१.१०; ३३.९; १३; ४६.१३; ४९.१; ५२.५; ६१.१; १८; ६५.१०; ७०.१५; ९६.२०; १०३.९; ९.८१.३; ९६.११; ९७.५५; १०.२३.२; ३; ३३.८; ४२.६; ८; ४३.३; ५; ६; ८; ४९.११; ८१.६; ११३.२; १६०.४

मघऽवान् ४.१६.१

मघऽवानः १.७३.५; ८; ७७.४; ९८.३; १३६.७; १४१.१३; ५.४२.८; ७९.६; ७.१६.७; २०.१०; २१.१०; ६०.११; ७८.५; १०.२७.४

मघऽवानः ७.४८.१; १०.३२.९

मघऽवानम् ३.३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.११; ३६.११; ३८.१०; ३९.९; ४३.८; ४८.५; ४९.५; ५०.५; ५१.१; ४.३१.७; ७.२६.१; २; २८.५; २९.५; ३०.५; ८.९७.१३; १०.४३.१; ७४.५; ८९.१८; १०४.७; ११; १६७.२

मघऽवाना ८.२६.७

मघऽवाना १.१८४.५; २.२४.१२; ३.५८.५; ४.२८.५

मघस्य ४.२०.७; ८.१.३०; ८८.६

मघा ५.३२.१२; ६.३७.४; ७.१६.१०; ९.१.१०

मघाऽइव १.१०४.५

मघानाम् ७.२६.४

मघानि ३.१९.१; ५३.७; ४.१७.८; ५.१०.३; ३०.१२; ६.१२.२; ७.१९.१०; २१.७; २९.१; ३०.४; ५७.६; ६७.९; १०.३२.९; ७३.४; १३२.३

मघाय ७.२७.५

मघैः ५.७९.४; ८.२४.२; १०.२३.२

मघोनः १.३१.१२; ५४.११; १४०.१२; २.२७.१७; २८.११; २९.७; ४.१७.५; ५.१६.३; २७.१; ३१.९; ६५.६; ६.२३.१०; ४४.१२; ७.१२.२; ३२.१५; ८१.६; ८.२.१३; ३३; २४.२; ९.८.७; ३२.१; १०.२२.१५; ६१.२२

मघोनाम् १.४८.२; ५.१८.३; ५; ३९.४; ६४.४; ५; ६.३७.४; ६८.२; ७.३२.७; ५८.६; ९६.२; ८.१.१६; ३०; २.३४; १९.३४; ५३.१; ९४.१; १०३.७; ९.१.३; ८०.२; १०.९३.९

मघोनि १.११३.१७; १२४.१०[२]; ३.६१.१; ४.५५.९; ५.७९.४; ६; ७; ६.६५.६; ७.७७.४

मघोनी १.४८.८; ११३.५; १३; २.११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; ३.६१.४; ६.६४.१; ७.७५.५; ७८.४; ७९.३

मघोनी इति ७.२.६

मघोनीः ४.५१.३; ६.६५.३

मघोनीः ५.८६.३

मज्जन्ति ९.६४.२१

मज्जानम् १०.६८.९

मज्मना १.५१.१०; ५५.५; ६४.३; ८४.६; ११२.३; ४; १७; १२८.५; १३०.४; १४१.६; १४३.२; ४; २.१.१५; १७.४; २२.२; ३.४६.३; ६.१८.७; ७.८२.५; ८.८८.४; १०३.२; ९.११०.९; १०.२९.६

मणिऽग्रीवम् १.१२२.१४

मणिना १.३३.८

मण्डूकः ७.१०३.४; ९.११२.४

मण्डूकाः ७.१०३.१; १०; १०.१६६.५

मण्डूकाः ७.१०३.७

मण्डूकाःऽइव १०.१६६.५

मण्डूकानाम् ७.१०३.२

मण्डूक्या १०.१६.१४

मण्डूरऽधाणिकीः १०.१५५.४

मत् २.२८.५; ६; २९.१; ५.२.८; ६.६७.२; १०.१०.८; १०; १२; ८६.६[२]; ९५.८; १६६.३

मतयः १.६२.११; १६५.४; १८६.७; ३.४१.५; ४३.२; ५.८७.१; ६.१०.२; ७.१०.३

९.७२.६; ८५.७; ११; ८६.३१; ४६; ९५.४; ९७.३४; १०६.११; १०.७.२; ४३.१; ९१.१२; १११.१
मतऽवचसा १.४६.५
मतऽवान् ९.८६.१३
मतस्नाभ्याम् १०.१६३.३
मतिः १.१४१.१; १४२.४; ३.३९.१; ५५.८; ५.४४.९; ५७.१; ६७.५^{२}; ६.८.१; ७.६६.८; १०४.६; ८.६.३४; १८.७; ७४.७; ९.६९.१; २; १०.३३.२; ४७.६; ११९.४
मतिऽभिः १.६०.५; २.१८.१; २३.६; १०; ३.३०.२०; ४३.३; ५०.४; ४.३.१६; ५.८०.१; ६.५.१; २२.२; २३.६; ३४.५; ७.१२.३; ३७.२; ३९.६; ६९.६; ७७.६; ७८.२; ८.९.६; २३.२३; ९.६८.७; ७५.४; ८४.५; ८६.२४; ९६.१५; ९७.३२; ३५; १०३.१; १०५.२; १०७.२४; १०.६.५; ७.२; ६४.१५; १६; ६७.९; ८८.५; १२३.१
मतिम् १.६.६; ३३.१३; ५७.१; १०५.१५; १३६.१; १४३.१; २.२४.१; ३.२६.८; ७.४.१; ८८.१; १००.२; ८.६.३१; ३२; ९.१६; ५९.६; ९.२१.७; ३२.३; १०७.१८; १०.२५.१०; ९१.८; १४; ११९.५
मती १.८२.२; १६५.१; २.२४.९; १३; ८.६.३९; २५.२४; ५१.३; ९.७.६; २०.३; ४४.२; ६३.२१; ६४.१०; ७१.३; ७२.१; १०.११.६
मतीः १.११४.१; ७.२९.३; ९.७२.५; ९५.१
मतीनाम् १.४६.५; ७; ६१.३; ८६.२; १८४.२; ३.५.३; ४६.४; ४९.३; ४.३२.१५; ५.४३.९; ६.१७.२; ४४.२; ६९.२–४; ७.१३.१; ९.१०.६; ७६.४; ८६.१९; ९६.५; ९७.३७; १०३.४; १०.२६.४
मतुथाः ९.७१.५
मते ८.६८.२
मत्ऽकृतानि २.२८.९
मत्था ५.५८.५
मत्ऽसखा १०.८६.१
मत्सत् ६.४४.१६
मत्सत् ४.३१.२; ५.४०.४
मत्सत ९.८५.१
मत्सति ८.९४.६
मत्सथ १.१८६.१
मत्सरः १.१७५.१; २; २.४१.१४; ९.१३.८; १७.३; २७.५; ३४.४; ६३.२४; ६५.१०; ६६.७; ७२.७; ८६.१०; २१; ९६.८; १३; ९७.११; १०७.२३
मत्सरम् ९.२६.६; ३०.६; ४६.४; ६; ५३.४; ६३.१०; १७; १०.३०.९
मत्सरऽवान् ९.९७.३२
मत्सरस्य १.१२५.३
मत्सराः १.१४.४; १३७.१^{२}; ९.१०७.२५
मत्सराणि ७.७३.४
मत्सरासः १.१५.१; ६.१७.४; ९.२१.१; ६९.६. १०७.१४
मत्सरिन्ऽतमः ९.६३.२; ६७.२; ७६.५; ९९.८
मत्सि १.९.१; १७५.१; १७६.१; ९.९०.५^{६}; ९४.५; ९७.४२^{५}
मत्स्यम् १०.६८.८
मत्स्यासः ७.१८.६
मत्स्व १.९.३; ३.४१.८; ८.१.२३; ३.१; ६.३९; १३.१४; ९२.३०; ९९.२
मत्स्व २.४१.१७; ३.६०.५; ६; ४.३२.१४; ८.५४.२; १०.१२२.५
मथायत् ९.७७.२
मथायति १.१४१.३
मथायन् ५.३०.८; ६.२०.६
मथितः ६.४८.५
मथितम् ३.९.५; ८.४८.६
मर्थाः १.१२७.११
मथीत् १.७१.४; १४८.१
मथीनाम् ८.५३.८
मथ्नन्तः १.१२७.७
मथ्ना १.१८१.५
मथ्यमानः ५.११.६

मदासः १.२०.५; ४.१७.६; ३५.१; ६.३६.१; ९.६९.७; ८६.२

मदिन्ऽतम १.९१.१७; ९.२५.६; ५०.४; ५; ७४.९

मदिन्ऽतमः ८.६४.११; ९.८०.३; ८५.३; ८६.१०; ९६.१३; ९९.६; १०८.५; १५; १०.१३६.६

मदिन्ऽतमम् ८.१.१९; १३.२३; ९.१५.८

मदिन्ऽतमस्य ९.६२.२२

मदिन्ऽतमाः ९.६७.१८

मदिन्ऽतमासः ९.८६.१

मदिन्ऽतरम् ८.२४.१६

मदिरः ९.९६.२१; ९७.१५; १०७.१२

मदिरम् २.१४.९; ५.६१.११; ६.१७.११; २०.६; ८.३८.३

मदिरस्य १.१६६.७; १०.११२.६

मदिराणि ६.६९.७

मदिरासः ८.५३.४; ९.८५.७; ८६.२

मदिरे ८.२१.५

मदिरेण १०.९४.४

मदिष्ठ ९.६.९

मदिष्ठः ६.४७.२

मदिष्ठया ९.१.१

मदिष्ठाः ४.१७.६

मदे १.४६.१२; ५२.५; १०; १४; ५६.३; ५; ६; ८०.१; ८५.१०; ११९.९; १२१.४; १७३.७; २.१५.१–९; १७.१; ३.४३.७[२]; ४.२६.७; ५.२.१०; ५३.३; ६.२७.१; २; ४३.१; ३; ४४.१४; ६९.५; ७.३७.१; ८२.३; ८.१.२१; ३.८; ७.१२; १४.७; १७.८; ३२.१; २८; ३३.४; ४८.६; ६६.२; ९२.१६; ९३.८; १०.२१.१–८; २४.१–३; २५.१–११; ४४.८; ५०.७; ९६.६

मदेन ८.१.२१; ९.७.७; ९८.७

मदेभिः ४.३५.९

मदेम १.३०.१३; ६.४.८; १०.७; १२.६; १३.६; १७.१५; २४.१०; ७.१.२४; १०.१३१.१

मदेम १.९१.२१; ३.५८.६; ४.१६.१९; ४२.१०; ५.३६.२; ४९.५; ६.१९.१३; ४९.१३; ५२.१४; ७.१९.८; ६४.३; १०.६७.९

मदेऽमदे १.८१.७; ८.१३.७; १०.१२०.४

मदेऽरघुः ८.१०१.३

मदेरिति मदेः ८.९२.१६

मदेरू इति १०.१०६.६

मदेषु १.१३१.५; १३४.५; ७.२०.४; २१.१; ८.४६.१४; ९.१.१०; १८.१–७; ६१.१; १०६.३; १०.११२.४; १२०.२

मद्यः ४.२२.८; ९.३८.५; ८६.३५

मद्यम् २.१४.१; ६.६८.१०; ७.९२.१; ९.६.२; २३.४; ६५.१५; १०७.१४

मद्यानि ७.६८.२

मद्याय ८.२.२५

मद्यासु १.१५३.४

मद्रिक् १.१७७.१; ३; ६.३१.५

मद्र्यक् ३.४१.१; ६.३८.२

मद्र्यञ्चम् ७.२४.३

मद्र्यद्रिक् ६.२२.११

मद्वने ८.९२.१९

मद्वा ९.८६.३५

मधु १.१४.१०; १५.११; १९.९; २५.१७; ९०.६[२]; ७[२]; ११२.११; २१; ११६.१२; ११७.२२; १६६.२; १९१.१०–१३; २.३६.४; ६; ३७.२; ३९.६; ३.३१.११; ३९.६; ५३.१०; ४.१८.१३; ४३.५; ५.६१.११; ६.११.३; ६०.१५; ७०.५; ७.७४.२; ८.५.११; ७.१०; ८.१; ३; ४; १०.४; १७.५; २४.१३; २६.२०; ३३.१३; ३५.२२; ३८.३; ४८.१; ६५.८; ६९.६; ७२.११; ९७.८; ९.१.८; २.३; ११.५; १८.२; ३९.५; ६२.२०; ६७.११; ३२; ६९.२; ७०.८; ७२.२; ७४.३; ७५.२; ८५.४; ८६.१०; २०; ४८; १०७.५; १०.२३.४; ३२.५; ४०.६; ४९.१०; ६८.८; ७३.९; ७६.६; ९४.३;

६१.७; ८१.१; ६.९.५; ६; १६.१७; ५३.३; ७५.६; ७.२०.६; २४.२; २५.१; २७.५; ८.१.७; ११.७; १३.२०; १७.१३; १९.२०; २४.६; ३१.१५–१८; ३३.१७; ४५.३२; ३६; ६१.२; ६२.५; ९२.२८; ९९.४; १००.५; ९.११४.१; १०.१०.३; १३; १४; ११.२; २०.१; २५.१; ४३.२; ५७.३–६; ५८.१–१२; ५९.५; ६०.८–१०; ६१.३; ८५.१०; ११७.२; ११९.१; १४५.६; १५२.५; १६४.१; २; १९१.३; ४

मनःऽऋङ्गा १०.१०६.८

मनःऽचित् ९.११.८

मनःऽजवसा १.११७.१५; ८.२२.१६

मनःऽजवाः १.१६३.९; ४.२६.५; ५.७७.३; ६.६३.७; ७.६८.३; ८.१००.८

मनःऽजवेभिः ६.६२.३

मनःऽजवेषु १०.७१.७

मनःऽजुवः १.८५.४; १८१.२; १८६.५

मनःऽजुवम् १.११९.१; १०.८१.७

मनःऽजुवा १.२३.३; ६.२२.६

मनःऽधृतः ३.३८.२

मनःऽयुजः १.१४.६; ५१.१०; ४.४८.४; ५.७५.६

मनःऽयुजम् ८.१३.२६; ९.१००.३

मनःऽयुजा ८.५.२

मनःऽवाताः ३.३८.२

मनना ३.६.१

मनना: ९.७०.३

मनन्त १०.६७.२

मनन्या १०.१०६.८

मनवः १.८९.७; ८.१८.२२; १०.६६.१२; ९१.९

मनवते १०.१२.६

मनवे १.३१.४; ३६.१०; ११२.१६; १२८.२; १३०.५; ८; १४०.४; १६५.८; १६६.१३; १८९.७; २.१९.४; २०.७; ३.३४.४; ५७.४; ४.२६.४; २८.१; ५.२.१२[२]; ३०.७; ३१.६; ६.४९.१३; ७.९१.१; ८.१०.२; १५.५; २२.६; २३.१७; २७.४; १४; २१; ९.९६.१२; १०.११.३; ४३.४; ८; ४६.९; ४९.९; ७३.७; ७६.३

मनवै १०.५२.१

मनसः १.७६.१; ११७.२; ११८.१; १५१.८; १८१.३; १८३.१; ४.३६.२; ७.३३.११; ९.११.८; २८.१; ९७.२२; २८; १०.३०.१; ३७.१२; ३९.१२; ७१.८; ८७.१३; ९०.१३; ११२.२; १२८.४; १२९.४

मनसः १०.१६४.१

मनसस्य ५.४४.१०

मनसा १.२०.२; ३१.१३; ३३.११; ५४.५; ६१.२; ६४.१; ७६.१; ७७.२; ९१.२३; ९३.८; १०२.३; १०९.१; ११२.१८; १३९.२; १४५.२; १५१.८; १५७.६; १५८.२; १६३.६; १२; १६४.५; ८; २७; ३६; ३७; १६५.२; १७१.२[२]; १७३.११; १८२.५; २.३.२; ३; १०.५; २३.१२; ३२.२; ३; ४०.३; ३.१.१३; ४.५; ८.४; १४.५; १९.३; २६.१; ३१.१; ५; ९; ३८.६; ६०.१; २; ४.१.१५; २.३; १६.१०; २४.६; २५.३; २७.३; ३३.९; ५८.६; ५.४२.४; ४४.७; ६.२८.५; ४०.३; ४; ४६.१०; ४९.५; ७.४.८; ६४.४; ६७.१; ७; ६९.२; ९०.५; ९८.२; १००.१; १०४.८; ८.२.३७; २६.२५; ३१.१२; ४८.७; ८४.५; १०२.२२; ९.६८.५; ७४.८; ७७.२; ४; १०.२.५; ५.३; १७.१२; ३०.६; १३; ३१.२; ४७.७; ५०.७; ५३.१; ११; ६३.७; ६५.५; ६७.८; ७०.४; ७१.२; ७४.२; ८१.४; ८२.१; ८५.९; ८८.१६; ९५.१; ११४.४; ११६.२; १२१.६; १३०.६; १३५.३; १४७.२; १६०.३; १७७.१; २; १८१.३; १८३.१; २

मनसि १०.१०.३

मनसे १.७३.१०; १०८.२; ४.३७.२; ६.२१.४

मनस्मयम् १०.८५.१२

मनस्यवे १०.१७१.३

मनस्यसि ८.४५.३१
मनस्ये १०.२७.५
मनस्वान् २.१२.१
मना ८.७८.२; १०.६.३
मनांसि ५.१.४; ६.४४.८; ७.५६.८; ८.२.२१; १०.१०३.१०; १९१.२
मनानक् १०.६१.६
मनानाः ६.६७.१०
मनाम् १.१७३.२
मनामहे १.२४.१; २
मनामहे १.२६.८; १५९.५; ५.१३.२; ३५.८; ४८.१; ५०.५[2]; ६६.३; ७.६६.१२; ८२.१०; ८३.१०; ८.११.५; ४७.३; ५३.७; ६१.११; ६८.१३; ९.४१.२; १०.६४.१
मनायतः २.२६.२
मनायति १.१३३.४[2]
मनायुः ४.२५.२; ५
मनायै २.३३.५; ४.३३.२
मनायोः १.९२.९; ४.२४.७
मनावसू इति ५.७४.१
मनिष्ये ६.९.६
मनीषया १.९४.१; ५.१७.२; ८.७२.३
मनीषा १.५४.८; ६१.२; ७०.१; ७६.१; ९१.१; १०१.७; १२६.१; १६५.१०; १८६.१; २.२०.१; ३.८.५; ३३.५; ५७.४; ५.११.५; ४७.१; ६.४९.४; ६७.२; ७.२४.२; ३४.१; ७०.७; ७१.६; ९९.६; १०.४.६; २९.३; ११४.६; १२४.९; १२९.४
मनीषाः १.६२.११; ४.११.३; ४१.८; ९; ६.३४.१; ६६.११; ९.६८.८; ८६.१७; ९५.३; ९६.७; १०.२६.१; २९.४
मनीषाणाम् १०.४५.५
मनीषाम् १.११०.६; ११२.२४; ३.३८.१; ५७.१; ५८.२; ४.५.३; ६.१; ११.२; ५.८३.१०; ६.४७.३; ७.२२.४; ८५.१; ८.५९.६; ९६.११; ९.९५.५; ९७.३४; १०.२०.१०; २८.५; ७७.८; ९४.१४; १११.१; १७७.२
मनीषिणः २.१९.१; १०.८१.४; १११.१
मनीषिणः १.१६४.४५; २.२१.५; ३.१०.१; ५.५७.२; ८.५.१९; ४३.१९; ४४.१९; ९.६८.६; ७२.२; ६; ७३.७; ७९.४; ८५.३; ९९.५; १०७.१४; १०.६४.१५
मनीषिणः १.१३.५; १८२.१
मनीषिणम् ९.६५.२९; ७८.३
मनीषिणे ८.१४.२
मनीषिऽभिः १.३४.१; ५२.३; ९.६४.१३; ७६.२; ८६.१९; २०; १०७.११
मनीषी ७.२२.६; ९.९१.१; ९६.८; ९७.५६; १०.६३.१७; ६४.१७
मनुः १.३६.१९; ८०.१६; ११४.२; १३९.९[2]; २.३३.१३; ४.२६.१; ५.४५.६; ८.६३.१; १०.५१.५; ५३.६; ६२.८; ११; ६३.७; ६९.३; १००.५
मनुःऽहितः १.१३.४; १४.११; ६.१६.९; ८.१९.२४; ३४.८; १०.२६.५
मनुःऽहितम् १.१०६.५; ३.२.१५; ६.७०.२; ८.१९.२१
मनुऽजातम् १.४५.१
मनुताम् ६.४७.२९
मनुना ७.२.३
मनुऽप्रीतासः १०.६३.१
मनुम् १.११२.१८; ६.२१.११; ९.९२.५
मनुऽवत् २.१०.६
मनुषः १.२६.४; ३६.७; ७६.५; १२८.१; १६७.३; १७५.३; १८०.९; १८१.८; १८९.७; २.२.५; ६; ८; १८.२; ३.२.१; ३.२; ६; २६.२; ६०.६; ४.१.९; २.१; ६.११; ३७.१; ५.३.४; ५.७; २९.१; ७; ६.४.१; १०.२; १४.२; १५.४; ७.८.२; ९.४; ७०.२; ७३.२; ८.२३.१३; ४९.८; ५०.८; ८७.२; ९.७२.४; १०.११.५; २१.७; २५.८; ४०.१३; ४९.७; ८०.६; १०४.४; ११०.१; ७
मनुषः १०.६३.६

मनुषस्य १.३१.११
मनुषा २.१०.१
मनुषाऽइव १.१३०.९
मनुषाय १.११७.२१; १०.६५.४
मनुषे १.५२.८; २.२०.६; ५.२९.३; ७.९९.३; १००.४; ९.७४.५; १०.९९.७; १०४.८
मनुष्यः १.५९.४; २.१८.१; १०.९८.८
मनुष्यऽजाः १०.८५.४०
मनुष्या १.९२.११; १२४.२; २.२३.९
मनुष्याः १.१६४.४५; ४.१.१३; ७.८९.५; १०.३५.८; ८५.३७; १०९.६; १३०.५; ६; १५०.४
मनुष्यान् ६.४७.१६
मनुष्यासः १०.७०.३
मनुष्यासु १.१४८.१
मनुष्येभिः ३.४.८; २९.२; ७.२.८
मनुष्ये३इति ३.१.१०
मनुष्वत् १.३१.१७; ४४.११; ४६.१३; १०५.१३; १४; २.५.२; ३.१७.२; ३२.५; ४.३४.३; ३७.३; ५.२१.१[३]; ६.६८.१; ७.२.३; ११.३; ८.२७.७; ४३.१३; २७; १०.६१.१५; ७०.८; ११०.८
मनूनाम् १.९६.२
मनै १०.९७.१
मनोः १.६८.४; ३.६०.३; ७.३५.१५; ८.३०.२; ४७.४; ९८.६; १०.३६.१०; ६५.१४
मनोतरा १.४६.२; ८.८.१२
मनोता २.९.४; ६.१.१; ९.९१.१
मनौ ८.५१.१; ५२.१
मनौ ८.७२.२; ९.६३.८; ६५.१६
मन्तवः १.१५२.१; ९.७३.६; १०.६३.८
मन्तवे १.११२.२
मन्तवै ७.४.८
मन्तुः १०.३२.४
मन्तुऽमः १.४२.५; ६.५६.४; १०.१३४.६
मन्त्रः १.१४७.४; १५२.२; १०.५०.४; ६; १९१.३
मन्त्रऽकृताम् ९.११४.२
मन्त्रम् १.३१.१३; ४०.५; ६; ७४.१; २.३५.२; ७.७.६; ३२.१३; १०.१०६.११; १९१.३
मन्त्रयन्ते १.१६४.१०
मन्त्रये १०.१९१.३
मन्त्रऽश्रुत्यम् १०.१३४.७
मन्त्राः ६.५०.१४; १०.१४.४; ९५.१
मन्त्रान् १.६७.२
मन्त्रेभिः १.६७.३
मन्त्रैः ३.५३.८; १०.८८.१४
मन्थः १०.८६.१५
मन्थत ३.२९.५
मन्थन्ति ३.२९.६
मन्थन्ति ६.१५.१७
मन्थाम् १.२८.४
मन्थाम ३.२९.१
मन्थिनम् ३.३२.२
मन्थिना ९.४६.४
मन्द ६.१८.९
मन्दतु ६.१७.३; ७.२२.१
मन्दत्ऽवीराय ८.६९.१
मन्दध्यै ४.१६.२
मन्दध्वे ८.७.१४
मन्दन् १०.८९.१६
मन्दना: ९.१०७.२६
मन्दन्तु १.१३४.२; २.११.११; ८.१.१५; ४.४; ४५.१४
मन्दन्तु १.१३९.६; ८.४५.२४; ६४.१
मन्दमानः ९.६५.५; १०.७३.५; ११२.२
मन्दमानाः ६.६७.५
मन्दमानाय १०.५०.१
मन्दय ३.३०.२०; ५०.४
मन्दयत्ऽसखम् १.४.७
मन्दयध्यै ४.२९.३
मन्दयन् ९.६७.१६
मन्दयुः १.१७३.२
मन्दसानः १.१०.११; १००.१४; १३१.४; २.११.३; १५; १७; ३०.५; ४.१७.३; २६.३; २९.१; ३२.१०; ५.६०.८;

मयःऽभून् १.८४.१६
मयन्ते १०.४०.१०
मर्या ८.१००.१; १०.८५.३६; १२५.४
मर्यि १.२३.२२; ८.५०.१०; ९.६६.२१; १०.९.८; ४८.३; १२८.३[२]
मयूखाः १०.१३०.२
मयूखैः ७.९९.३
मयूररोमऽभिः ३.४५.१
मयूरऽशेप्या ८.१.२५
मयूर्थैः १.१९१.१४
मरते १०.८६.११
मरन्ति १.१९१.१२
मराति १.१९१.१०; ११
मराम १.१९१.१०–१२
मरामहे १.९१.६
मराथी १०.६०.४
मरायु १०.१०६.६; ७
मरीचीः १०.५८.६
मरीचीनाम् १०.१७७.१
मरुतः १.१५.२; ३७.१२; ३८.३; ११; ८६.१; २; ७; १७२.१; २; ५.५७.८; ५८.८; ६.४९.११; ६६.८; ७.५९.१; ९; १०; ८.७.१; ११; २०.२३; २७.५; ८; ८३.७; ८९.१; ३; १०.६४.१२
मरुतः १.२३.१०; १२; ३१.१; ३७.१३; ४०.१; ४४.१४; ५२.९; १५; ६४.६; ११; ८५.१; १०; ८९.७; ९०.४; १०७.२; १११.४; १२२.१; १३४.४; १६१.१४; १६२.१; १६५.१; २; १६६.३; ११; १६७.२; ४; १६८.४; ८; १६९.३; ५; १७०.२; १७१.३; १७३.१२; १८६.८; २.३४.१; ८; ११; ३.१४.४; २६.४; ५; ३२.३; ४; ३५.९; ४७.३; ५४.१३; २०; ४.२.४; ५.३.३; २६.९; २९.१; २; ६; ३०.६; ३१.१०; ४१.२; १६[२]; ४३.१०; ४५.४; ४६.३; ५२.६; ५३.१२; ५४.३; ८; ५५.१; ५७.४; ५८.३; ५; ५९.८; ६०.२; ६३.५; ६; ६.१७.११; २१.९; ४८.२१; ५०.४; ६६.२; १०; ७.९.५; ३२.१०; ३४.२४; ३५.९; ३६.७; ३९.५; ५१.३; ५६.१६; १७; १९; २०; ५७.२; ३; ५; ६; ५८.३; ५; ६; ९३.८; ८.३.२१; ७.४; २०.१४; १८; २०; २५.१०; १४; २७.१; ४६.४; ५४.३; ९४.३; ४; ९; ११; ९६.८; ९.५१.३; ६४.२४; ८१.४; ९६.१७; १०८.१४; १०.३५.१३; ३६.१; ३७.६; ५२.२; ६३.९; ६५.१; ६६.४; ७०.११; ७३.१; ७६.१; ९२.६; ११; ९३.४; १०३.८; ११३.३; १२२.५; १२८.२
मरुतः १.३९.१; ५; ८–१०; ४०.२; ६४.९; १३–१५; ८५.४–६; १२; ८६.६; ८७.२; ८८.१; ३; ५; ६; १३९.८; १६५.६–८; १०–१५; १६६.१; ६; ८; ९; १२–१५; १६७.६; ८; ९; ११; १६८.५–७; १०; १७१.१–४; २.३३.१३; ३४.२; ३; ५–७; ९; १०; १५; ३.१६.२; ५१.९; ६२.३; ४.२६.४; ५.२९.३; ३६.६; ४१.५; ४२.१०; ४३.१०; ५३.५; ८; १४; १५; ५४.२; ४–७; १०–१२; १३[२]; १४; १५; ५५.४–१०; ५६.३; ७; ५७.२; ६; ७; ५८.३; ४; ६; ५९.४; ६०.३; ६; ७; ८३.६; ८७.२; ८; ६.४८.२०; ५०.५; ५२.२; ६६.७; ७.१८.२५; ३६.९; ४०.३; ५६.१०; १२–१५; १८; २१–२४; ५७.४; ७; ५८.२; ४; ५९.३; ५; ६; ८; ११; १०४.१८; ८.७.९; १३; ३०; १८.२१; २०.२; ६; १०; १५; २१; २२; २५; २६; २७.६; ९४.१०; १०.६३.१४; १५; ६४.१३; ७१.६; ७८.८
मरुताम् १.२३.११; ३८.१०; ९४.१२; ११४.६; १२८.५; १६७.७; १६८.९; १६९.१; २; ७; २.३.३; ३.२६.६; ४.३.८; ३९.४; ५५.५; ५.५२.३; ५३.१; ५६.१; ५; ६०.१; ६.३.८; ११.१; ४७.२८; ४८.१२; ७.३४.२५; ५६.२५; ८.१८.२०; २०.३; ४६.१७; ९४.१; ९६.९; १०.३६.४; ६४.११; १०३.९; १३७.५

मरुताम् १.११४.९; २.३३.१
मरुतामऽइव १.१४३.५; ३.२९.१५; ९.७०.६
मरुत्ऽगण ८.८९.२
मरुत्ऽगणः ६.५२.११; ९.६६.२६
मरुत्ऽगणाः १.२३.८; २.४१.१५
मरुत्ऽगणे १०.६६.२
मरुत्ऽतमा १.१८२.२
मरुत्ऽभिः १.१९.१–९; १०१.९; १०७.२; १३६.७. १६९.८; १७०.५; १७१.५; ६; ३.४७.२; ४; ५१.८; ५२.७; ६२.२; ४.३४.७; ११; ५.५२.१; ६०.८; ६.४०.५; ७.५६.५; ७; २३[२]; ८२.५; ८.७.३२; ३५.३; ९६.७; १०.१२६.५; १५७.३
मरुत्ऽभ्यः १.६४.१; ८५.८; ५.५.११; ३०.८; ५२.५; ५४.९; ६०.५; ८.४१.१; ९.२५.१; ३३.३; ३४.२; ६१.१२; ६५.२०; १०.७७.७
मरुत्वः १.१०१.८; ३.५१.७; १०.८४.१
मरुत्वतः ५.४२.६; ८.६३.१०
मरुत्वता १.२०.५; ८.७६.४
मरुत्वती २.३०.८; ७.३१.८
मरुत्वतीः १.८०.४; ८.१३.२८
मरुत्वते १.१४२.१२; ३.३५.७; ५.८७.१; ८.७६.८; ९.६४.२२; ६५.१०; १०७.१७; १०.१३.५
मरुत्वन्तः ९.१०७.२५
मरुत्वन्तम् १.२३.७; १०१.१–७; ३.४७.५; ६.१९.११; ८.७६.१; ५; ६
मरुत्वन्ता ८.३५.१३–१५
मरुत्वान् १.८०.११; १००.१–१५; ११४.११; २.३३.६; ३.४.६; ४७.१; ५०.१; ४.२१.३; ६.४७.५; ८.३६.१–६; ७६.७; १०.९८.१
मरुत्ऽवृधः ३.१३.६
मरुत्ऽवृधे १०.७५.५
मरुत्ऽसखा ७.९६.२; ८.७६.२; ३; ९; १०३.१४; १०.८६.९
मरुत्ऽसु १.१४२.९; ४.१.३; ५.५२.४; ५६.८; ९; ७.४२.५; ८.१२.१६; २७.३
मरुत्ऽस्तोत्रस्य १.१०१.११
मरै ८.९३.५
मर्कः १०.२७.२०
मर्चयति १.१४७.४; ५; ५.३.७
मर्चयात् २.२३.७
मर्जयध्वम् ७.२.४
मर्जयन् १०.१२२.५
मर्जयन्त १.६१.२; ५.३.३. ७.३.५; ३९.३; ८.८४.८; ९.६८.६; ९३.१
मर्जयन्तः १.६०.५; ९.८७.१
मर्जयन्ति ९.८९.४
मर्जयन्तीः ९.१४.७
मर्जयन्ते १०.७६.७
मर्जयसि ९.१११.२
मर्जयामसि ९.९९.३
मर्जयेम ४.४.८
मर्ज्यः ९.३४.४. १०७.१३
मर्ज्यम् ९.१५.७; ४६.६; ६३.२०
मर्डिता १.८४.१९; ४.१७.१७; ८.६६.१३; १०.६४.२
मर्डितारम् ४.१८.१३; ८.८०.१; १०.३४.३; ११७.१; २
मर्त ५.६६.१
मर्तः १.३०.२०; ६४.१३; ७२.४; १४७.५; १४९.५; १६३.७; २.२३.७; ३.५९.२; ४.४१.२; ५.५०.१; ६.१.९; २.४; १३.४; १६.२६; ३१; ३२; ४६; ५९.५; ७०.३; ७.१.२३; १००.१; ८.१९.५; ९; २०.२२; २३.२१; ४४.१५; १०३.४; ९.१०१.१३; १०.७.२; ११.७; ३१.२; ६३.१३; ९५.९; १०५.३
मर्तऽभोजनम् १.८१.६; ११४.६; ७.३८.२; ४५.३; ८१.५
मर्तऽभोजना ७.१६.४
मर्तम् १.३१.७; ८४.८; १३६.५; १४१.६; १४७.५; ५.४१.१३; ६१.१५; ६.३.१; २; १४.५; ८.७१.४
मर्तस्य १.९२.१०; ३.१५.६; ४.१.९; २.१०; ९.६; २३.५; ५.८.४; ६.२८.४; ७.८२.७; ८.११.४; ९.५८.२; ७९.२; १०.१३४.२

मर्ताः १.५.१०; ६०.२; १००.१५; १९०.१; २.२७.१०; ३.९.६; ४.११.५; १७.१९; ५.१४.२; ३१.१३; ६.२१.३; ६७.९; ७.१.९; २८.१; ३७.७; ८.११.५; १०.४.५

म॒र्ताः १०.११८.६

मर्तात् ४.१०.७; ५५.१

मर्तान् १.७०.३; ७३.८; ३.१.१७; ४.२.३; ११; ५.३.५; ६; ७.१८.१८; २३.५; १०.१२.१; ८७.२१

मर्तानाम् १.६३.५; ४.२.१८; ८.३९.६

मर्ताय १.४५.८; ७७.२; ८४.७; ५.८६.५; ६.६७.४; ८.१.२२; २२.१४; ६०.८; ७१.६; ७; ९.९४.३; ९८.४

मर्तासः १.३८.४; ११०.४; १४४.५; २.१.१४; ३.९.१; १०.१; १४.७; ४.७.२; ५.९.१; १६.१; २२.३; ६.१५.८; १६.७; ७.४.३; २५.२; ८.११.६; ६०.१५; ८१.३; १०.१३६.३; १५०.२

म॒र्तासः १.१०५.१६

मर्ते १.१२०.२

मर्तेषु १.६७.१; ४.१.१७; ५.१८.१; २५.४; ६.५१.२; ६६.१; ७.४.४; ६०.२; ७५.२; १०.४५.७

मर्तैः ५.३.८; १०.११५.७

मर्त्यऽदूषितः १.३९.८

मर्त्यः १.१९.२; ३६.४; १६; ४०.२; ४१.६; ८३.१; ८६.७; ९१.१४; १३८.२; १५०.३; १५५.५; १७९.५; २.३४.९; ४१.८; ३.११.७; ४.१५.५; ५.४.१०; ७.६; १७.१; २१.४; ४१.१७²; ५३.१५; ६.२.५; १४.१; ३०.४; ६०.११; ७.३२.११; १४; २१; ८.३.१३; ६.४४; ७.१५; १४.४; १८.१; १३; १९.१४; २५; २८; २३.१५; १९; २८.४; ४६.४; ६८.८; ९९; ७०.७; ७४.१५; ९६.२; १०१.१; १६; १०२.२२; १०.२२.५; ७९.४; ९१.११; ९३.२

मर्त्यऽकृतम् ८.१९.६

म॒र्त्यऽत्रा १.१२३.३; १६९.२; ६.४४.१०; ६२.८; ७.५२.१

म॒र्त्यऽत्वना ८.९२.१३

मर्त्यम् १.१८.४; ५; २७.७; ३५.२; ४१.२; ८४.१९; १२९.३²; १३१.४; ७²; १६४.२९; १६९.७; ४.३७.६; ५.३५.५; ५२.४; ६७.३; ८६.१; ७.४०.३; ८२.७; ९४.१२; ८.४.१६; १८.१४; १५; १९.३४; २७.१५; १०.२२.६; १२६.१; २; १७१.३

मर्त्यस्य १.१८.३; ३९.२; ११८.१; २.७.२; ३.२९.८; ४.२२.९; ६.४८.२०; ६२.३; १०; ७.२५.३; ९४.८; ८.४८.३; ७१.१; १०.१०.३

मर्त्याः १०.११८.५

मर्त्यात् १.२७.३

मर्त्यान् ४.५८.३; ८.२.४; ४८.१२

मर्त्यानाम् १.२६.९; ३१.१६; ३.१.१८; ४.१२.५; ५.४.१; ९.६; ७४.७; ६.१५.१३; ७.३९.६; ८.७८.६; १०१.६; ९.९७.२४; १०.४.२; ३३.८; ८८.१५

मर्त्याय १.११३.१८; १२४.१२; १५५.२; २.१९.५; २७.९; ३.३०.७; ४.५.२; ११.३; १२.३; २४.२; २६.२; ३०.६; ३४.४; ३९.५; ५.३.१; ४१.७; ६.१६.२५; ६४.६; ६५.३; ७.५.८; ११.३; ६५.३; ७१.२; १०.१५.७; १८५.३

मर्त्यासः १.११३.११; ३.२९.१३; ३०.१५; ८.४८.१; ९७.९; १०.२.५

मर्त्यासु १०.७९.१

मर्त्ये ३.२.९

मर्त्येन १.१६४.३०; ३८

मर्त्येभिः ९.९१.२

मर्त्येभ्यः १.९०.३; १४५.५; ८.९.१६; १०.१७.२

मर्त्येषु १.७७.१; ३.३०.३; ३९.४; ५१.५; ४.१.१; ६; २.१; ५.२.६; ७.९; ७४.८; ६.४.२; ५.५; ९.४; १०.३; ११.२; १५.३; ७.३.१; ६१.१; ९०.२; ८.११.१; ७१.११; ८४.२; ९.११०.४; १०.९५.१६; ११८.१

४८.३; ७.११.१; ३१.७; ५२.३; ६३.२; ८.१.२७; २.३२; ६.१. २६; १३.१; १६.७; ३२.१३; ३३.८; ५२.५; ६०.६; १९; ६२.१२; ६४.२; ६५.५; ९२.३; ९५.४; ९८.२; १०१.११[३]; १२[२]. ९.२.६; ९.३; ५९.४; ६६.१६; ७७.५; ९७.२; १०९.४; १०.४.२; ४६.१; ५०.४; ७५.९; १२०.९; १५२.१

महानाम् १.१८७.६; ८.६३.१; ९२.३;९४.८; ९.१.४

महानि १.५५.५; २.११.६; १५.१; ३.६.५; ३४.६; ४६.१; ४८.३; ४.२२.५; ६.७.५; ७२.१; ७.६.२

महान्ऽइव ८.२.१९

महान्तः १.१६६.११; ८.२०.८

महान्तः ५.४१.१३; ५५.२

महान्तम् १.५१.६; ११४.७; ५.३२.१; ८३.८; ६.२१.६; ८.१२.२३; ९.२.४; १०.१३४.१

महान्ता १.२१.५; ६.६७.४; ८.२५.४

महान्ति ३.१.२०; ५.५९.४; १०.१११.२

महान्तौ ७.८२.२

महाऽपदेन १०.७३.२

महाम् १.६.६; ५७.६; ११२.१४; २.११.९; २२.१; २४.११; ३.२.३; ४९.१; ४.५.९; १७.८; १९.१; २३.१; ६.७.२; १७.४; ५; १३; २९.१. ३८.५; ८.३.२०; ६५.३; ९.४०.३; ६५.१; ९०.५; १०९.७; १०.४६.५; ८०.७; ११२.९

महाऽमनसाम् १०.१०३.९

महाऽमह ८.२४.१०; ३३.१५; ४६.१०

महाऽमहः १०.११९.१२

महाऽमहिव्रतम् ९.४८.२

महाय्यम् ८.७०.८

महाऽवटूरिणा १.१३३.२

महाऽवधः ५.३४.२

महाऽवधात् ५.८३.२

महावसु इति महाऽवसू ७.८२.२

महाऽवीरम् १.३२.६

महाऽवैलस्थे १.१३३.३

महाऽव्रातः ३.३०.३

महाऽसेनासः ७.३४.१९

महाऽहस्ती ८.८१.१

महि १.४१.७; ४३.७; ५४.८; ११; ६२.२; ७९.४; ९३.८; ११६.६; ११९.४; १२७.११[२]; १३०.७; १३५.९; १३९.९; १४०.५; १५१.४; १५५.३; १५६.२; १५९.२; १६०.५; १६३.१; १६७.१०; २.१२.१०; २२.१; २३.४; २४.१४; २७.८; ३४.१४; ३.१.२२; ७.४; ३०.१३; १४; ३१.३; ४; ६; १२; १४[२]; १५; ५४.२; ४.३.१४; ५.३; ९; १६.४; ३४.४; ५६.५; ५.१.१०; ६.७; १८.५; ३२.८; ३३.१; ५४.१; ६०.३; ६८.३; ८३.५; ६.१.१०; ३.४; ४.७; १७.१; ७; १२; १९.१०; १२; २१.७; ३४.५; ४४.१८; ४७.२५; ५१.१; ६७.४; ७०.५; ७२.१; ७.५.९; ३०.१; ५३.२; ८१.१; ८२.१; १०; ८३.१०; ९७.३; ८.१२.८; २०.७. २९.१०; ३२.१४; ४६.२५; ४७.१; ५४.८; ५५.५; ६७.४; ८६. ५; ९.२.२; ४.१; ९.९; ६१.१०; ७४.३; ८०.२; ८३.५; ८५.८; ८६.१५; ३४; ९७.५४. १००.८; १०८.१; १०.३.७; ३७.८; ५०.१; ६५.२; ८०.७; ८९.१५; ९३.१; १०७.१[२]; ११५.१; १४०.१; १४४.६; १६७.२; १६९.२; १७०.३; १८५.१;

महि १.४८.१४; १६; ७.८१.४; ८.९.१७; २७.५; ६७.१०

महिऽकेरवः १.४५.४

महिऽक्षत्रौ ५.६८.१

महिऽत्वनम् १.१६६.१२; २.२३.४; ४.३६.३; ५.५४.५; ५५.४

महिऽत्वना १.८५.७; ८६.९; ४.५३.५; ५.८१.३; ६.१६.२०; ८.२४.१३; ६८.२; ९.१००.९

महिऽत्वम् १.८.५; ५९.५; ६; ६१.९; ८७.३; ११५.४; १३८.१; १६६.१; २.२७.८;

३.३२.९; ११; ५.६२.२; ६.२१.२; ६७.८; ७२.१; ७.४०.५; ९९.१; ९.४८.५; १०.४.४; २६.२; ७९.१

महिऽत्वा १.५२.१३; ६७.५; ६८.१; ९१.२; १०९.६; १६४.२५ २.१५.६; ३.१.४; ५४.१५; ४.१६.५; ४२.३; ५.२.९; ५८.२; ६.२९.५; ६७.३; १०; ६८.४; ७.१३.२; २०.४; २३.३; ५८.१; ६१.४; ९७.८; १००.३; ८.२५.१८; १०.५४.१; ५५.५; ५६.७; ७५.७; ८८.९; ८९.१; ९६.११; १२१.३; ४

महिऽत्वेभिः १०.११३.७

महिन ६.२६.८

महिनः ६.५२.१५

महिनस्य ६.३३.५; ६८.८

महिना ६.६१.१३

महिना १.३२.८; ३३.९; १२२.११; १३९.११; १५१.५; १७३.६; १८०.९; १८६.९; २.१.१५; १७.२; ३.६.२; ७.१०; ३०.१३; ५९.७; ५.५७.४; ८७.२; ६.८.२; १५.१४; ६८.९; ७.२१.४; ९; ६०.१०; ८६.१; ९५.१; ९६.२; ८.१२.२३; ६८.३; ७०.६; ९२.२३; १०.२८.७; ७०.५; ८१.२; ८८.७; ११९.८; १२१.८; १२५.८; १२९.३; १४७.५

महिनि ५.८४.१

महिनी इति १.१६०.२

महिनी इति १.१६०.५

महिने ७.३१.११

महिन्ऽतमाय १०.११५.६

महिंऽमघस्य १.१२२.८

महिमनः ६.२७.३; १०.५४.३

महिमा १.१२९.१०; १६७.७; ४.१६.५; ५.८७.६; ६.१८.१२; ५९.२; ७५.१; ७.२८.२; ३३.८; ४५.२; ८.३.४; १०; १०१.११; १०.६६.५; ७५.९; ९०.३

महिमानः १.१६४.५०; १०.९०.१६; ११४.७; ८; १२९.५

महिमानम् १.६१.८; ८५.२; २.१७.२; ३५.९; ३.३१.१७; ३२.७; ५.८१.३; ६.७५.६; ७.२.२; २१.६; २२.८; ७५.१; ९८.३; ८.३.८; १३; ४६.३; ५९.२; ५; ६५.४; १०.६५.२; ६९.९; ७५.१; ११२.४; ११३.१–३; १६८.१

महिम्नः ७.९९.२; १०.५६.४

महिम्ना १.५९.७; ६.६१.१३; १०.८८.१४

महिम्ने ९.६२.२७

महिऽरत्न १.१४१.१०

महिऽवृधे ७.३१.१०

महिऽव्रत १.४५.३; ९.१००.९

महिंऽव्रतः ६.६८.९; ९.९७.७

महिंऽव्रतम् १०.११५.३

महिष ३.४६.२

महिषः १.१२१.२; २.२२.१; ९.६९.३; ८६.४०; ८७.७; ९२.६; ९६.६; १८; १९; ९७.४१; १०.८.१; २८.१०; १२८.८; १८९.२

महिषम् ४.१८.११; ८.६९.१५; ९.९५.४; ११३.३; १०.१४०.६

महिषस्य १.९५.९; १४१.३; ९.८२.३; १०.५४.४; ६६.१०; १२३.४

महिषा ५.२९.७

महिषाऽइव ८.३५.७–९; १०.१०६.२

महिषाः ६.८.४; ७.४४.५; ९.७३.२; ८६.२५; ९७.५७; १०.५.२; ४५.३

महिषाःऽइव ९.३३.१

महिषाणाम् ५.२९.८

महिषान् ६.१७.११; ८.१२.८; ७७.१०

महिषान्ऽइव १०.६०.३

महिषाय १०.६५.८

महिषासः १.६४.७

महिंषी ५.२.२

महिंषीऽइव ५.२५.७

महिंषीम् ५.३७.३

महिंष्वन्तम् ७.६८.५

महिऽस्वनीनाम् ८.४६.१८

मही १.८.८; १३.९; २२.१३; १०२.७; ११७.१९; १३१.१; १४२.९; १५७.१;

१६४.३३; २.३३.१४; ३.३१.३; १३; ६१.७; ४.१४.३; ४१.५; ५.५.८; ४१.१५; ४३.८; ४७.१; ८१.१; ६.४५.४; ६६.३; ७.१५.१४; ५६.४; ८.२५.३; ४०.४; ४६.३३; ९.५.८; ८६.४४; १०.६०.९; ७७.४; ८५.२; ९२.४; ९६.१०; १०१.९; १३३.७

मही इति १.८०.११; १२१.११; १५१.५; १५९.१; ३; ३.१.७; ३८.३; ५५.२०; ६१.७; ४.५६.१; ७; ७.२.६; ५३.१; ८७.२; ९३.५; ८.६.१७; ७२.१२; ९.५.६; ९.३; १८.५; ४१.५; ६८.३; ७४.२; १०.३५.१; ३; ६४.१४; ८०.२; ११२.४

महीऽइव २.२४.१४; ८.९०.६; १०.१३३.५

महीः १.१३३.१; १४२.६; २.११.२; ३.२२.४; ३०.१८; ५६.२; ५.११.५; ६.४५.३; ५७.४; ७.५९.२; ८७.१; ८.३.१०; ६.१६; १२.३; २१; २७.१६; ५०.२; ६६.१०; ७०.४; ९.२.४; ८; ७.२; १५.७; ६१.२२; ९९.७; १०.१४.१; ६४.८; ९; १०४.९

महीनाम् ३.१.१२; ५.४५.३; ९.१०२.१; १०.१३४.१

महीनाम् ८.१९.३१

महीभिः ३.१.१९; ३१.१८; ४.३२.१; ८.२.३२; १६.७

महीम् १.१०२.१; १३१.४; १४०.५; २.१५.५; ३३.८; ३४.८; ३.३०.९; ४.१९.६; ३२.७; ५.४३.६; ४४.६; ८५.५; ६; ६.३८.१; ७.२४.६; २५.६; ३६.८; ८.६.२३; ९.४१.४; ६५.१३; १०.३०.१; ५०.५; ७४.४; ९२.५; १११.५; ११९.८; १४०.५; १८८.२

महीयते १.१८२.३; ५.५६.९; ९.११३.६

महीयते ९.१२.४; १०.८६.१०; १४६.२

महीयन्ते १०.१७५.३

महीयमानाम् ४.३०.९

महीयुवः ९.६५.१; ९९.१

महीयै १.११३.६

महे १.५३.१; १०; ५६.१; ६२.२; ७१.५; ७६.२; ९१.७; ११६.१३; १२७.१०; १२९.१०; १३९.६; १५१.३; १५५.१; १६८.१; १८०.६; २.३१.३; ३.७.९; १०; १०.६; ४१.६; ५१.८; ५४.१–३; ४.३.७; २५.१; ५.३३.१; ४१.११; ४२.११; १३; ४८.१; ५९.२; ६६.१; ७९.१; ८७.१; ६.१.१०; २०.११; २५.८; ३२.१; ३४.२; ४०.३; ४४.१३; ४५.२७; ३०; ६८.१[२]; ७.२४.५; २८.३; ३०.१; ३१.१०; ३२.९; ७५.२[२]; ८२.६; ८.१.५; २.२९; ७.५; १५.१३; २२.७; २४.१०; २६.२; ४५.२४; ४६.२५; ५९.१; ६४.१२; ६७.८; ६८.७; ७०.९[२]; ९३.७; १६; ९६.१०; ९.९.५; १६.५; ४४.१; ६२.२२; ६५.७; ६६.१३; १५; ७७.३; ८६.३४; ८७.५; ९६.३; ९७.२७; १०८.१४; १०९.३; ११; ११०.२; ७; १०.९.१; ४८.८; ५०.१; ९१.८; ९५.७; ९६.१

महे ७.९७.२

महेत १.१११.३

महेऽनदि ८.७४.१५

महेम १.९४.१; ७.२.३

महेऽमते ८.१३.११; ३४.७; ४९.७; ५०.७

मह्ना १.५५.१; ७२.९; १६४.२५; १६६.११; १७४.४; २.३.२; १२.१; २८.१; ३५.२; ३.३४.७; ६२.१७; ४.२.१; ५.३३.१०; ७३.३; ८४.१; ८७.२; ६.२१.२; २४.३; ६६.५; ७.१२.२; १८.८; ८.३.६; २०.१४; ५५.२; १००.४; १०१.१२; १०.१.५; ६.७; ५५.७; ६५.३; ६७.१२; ८९.१; १११.४; ११३.७

मह्यम् १.२३.१५; २४.१२; ५०.१३; १०९.१; १२२.८; १२६.६; १६५.११; २.२८.१०; २९.४; ४.५.२; ३; ४२.२; ५.४२.१६; ४३.१५; ५२.१०; ६.२७.८; ४६.९; ४७.१०; ८.१.३२; ३३; २६.१२; ५६.२;

१००.१; ९.३२.६; १०.३४.१; २; ३९.६; ४८.३; ४९.१; ८५.३६; ४१; १२८.१; २; ४; १६९.४

मह्या ४.१.९

मह्याः १०.३०.७

मह्यै १.२४.१; २; ६.५७.६; ८.७०.९

मा १.४.३; ५.१०; ११.२; १८.३; २३.९; २४.११; २५.२^{२}; २७.१३; ३३.३; ३६.१६; ३८.५; ३९.२; ४१.८^{२}; ४३.८^{२}; ५३.३; ५४.१; ७१.१०; ८२.१; ८४.२०^{२}; ८९.९; ९१.२३; ९४.१–१४; १०४.५–७; ८^{५}; १०५.३; १०९.३; ११४.७^{७}; ८^{५}; १२०.८^{२}; १२१.१५; १२५.७^{२}; १२६.७; १३९.५; ८; १५८.४^{२}; १६२.१; ११^{२}; १५^{२}; २०^{३}; १७०.२; १७८.१; १८३.४^{४}; १८९.४^{२}; ५^{४}; २.७.२; ११.१; २१; १५.१०; १६.९; १७.९; १८.४; ९; १९.९; २०.९; २३.८; १०; १२; १६; २७.१४; १७^{२}; २८.५^{२}; ७^{२}; ९; ११^{२}; २९.४^{२}; ५; ७^{२}; ३०.७; ३२.२^{३}; ३३.१; ४^{३}; ५; ४२.१; २^{३}; ३^{२}; ३.१५.६; १६.५^{४}; ३३.८^{२}; १३; ३५.५; ४१.८; ४५.१; ५३.२; १७^{२}; १९; २०^{२}; ५५.२; ४.३.१३^{५}; ५.२; १२.५; १८.१; २०.१०; ३२.२०; २२; ३५.१; ४४.५; ५.३१.२; ३६.४; ४०.७; ४१.१६; ४२.१६; ४३.१५; ५३.८; ९^{३}; ५५.९; ५६.७; ६५.६; ७०.४^{३}; ७५.७; ७८.१; ७९.९; ६.२८.७^{२}; ३५.५; ४४.१०; ११^{२}; १२; ४७.९; ४८.१७^{२}; ५१.६; ७^{२}; ५२.१४; ५९.७; ६१.१४^{३}; ७५.१६; ७.१.११^{२}; १९^{६}; २१^{२}; २२^{२}; ४.४; ६^{३}; ७; ९.५; १९.७; २१.५; २२.६; २५.१; ३१.५; ३२.९; २७^{२}; ३४.१७^{२}; ३६.७; ४०.६; ४३.३; ४६.३; ४^{३}; ५०.१^{२}; २; ३; ५२.२^{२}; ५६.९; २१^{२}; ५७.४; ५९.१०; १२; ६०.८; ६२.४^{२}; ६९.६; ७३.४; ७४.३; ७५.८; ८८.६; ८९.५; ९३.८; ९४.३^{३}; ७; ८; १००.६; १०४.७; २३; २४; ८.१.१^{२}; १३; २०; २.१५^{२}; १९; ३.२; ४.७^{२}; ८; ८.१३; २०.१^{२}; २१.१५; १६^{२}; २२.१४; ३०.३; ३३.१९^{२}; ४५.२३^{२}; ३१; ३४^{३}; ३६^{२}; ४८.८; १४^{२}; ६०.८^{२}; २०^{२}; ६५.१०; ६६.१५; ६७.८; ९; २०; ७१.७; ७३.१५; ७५.८; ९; १२; ७९.८^{३}; ८०.८; ८१.६; ८६.१–५; ९२.३१; ९६.१२; ९७.२; ७^{२}; १०१.१५; १०३.१२; ९.७२.८; ८१.३; ८५.१; ११४.४; १०.१५.६; १६.१^{४}; ८; १८.१^{२}; ४; ११; १९.१; २२.१२; १५; २५.७; २७.२४; ३४.१३; १४; ३६.२; ३७.६; ५४.५; ५७.१^{३}; ६२.११; ६९.५; ८५.३२; ४२; ८७.९; १७; १९; ९५.१५^{३}; ९७.२०; १०१.८; १०६.२; १०८.९; १२०.४; १२१.९; १२८.४; ५^{३}; ८^{२}; १४२.३; १६०.१; १६५.३; १७३.१; २; १७८.२^{२}

मा १.२३.२३; २४; ४८.२; १०५.७; ८^{२}; १८; १२०.११; १२२.१५; १२६.३; १५८.५; १६४.२१; ३७; १६५.११; १२; १७९.४; २.२८.६; २९.५^{२}; ३०.७^{२}; ३३.६; ७; ३.१.१; ३२.१४; ४३.५^{२}; ४.४.११; १५.७; २६.१; २७.१; ४२.६^{२}; ५.२७.५; ३०.९; १३; ३३.८^{२}; ९; १०; ४०.७; ४२.१५; ६.४७.१०; ४८.१६; ५२.४^{३}; ५९.८; ७.१८.२३^{२}; ३३.१; ५९.७; ८३.५; ८८.२; १०१.६; १०४.८; १५; १६; ८.९.५; १०.५; ४६.३०; ४८.५^{२}; ६; १०; ६८.१४; ९७.१५; १००.१; ४^{२}; ५; १०१.१६; ९.६७.२७^{२}; १०.९.९; १०.७; १७.१४; २८.६; २९.३; ३३.१–३; ५; ३४.१; २; ३५.८; ३७.२; ४२.३; ४८.४; ५; ७; ११; ४९.५; ७; ५१.२; ४; ५२.१; २; ८३.५; ६; ९५.५; १३; ९७.१६; ११९.२–४; १२४.५; १२५.३; १२७.७; १२८.९; १६६.१

माँश्चत्वे ९.९७.५४

माँश्चत्वे ९.९७.५२
मांसऽभिक्षाम् १.१६२.१२
मांसम् १.१६१.१०
मांस्पचन्याः १.१६२.१३
माः ४.३३.४; ५.२९.८
माकिः १.१४७.५; ३.३६.९; ४.४.३; ६.५४.७; ७१.३; ७५.१०; ८.५.३९; ६७.११; ७१.८; ९.८५.८; १०.११.९; १२.९; २३.७; १००.७
माकी इति ८.२.४२
माकीनया ८.२७.८
माकीम् ६.५४.७[२]; ८.४५.२३
माघोनम् ६.४३.४; ८.५४.५; १०.१०७.१
माघोने १०.६६.२
मातः १.१८५.११; ६.५१.५
मातरः १.९२.१; ३.३१.२; ४१.५; ५.४७.६; ६.४५.२५; ८.८९.४; ९५.१; ९६.१; १०२.१७; ९.१२.२; १९.४; ३३.५; ८६.३६; १००.१; ७; १०२.४; १०.९.२; १७.१०; ६४.९; ७५.४; ९१.६; १२३.३
मातरः १०.९७.४
मातरम् १.२४.१; २; ११०.८; १११.१; ११४.७; १२१.२; १६३.१३; ३.४८.३; ४.१८.१; ३; १२; ५.३४.४; ५२.१६; ६.७२.२; ७.४३.३; ८.४५.४; ७७.१; १०३.२; १०.१८.१०; ५४.३; ६२.३; ८८.१५; ९४.१४; ११४.४; १४६.६; १७६.१; १८९.१
मातरा १.१२२.४; १४०.३; १४२.७; १५५.३; १५९.३; ३.१.७; ५.७; ७.१; ३३.१; ३; ४.२२.४; ५.५.६; ६.१७.७; ३२.२; ७.२.५; ७.३; ८.९९.६; ९.९.३; ६८.४; ७०.६; ७५.४; ८५.१२; १०२.७; १०.१.७; ३५.३; ५९.८; ६४.१४; ७९.४; १२०.७; १४०.२
मातराऽइव ९.१८.५
मातरापितरा ४.६.७
मातरि ३.२९.११; ५.७८.९
मातरिभ्वरीः १०.१२०.९
मातरिश्वः १०.८८.१९
मातरिश्वना ९.६७.३१
मातरिश्वनि ८.५२.२
मातरिश्वने १.३१.३; १४३.२; १०.४८.२
मातरिश्वा १.६०.१; ७१.४; ९३.६; ९६.४; १२८.२; १४१.३; १४८.१; १९०.२; ३.२.१३; ५.९; १०; ९.५; २९.११; ६.८.४; १०.४६.९; ८५.४७; १०५.६; १०९.१; ११४.१
मातरिश्वानम् १.१६४.४६; ३.२६.२
मातरौ १०.११५.१
मातला १०.१४.३
मातवै १.१६४.२८
माता ८.४१.४
माता १.३८.८; ७२.९; ८९.४; १०; ११३.१९; १६०.२; १६४.८; ९; ३३; १८५.१०; १९१.६; २.३८.५; ३.४६.५; ४८.२; ५५.४; १२; ४.१८.५; १०; ११; ५२.२; ३; ५.२.१; २; ७.८; ४१.१५; १९; ४२.२; १६; ४३.२; १५; ४५.२; ६; ४७.१; ६.१.५; ६६.३; ७०.६; ७.५५.५; ७७.२; ९८.३; १०१.३; ८.१.६; २५.३; ४७.९; ९४.१; ९८.११; १०१.१५; १०.४.३; १७.१; १८.११; २७.१४; १६; ३२.४; ३४.४; १०; ३६.३; ६०.७; ६१.२०; ६३.३; ६४.१०; ७३.१; ९७.९; ११४.४; १३२.६
माताऽइव ५.१५.४; ६.७५.४
मातुः १.३७.९; ६१.७; १४०.९; १५९.२; १६४.३२; २.५.६; ३.८.१; २९.१४; ४.१.१६; २.१५; ५.१०; १७.१२; ५.१.६; १९.१; ४३.१४; ४७.५; ६.१६.३५; २०.८; ५५.५; ७.४.२; ८१.४; ८.८३.८; ९.६९.१; ७३.५; ८९.१; १०.२०.२; ३२.८; ७९.३
मातृऽतमाः १.१५८.५; ६.५०.७
मातृऽतमाम् ३.३३.३
मातृऽभिः २.११.८; ८.७२.१४; ९.९३.२; १०४.२; १०५.२; १११.२

मानुषाः १.३८.१०; ३९.६; १६२.४; १०.१३.२; १२२.७

मानुषाणाम् १.८४.२; १२७.८. १२८.७; ४.१.२०; ८.८; ९.५; ५.७.३; ६.१.५; १८.७; १९.६; ७.१०.३; ६२.१; ६३.१; ७७.१; ८.२३.२५; ४१.१; ९.६१.११

मानुषात् २.३.३

मानुषान् १.४८.७; ५०.५; ११३.९; ८.९.२; १९.३५; १०.११५.७

मानुषाय १.१२३.१

मानुषासः १.६०.३; ७.७.४; ११.२; १०.४६.१०

मानुषि ७.७५.२

मानुषी १.७२.८

मानुषीः ३.२.१०; ६.३; ५.८.३; ४५.१; ६.६५.१; ७.५.२; ७९.१; ९.६३.७; १०.६९.९; ८०.६; ८३.२

मानुषीः ६.५०.७

मानुषीणाम् १.५९.५; ३.११.५; ३४.२; ५.१.९; ४.३; ९.३; ६.१८.२; ४८.८

मानुषीषु २.४.३; ३.५.३; ४.६.७; ८; ९.२; ७.६७.७; ९.३८.४; १०.१.४

मानुषे १.४८.११; १२८.७; ३.२३.४; ५.१४.२; २१.२; ६.१६.१; ७.१८.९; ८.६४.१०; १०.११८.९

मानुषेभिः ७.३८.१; १०.१२५.५

मानुषेभ्यः ४.५४.२

मानुषेषु १.२५.१५; ५८.६; ५९.३; ६०.४; ४.५४.३; ५.१३.३; ७.२.७; २२.६; १०.४६.४

मानै १०.२७.२३

मानेन १.११७.११

मानेनऽइव ५.८५.५

मानेभिः १.१८४.५

मानेभ्यः १.१६९.८

मानैः २.१५.३

मान्दार्यस्य १.१६५.१५; १६६.१५; १६७.११; १६८.१०

मान्यमानम् ७.१८.२०

मान्यस्य १.१६५.१४; १५; १६६.१५; १६७.११; १६८.१०; १७७.५; १८४.४

माम् १.१५८.४^{2}; १६५.६; १८५.९^{2}; ४.२७.२; ३९.१; ४०.१; ४२.५^{2}; ५.२.३; ३०.८; ४०.७; ६.५२.४; ७.४९.१–४; ५०.१^{2}; २; ३; ८३.३; ८.६.३२; ७४.१४; ९.६७.२१; २५; २७; १०७.१९; ११३.७–११; १०.१८.१४; २७.५; २८.६; ७; ३३.१; ४८.१; ३; ४९.२; ५२.४; ८३.६; ८६.९; ९८.२^{2}; १२५.४; १४५.६; १८३.२

मामकः १०.१५९.१

मामकम् १०.१७.१४

मामकानाम् १०.१०३.१०

मामतेयः १.१५८.६

मामतेयम् १.१४७.३; १५२.६; ४.४.१३

मायया १.८०.७; १४४.१; १६०.३; २.१७.५; ३.२७.७; ४.३०.१२; २१; ५.६३.३; ६; ७; ६.२२.६; ७.१०४.२४; ८.२३.१५; ४१.३; ९.७३.५; ९; ८३.३; १०.७१.५; ८५.१८; १७७.१

मायवः १०.९३.१५

माया ३.६१.७; ५.६३.४; १०.५४.२

मायाः १.३२.४; ११७.३; २.११.१०; २७.१६; ३.२०.३; ५३.८; ५.२.९; ३१.७; ४०.६; ८; ६.१८.९; २०.४; २२.९; ४४.२२; ४५.९; ५८.१; ७.१.१०; ९८.५; ९९.४; ८.४१.८; १०.५३.९; ७३.५; ९९.२; १११.६

मायाभिः १.११.७; ३३.१०; ५१.५; १५१.९; ३.३४.६; ६०.१; ५.३०.६; ४४.२; ७८.६; ६.४७.१८; ६३.५; ८.१४.१४; १०.१४७.२

मायाम् ५.८५.५; ६; १०.८८.६

मायाऽवान् ४.१६.९

मायाऽविनः ९.८३.३

मायाऽविनम् २.१११.९

मायाऽविना १०.२४.४

मायिनः १.३९.२; ५१.५; ५४.४; ६४.७;

मिनाति १.१७९.१; ५.७.४; ७.३६.४; ८४.४
मिनाति १.७१.१०; १२३.९; १२४.३; २.१२.५; ३.३०.१२; ५.८०.४; ६.३०.२; ८.८८.३; ९.८६.१६; ९७.३०
मिनानः ५.४२.१३
मिनामि १०.२५.३; ४८.११
मिनीमसि १.२५.१
मिनीमसि १०.१३४.७
मिनोतु १०.१८.१३
मिन्वन् १०.२०.५
मिन्वन् ३.३१.१२
मिमते १.१६४.२४; ९.९७.९; १०.११४.५
मिमन्ति ९.३३.४
मिमय २.२९.५
मिमाति १.१६४.२८; २९; ९.६४.१९
मिमाति १.३८.८; ९.६९.४
मिमातु ५.५९.८
मिमाते इति ७.८२.६
मिमाथाम् ४.४४.६
मिमाथाम् ४.४१.४
मिमानः १.५०.७; २.१७.२; १०.८४.२
मिमानम् ५.२.३
मिमाना ६.६२.२; १०.११०.७
मिमानाः ७.१८.१५; १०.५६.५
मिमाने इति १.१४६.३
मिमाय १.१६४.४१; २.१५.३; ३.५३.१५; ५५.१३; ७.१८.१६; १०.२७.१४
मिमिक्ष ९.१०७.६
मिमिक्षः ६.३४.४
मिमिक्षतम् १.२२.३; ३४.३; ४७.४; १५७.४
मिमिक्षताम् १.२२.१३; ६.७०.५
मिमिक्षति १.१४२.३
मिमिक्षतुः ८.६१.१८
मिमिंक्षन् ७.२०.४
मिमिक्षिरे १.८७.६; १०.९६.३
मिमिक्षुः ६.२९.२; १०.१०४.२
मिमिक्षुः १.१६५.१; १६७.४; ५.५८.५; ६.२९.३
मिमिक्षुम् ३.५०.३
मिमिक्षे २.३.११
मिमिक्ष्व १.४८.१६
मिमीतः ५.७६.२
मिमीतम् १.१२०.९
मिमीतम् १.१२०.९
मिमीताम् ५.५१.११
मिमीते ८.१२.१०–१२; १३.३०; ९.१०२.३
मिमीते १.१६४.२४; ३.१.५; १०.७१.११
मिमीयाः १०.५६.२
मिमीयात् १०.१०.९
मिमीहि १.३८.१४
मिमीहि ३.१.१५; ५४.२२; ५.४.२; ६.१९.३; ७.१९.११
मिमृक्षुः १.६४.४
मिमे १०.१३.३; १२४.३
मिमेथ १०.३४.२
मिम्यक्ष १.१६७.३; ६.५०.५; १०.४४.२
मियेधः १.१७७.४; ३.३२.१२; १०.७०.२
मियेधे ३.१९.१; ५; ७.१.१७
मियेधैः ६.५१.१२
मियेध्य १.२६.१; ३६.९; ४४.५
मिश्रा १०.९५.१
मिषतः १०.१९०.२
मिषति ३.२९.१४
मिषन्तम् १.१६४.२८
मिषन्ता ८.२५.९
मिषन्ति ९.७३.४; १०.१०.८
मिहः १.७९.२; ३.३१.२०; १०.७३.५
मिहः १.३७.११; ५.३२.४
मिहम् १.३२.१३; ३८.७; १४१.१३; २.३०.३; ८.७.४; १०.३१.९
मिहे १.६४.६
मीळ्हुःऽतमाय १.४३.१
मीळ्हुषः १.१५५.४; १६९.६; १७३.१२; २.८.१; ४.१५.५; ६.६६.३; ७.१६.३; ४०.५; ५८.५; ८.२०.१८; १०२.१५; १०.१८८.२
मीळ्हुषाम् ८.२०.३

३.४७.२; ५.३०.६; ६.५३.४; ६०.५; ७.४३.३; ८.४५.४०; ६१.१३; ९.४.३; ४०.१; ६१.२५; २६; ६३.२४; ८५.२; ८६.२६; ९७.४३; १०.६७.११; ८४.२; ९८.१२; १५२.३; ४; १८०.२

मृधाति ६.२३.९

मृधि १.१७४.७

मृध्याः ३.५४.२१

मृध्रऽवाचः १.१७४.२; ५.२९.१०; ७.६.३; १०.२३.५

मृध्रऽवाचम् ५.३२.८; ७.१८.१३

मृध्राणि ८.४३.२६

मृध्रेभ्यः ८.४४.३०

मृश १.१२६.७; ८.२१.१६; ८१.६

मृशते १.१४५.४

मृशन्ति १०.३४.४

मृशसे ९.२०.३

मृशस्व ८.७०.९

मृशामसि १०.१७३.६

मृषन्त ७.१८.२१

मृषा १.१७९.३

मृष्ट १.१४०.२; १७४.४

मृष्टः ९.८२.२

मृष्टाः ९.२२.४

मृष्ठाः ३.३३.८

मृष्यते १.१४५.२; ६.५४.४

मृष्यन्ते ६.६७.७

मृष्ये ७.२२.५

मे १.१०.९; २३.२०; २४; २५.४; १६–१९; ५०.१२[२]; ९३.१; १०५.१–८; ९[२]; १०–१८; ११०.१; ११७.२३; १२२.४; ६; १२४.१३; १२६.१; ७[२]; १३१.६; १३९.७; ९[२]; १४५.३; १४७.२; १६२.७; १६३.४; १६४.१६; ३३[२]; १६५.४[२]; १०–१३; १८१.७; १८३.५; १८४.२; २.४.५; ६.१; १०.२; १४.१०; १८.८; २४.१५; २७.२; २८.५; १०; ३०.७; ३२.१; ३५.१; ३६.६; ४०.५; ४१.१३; ३.१५.२; २६.७[२]; ३३.५; ३८.८; ४३.५; ५१.२; ५३.३; १६; ५४.२; १६; २१; ५५.३; ५७.१; ६२.२; ४.५.६; ८; १८.२; १३; २३.४; २४.१०; ३२.२४; ४१.८; ९; ५.२.५; ८; १२.३; १४.५; १८.५; २७.१–४; २९.३; ३०.२; ३२.११; ३३.९; ३६.३; ४१.१५; १७; ४२.२; ४६.६; ५२.१२; १६; १७; ५३.३; ५४.१५; ५६.२; ६१.९; १०; १७; १८[२]; ६४.७; ७४.६; ७८.५; ६.९.६[२]; २१.११; २८.५; ४७.३; ४९.५; ५०.१०; ५२.७; १३; १६; ६३.२; ९; ६९.४; ७; ७.१.१०; २०; २५; ७.६; १८.४; २२.३; २३.१; २९.३; ३३.१; ६२.५; ६३.३; ६७.५; १०; ६८.२; ६९.८; ७६.२; ८२.८; ८४.५; ८५.५; ८६.२–४; ८७.४; ९९.७[२]; १००.७[२]; ८.१.६[२]; ३.२१; २२; ४.२१; ५.३७; ३८; ६.३२; ७.९[२]; ८.१२; १३.२१; १४.१; १९.२६; ३६; ३७; २२.१२; २३.१४; २५.२३; २६.८; ११; १७; ३२.६; २३; ३५.४; ४३.१६; २७; ४४.२; ४६.२७; ५०.३; ५४.४; ५५.३; ५६.३; ६१.१०; ६५.१०; १२; ६६.१२; ७३.१०; ८०.४; ८२.६; ८५.१; २[२]; ९; ९१.५; ९२.२९; ९३.१५; १००.२; ५; १०१.७; १०२.१९; १०.९.६; १०.११; ११.२; १२.४; २४.६; २७.१; ३; ४; १०; १८; २०; २८.२; ४; ६; ३०.८; ३२.३; ६; ३४.१३; ३९.६; ४०.५; ४३.१; २; ४८.५; ९; ५१.२; ४; ८; ५२.१; ५४.५; ६०.१२[३]; ६१.४[२]; ८; १५; १९[३]; ६२.७; ६३.२; ६४.२; १२; ६५.१३; ६६.१०; ११; ७०.१; १०; ७५.५; ८३.७; ८६.५; ७[३]; १४[२]; ९३.१२; ९५.५[२]; १०; ११[२]; १७; ९७.२; १४; ९८.१; १०६.६; १०८.१०; ११९.१; ६; ७; ११; १२२.२; १२८.४; १४५.२[२]; ५; १५१.२; १५९.३[२]; १६६.२; ५

मेवः १.१८१.८

मेळिम् ३.२६.९; ४.७.११

य

५४.१३; ५८.३; ६१.१०; ६५.१;
७७.४; ८१.३; ८२.८; ९; ८५.१; ५;
६.१.९^{२}; ११; २.४; ५; ३.५; ६^{३}; ७; ८^{२};
४.२; ३; ५^{२}; ५.१; ४^{२}; ५^{२}; ६.२; ७.७^{२};
९.३; १०.३; ४; १२.५; १३.४; १४.१;
१५.५^{२}; ११; १३; १६.२३; ३१; ३२;
३९; ४६; १७.१; २^{५}; १८.१; ८; १०;
१९.२; ७; २०.१; २१.२; ४; २२.१^{२};
३; २३.५; ३३.१^{२}; ३४.२; ३६.५; ४१.३;
४४.१^{२}; २; १३; ४५.१; ११^{२}; १६; १७;
४६.३; ४७.२; ४; ४८.५; ६; ४९.५; १३;
५०.८; ५१.२; ५२.२^{२}; ८; ५४.१^{२}; २;
४; ५५.४; ५६.१; ५९.४; ६०.१; १०;
११; ६१.५; ६२.९; ६३.१; ४; ६८.१;
५; ६; ९; ७०.३; ७१.२^{२}; ७३.१; २;
७५.१९^{२}; ७.१.२; ८; १५; २३; ३.१;
९; ४.१–३; ५; ५.१; ६.४; ५^{२}; ७.४;
८.४; ९.२; ४; १२.१; १५.१; २; १६.६;
१८.७; ११; १८; १९.१^{२}; २०.५; ६^{२}; ८;
२२.२; २३.१; २७.२; २८.५; २९.५;
३०.५; ३२.५; ६; १२; १३; ३६.४^{२};
३८.१; ४१.२; ५५.६^{३}; ७; ५६.१८; २४;
५८.१; ५९.२; ८; ६०.३; ११; ६१.१;
६३.१; ३; ६४.४; ६७.१; ६८.५; ७;
६९.५; ७०.२; ६; ७१.४; ७३.२; ८२.१;
८४.४; ८५.४; ८६.१; ८७.७; ८८.१; ६;
९०.२; ९६.६; ९७.२–४; १००.१^{२};
१०१.२^{३}; १०२.२; १०४.७; ८; १०^{४};
११^{२}; १५; १६^{२}; ८.१.८; १२; २७; ३१;
३२; २.२४; ३४; ३७; ३९; ४.६; ५.१९;
३४; ३८; ६.१; १६; १७; ८.१५; १६; १९;
१२.१; ६; १३.८; ९; १७.१३; १८.१३;
१४; १९.५^{४}; १३; १४; २२; २४;
२०.१५; २१.२; ९; १०; २२.५; २३.१०;
१५; २१; २४.३; १९; २७^{२}; २५.२; १८;
२६.१३; १४; २७.८; १५; १६; ३१.१;
२; १५–१८; ३२.२; ११; १३; १८; २०^{२};
२५^{२}; २८; ३३.४^{२}; ५^{५}; ६^{३}; ७; ९; १६;
३९.८; ४०.१०; ११; ४१.१; २; ४; ५^{२};
७; १०^{२}; ४३.२२; ४४.१५; ४५.५; ६;
१५; ३०; ४६.८^{४}; ९; १२; २१; २६–२८;
४८.१०^{२}; १२; ४९.१; ५०.१; ५१.३^{२};
५; ८; ५२.३^{२}; ५; ५३.२; ७; ५८.१;
५९.३; ६०.७; ६३.१२; ६६.२; ३^{२}; ४;
६८.७; ६९.१३^{२}; ७०.१^{२}; ३; ७; ८^{२};
१३; ७१.११; १३; ७३.१३; ७४.३; ८०.२;
८१.८; ८२.७; ८; ८४.९; ९१.२; ९२.१६;
१७^{३}; १८; २३; ९३.२; ३२; ९५.४; ५;
९६.६; १९^{३}; ९७.३; १००.७; १०१.१;
३; ४; १०२.११; १०३.४; ६; ११; १२;
९.७.७; १२.४; ५; १४.५; १८.४–६;
२१.५; २४.४; ३८.५; ३९.४; ४३.१;
५२.३; ४; ५३.३; ५५.४; ६१.१; १४;
१९; २२; ६३.११; १६; ६४.११; १२;
६६.१७; ६७.२२; ३१; ३२; ६८.३; ८;
७४.२; ३^{२}; ७६.४; ७७.४; ७८.५; ७९.४;
८४.२; ३; ८६.१५; ८८.३–५; ९१.२;
९६.१८; ९७.४६; ४८; ९८.३; ७; ८;
९९.३; १०१.२; ९^{२}; १५; १०७.१^{२};
१०८.६; ८; १३^{४}; ११४.१^{२}; २; १०.३.५;
६; ६.१; २^{२}; ३; ८.३; ९.२; १०.१२;
११.७; १२.६; १४.५; १६.५; ६; ८;
१०; ११; १७.११; १२^{३}; १३^{३}; १८.१;
१९.४; ५^{२}; २२.१–३; २३.५^{२}; २४.३;
२६.५; ७; २७.३; ७; १०; ११^{२}; २१;
२८.२; २९.१; २; ३०.४; ७^{२}; ८; ९;
३४.१२; ३५.१४; ३७.१२; ३८.३; ४^{३};
३९.१; ४२.४–७; ९; ४३.८; ४४.१;
४५.९; ४६.१; ४७.६; ४९.३; ६; ५१.२;
५२.३; ५४.६^{२}; ५५.६; ५७.२; ५९.१०;
६०.३; ६१.३; ६२.८; ६३.६; ६५.१०;
६८.१२; ७१.६; ७२.१; ७४.५; ७७.७;
७९.५; ८०.४; ८१.१; ८२.३^{३}; ७;
८३.१; ८५.३४; ३९; ८६.२१; ८७.८^{२};
११; १६^{३}; ८८.३; ४; ७; १२; १४; ८९.१;
३; ४; ९१.११; ९३.२; ९६.१; ३; ४;
७; ८^{२}; ९७.२३; ९९.९; १०; १००.२;
१०५.५; ७; १०७.५–७; ११०.९; १११.४;

११२.२; ११५.१; २; ६; ११६.३; ११७.२–४; १२१.२; ३[२]; ५; ८[२]; ९[३]; १२२.३; १२५.४[३]; १२८.७; १२९.७; १३०.१; १३३.३; ४; ५[२]; १३४.२; १३६.५; १४४.४; १४७.४; १४८.५; १५२.४; १६०.३; ४; १६२.१; २; ३[२]; ४[२]; ५[२]; ६[२]; १६४.५; १७०.१; १७४.२; १७८.३; १८७.२–५

यके ८.२१.१८

यक्नः १०.१६३.३

यक्षत् ६.१२.२; ७.१७.४; ८.३९.९; १०.१६.११

यक्षत् १.१३९.१०; ३.४.३; १९.१; ५.१३.३; ६.१५.१०; ४९.९; ६२.४; ९.७४.२; १०.५३.१

यक्षतः २.३.७

यक्षताम् १.१३.८; १४२.८; १८८.७

यक्षते ८.१९.४

यक्षऽदृशः ७.५६.१६

यक्षन्त १.१३२.५

यक्षऽभृत् १.१९०.४

यक्षम् ४.३.१३; ५.७०.४; ७.६१.५

यक्षवः ७.१८.१९

यक्षस्य १०.८८.१३

यक्षि १.१३.१; १४.१; ३१.१७; ३६.६; ७५.५; २.६.८; ३६.४; ५.२६.१; ६.१६.२; ९; २४; ४८.४; ७.९.५; ६; १६.५; १७.३; ८.१०२.१६

यक्षि १.१०५.१३; १४२.११; २.३.३; ३.४.१; १४.५; १७.२; ३; ५३.२; ५.२८.५; ६.४.१; १६.८; ७.११.३; ३९.४; १०.१.६; ४.१; ५२.५; ७०.४; ९; ११०.३; ९

यक्षिन् ७.८८.६

यक्षुः ७.१८.६

यक्ष्म १०.९७.१३

यक्ष्मम् १.१२२.९; १०.९७.१२; १३७.४; १६३.१–६

यक्ष्मस्य १०.९७.११

यक्ष्माः १०.८५.३१

यक्ष्यः ८.६०.३

यक्ष्यमाणम् १.१२५.४

यक्ष्यमाणान् १.११३.९

यक्ष्व १.४५.१०; ५.४२.११

यक्ष्व ४.१.५

यच्छ १.२२.१५; ४.१२.५; ५.२७.२; ७.१६.८; ३०.४

यच्छ १.५८.८; १०२.३; ११४.१०; ३.५१.११; ५.८३.५; ६.१५.३; १६.३३; ४६.९; १२; ७.५.९; १०.९८.११; १०२.३; १४१.१; १५२.४; ५; १६९.२

यच्छत २.२७.६

यच्छत १.८५.१२; ४.५१.१०; ५.४६.७; ७.५९.१; ८.१८.१२; २७.९; ३०.४; ४७.२; १०.१५.७; ३५.१२; ३७.११; ६३.७; १२

यच्छतम् ८.८.१६

यच्छतम् १.१७.८; २१.६; ४६.१५; ९२.१६; ९३.८; ४.४७.४; ५०.१०; ६.५९.९; ७.७४.२; ८२.१; ८; ८३.९; ९४.८; ८.९.१; १५; ३५.२१; २२

यच्छतात् १.४८.१५

यच्छताम् २.४१.२०

यच्छति ४.५३.१

यच्छति ५.८०.२; ९.८६.१५

यच्छतु ३.१३.४; ४.३२.१५; ५३.६; ५७.७; ६.७५.१२; १७[२]; ८.३४.२; ४७.९; १०.१९.२; ६६.३; १०३.१३; १४१.२

यच्छध्वम् ७.४३.२

यच्छन्ति ७.६०.८; १०.१०७.४; १८५.३

यच्छन्ति ६.७५.६; ७.७९.२; ८.४.२

यच्छन्तीः ७.७८.३

यच्छन्तु ३.५४.२०; ७.३९.७; ४०.७; ६२.३

यच्छन्तु १.१३०.२; ७.८२.१०; ८.१८.३; ३२.२३; १०.१२६.७

यच्छमानाः ७.५६.१३

यच्छसे १.८४.६; ७.५५.२

यज १.४५.१; ७५.५[२]; ७६.२

यज १.१४.११; १५.१२; २६.१; १८८.९;

३.१०.७; १७.५; २५.१; ५.२१.१; ६.१६.२; ४७.२७; ५२.१२; ७.४२.५; १०.२.१
यजत ४.१.१
यजतः १.३५.३; ४; ५९.७; १४१.७; १८१.३; २.१४.१०; ३.५.३; ५.४१.९; ४४.१२; ६.५०.८; ७१.४; ८.१७.१५; ९.६९.३; ८६.१४; १०.९२.१; ९९.११
यजतम् १.१२८.८; १५१.१; २.३३.१०; ५.८.१; ४६.५; ६७.१; ६.१.८; ४९.९; ५८.१; ७.२.१; ९७.५; १०.७.३
यजतस्य ५.४४.१०; ११; ७.२.२
यजता १.३४.७; ४.१५.८; ५.४३.११; ६४.७; ७.७५.७; १०.११.८; ४०.३
यजताः ६.५०.२
यजताम् १०.१०१.९
यजताम् ६.१५.१३
यजताय २.१६.४; २१.१
यजति १.२६.३; १२०.५; १३३.७; १५१.७; ७.७.५
यजति १.१३९.१०
यजतु २.३.१; १०.२.२; ११.१
यजते १.३१.१५; १८०.३; ४.६.११; ६.२८.३; ७.७३.२; ९.७१.३
यजते ५.७७.२
यजते इति ४.५६.२; ४; १०.११०.६
यजतेभिः ५.१.११
यजतेभ्यः २.५.८
यजत्र १.७६.४; १८९.३; ७; ३.१४.२; २२.२; ३५.१०; ६.१२.२; २५.८; ७.१४.२; १०.११.८
यजत्रः १.१२१.१; १७३.२; ७.५२.३; १०.३१.१
यजत्रम् १.१२९.७; ७.८८.१; १०.४६.९; १०; १४९.३
यजत्रा १.१०८.७; १८०.५; ८.५७.१; ४
यजत्राः १.१४.८; ६५.१; ३.६.८; ५७.४; ६.५२.१३; ७.३५.१५; ४३.४; १०.६५.१४; ७०.११
यजत्राः १.८९.८; १८६.११; २.२७.१६; २९.६[२]; ३१.७; ४.१२.६; ५.५५.१०; ५८.४; ६.५०.१५; ५१.६; ९; ५२.१७; ७.५७.१; ४; ५; १०.६१.२७; ६३.११; १२६.८
यजत्रान् १.१४.७; ३.५७.५
यजत्रे इति ३.३१.१७; ७.५३.१
यजत्रैः ४.५६.२; ६.२१.११; ७.७५.७
यजथः १०.१०६.३
यजथाय २.२८.१; ३.४.१; ५.९; १७.१; १९.५; ५.१.२; ११.२; ७.१०.५; १०.७.१; १२.१
यजध्यै ३.१.१; ४.३; ४.२१.५; २४.५; ६.११.३; १२.१; २; १५.१५; ४९.२; ६८.१; ७.२.७; १०.६१.१५; ११०.७
यजध्यै ८.३९.१
यजध्व ८.२.३७
यजध्वम् २.२.१; ३.३; ५.७७.१; २; ६.२९.१; १०.३०.३
यजन्ताम् १०.१२८.३
यजन्ति १.९१.१९; ५.४५.४
यजन्तु १०.१२८.४
यजन्ते ७.३६.५
यजन्ते ४.२४.५
यजन्तौ २.३.७
यजमान ८.३१.१६
यजमानः १.२४.११; ३.१.१५; ३.३; ४.१७.१५; ५.७७.२; ६.५१.१२; ८.३१.१५–१८
यजमानम् १.१३०.८; १५६.५; ५.४५.५; १०.१२८.७
यजमानस्य १.५१.८; १७८.४; २.२०.७; ३०.६; ३.५३.३; ५.४४.१३; ६.२३.७; ५४.६; ६०.१५; ७.५७.२; ८.१२.१८; ५८.१; १०.४०.१४; ४९.१; ४; ११६.८
यजमानाः १.१२७.२; १०.४५.११; १५१.४
यजमानात् ४.१०.७
यजमानाय १.८१.२; ८३.३; ९२.३; ९३.७; ३.१७.३; ५.२६.५; ६०.७; ६.१५.१६;

७.१६.६; ८.१४.३; १७.१०; ५९.१; ४; १०.२७.१; १००.३; १२२.६; १२५.२; १७५.४; १८२.१–३

यजमानासः २.१८.३; ३.३५.५; १०.१६०.१

यजमाने ३.२९.८; ८.९७.२

यजमानेषु ८.५९.७; १०.१७.९; १२२.८

यजसा ८.४०.४

यजसि ६.४८.४; १०.९१.११

यजसि १०.११०.१

यजसे ८.२५.१

यजस्व २.९.४; २६.२; ६.११.१; २; ४; ७.४२.३; ८.२३.१

यजस्व १.७६.५; २.१६.४; ३.१.२२; ८.११.१०; १०.२.६; ७.६[2]; ८०.७; ८१.५; ६; ९८.४

यजात् १०.२.३

यजाति ८.३१.१

यजाति १.७७.२; ३.४.१०; ७.२.१०; ३९.१; १०.२.५; ९५.१८

यजाते ७.१००.१; ८.३१.१

यजाते ३.५३.११; ६.४७.१५

यजातै १.८४.१८

यजाम १.२७.१३; ५.६०.६

यजाम १०.१२४.६

यजामः ३.३२.७

यजामसि १०.१७२.३

यजामसि १०.१३२.२

यजामहे १.१५.१०; २६.६; १५३.१; १०.२३.१

यजामहे १.४०.४; ८३.५; ९७.२; ७.५९.१२; ८.४०.२

यजामहै १०.५३.२

यजासि ३.११.४; ६.४.१

यजासि ३.२९.८; ६.१५.१४

यजिष्ठ २.६.६

यजिष्ठः १.७७.१; १२८.१; १४९.४; ३.१०.७; १३.१; ४.१.४; २.१; ७.१; ६.१५.१३; ७.१५.६; ८.६०.३; १०.२.५; ६.४

यजिष्ठम् १.३६.१०; ४४.५; ५८.७; १२७.२; ४.१.१९; ७.५; ८.१; ५.१४.२; ७.३.१; ८.१९.३; २१; ६०.१; १०.४६.८; ११८.९

यजिष्ठेन ३.१४.५

यजीयान् २.९.४; ३.४.३; १७.५; १९.१; ४.६.१; ५.१.५; ६; ३.५; ६.१.२; ६; ११.१; १०.१२.२; ५२.२; ५३.१; २; ११०.३; ९

यजुः ८.४१.८; १०.१२.३; ९०.९; १०६.३; १८१.३

यजुषा ५.६२.५

यजे २.९.३

यजेत ७.६०.९

यजेथाम् १०.७०.७

यज्ञः १.१८.७; १०७.१; १५६.१; १६४.३५; १७३.११; १७७.४; १८१.१; १८८.२; ३.१२.२; ३२.१२[2]; ४.२.५; ३४.३; ५८.९; ५.२२.२; २६.८; ६.११.५; २१.४; ३८.४; ४०.४; ६८.१; ७.७.३; १६.२; ३४.१७; ४३.२; ७०.६; ८.६.२२; १३.३२; १४.५; १८.१९; ६८.११; ८९.६; ९.१०.३; ८८.७; १०.१४.१३; २०.६; ५०.६; ५१.९; ६६.६; ७७.४; ८८.८; ९३.८; १००.५; ६; १०३.८; १०४.६; १०५.८; १३०.१

यज्ञऽकामः १०.५१.५

यज्ञऽकेतुः ४.५१.११

यज्ञऽधीराः ७.८७.३

यज्ञनिःऽकृतः १०.६६.८

यज्ञऽनीः १.१५.१२

यज्ञऽन्यम् १०.१०७.६

यज्ञऽन्योः १०.८८.१७

यज्ञऽपतौ १०.१७०.१

यज्ञऽप्रियै १०.१२२.६

यज्ञऽबन्धुः ४.१.९

यज्ञम् १.१.४; ३.१०; ११; १०.४; १२.१०; १३.२; ८; १२; १५.२; ३; ६; २०.२; २२.३; १३; २६.१०; ३४.३; ९; ४०.३; ४१.५; ४७.४; ८४.२; ९१.१०; १९; १०५.४; १२२.१; १३९.११; १४२.२;

२३.११; २२^{३}; २५.१; २६.६; २८.५; २९.१; ३०.३; १५; ३१.४; ११; १४; १८; ३२.४; ११–१३; १४^{२}; ३३.५; ९; ३६.१३; ३७.३; ५; ६; ९; १२; १३; ३८.४; ८; ९; ३९.१; ३; ४४.१२; ४६.३; ४७.७^{२}; ४८.१०; १५; ५१.४; १०; ११; ५२.२; ५; ६; ९^{२}; १०; ११; १५; ५३.६; ७; ५४.४; ५^{२}; ५५.४; ५६.५^{२}; ५७.२; ५८.१; ४; ६१.११; १३; १५; ६२.६; ६३.१; २; ४^{२}; ७; ६४.७; ६५.४; ६६.३; ६७.२; ६८.१; २; ६९.३; ४^{३}; ७१.४; ५; ८; ७२.३; ६; १०; ७४.७; ७७.२; ७९.३; ८०.७; ११; १३; १४; ८१.३; ८३.६; ८४.६; १४; ८५.३–५; ७; ९; ८६.१०; ८७.२; ३; ५; ८८.५; ८९.८; ९३.४; ९४.५; १०; ११; १४; ९५.८; ९७.३–५; १००.११; १०१.८^{२}; १०२.१; १०३.४; ७; १०४.५; १०६.५; १०८.६; ७^{२}; ८^{२}; ९; १०; ११^{३}; १२; ११०.२; ३; ११२.२१; ११३.९^{३}; १०; २०; ११४.२; ११६.५; ११; १२^{२}; १८; ११७.८; १०; १६; २२; ११९.३^{२}; १२०.७; १२१.१; ४; ५^{२}; ७^{२}; ८; १०^{२}; १२२.९; ११; १३; १२३.३; १२७.३; ७; १०; १२८.५; १३०.९; १३१.३; ४; ५^{२}; ६; १३२.४–६; १३४.२; १३६.४^{२}; १३८.२; १३९.१; २; ७; ८^{३}; १४०.५; ११; १४१.१; ३^{२}; ४^{३}; ५–७; ९; १४४.२; १४५.२; ४^{२}; १४६.५; १४७.१; १४८.१; १५१.२; ३^{२}; १५३.१–३; १५७.२; १५८.१^{२}; २–४; ५^{२}; १६०.२; १६१.१; ३; ५; ११; १२; १६२.१–४; ८^{२}; ९^{४}; १०; ११; १३; १४^{३}; १६; १७; १६३.१; १०; १३; १६४.४; २३^{२}; १६५.३; ६; ७; ११; १४; १६६.५; १३; १४; १६७.२; ५–७; १६८.६; ८; १६९.६; १७०.१; १७३.१; २; ६; ८; १७४.२; ४; ९; १७८.१; १७९.३^{२}; ५; १८०.१; २^{२}; ३; ६; ९; १८१.१; ९; १८२.८; १८३.२; १८४.४; १८५.१; ८; ११; १८६.९^{२}; १८७.७–९; **२.१.१५**; ४.५; ५.३; १०.१; ११.१०; १३.३; ९; ११; १३; १४.८; १२; १६.३; १७.१^{२}; ३; १९.२; ५; २०.८; २२.४; २३.१४; १५^{२}; १८; १९; २४.९; १५; १६; २७.५; १४; २९.५; ३१.१; २; ५; ३४.२; ८; १०^{२}; ३५.१५; ३८.११; ४१.८; ४३.३; **३.२.७**; ५.४; ६.७; ८.१^{२}; ९.२^{२}; ६; ७; १४.३; ४; १८.५; १९.४; ५; २२.२^{२}; २९.११^{२}; १४^{२}; १६; ३०.३; ५; १२–१४; १८; ३१.१७; ३२.१; ६; ९–११; १४; १६; ३३.७; ८; ११; ३६.४; ६^{२}; ८; ९; ३८.९; ३९.१; ४०.९; ४८.२; ५१.८; ५२.५; ५३.८; ९; ५४.१७; ५५.१; ११; १७; ५७.२; **४.१.१०**^{२}; २.१४; १८; ५.८; ९; ११^{३}; १२; ६.५; ६; ७.७; ९–११; ११.२; ६; १२.४; १३.२; १५.७; १६.३; ४^{२}; ८; ११; १४; १७^{२}; १७.१९; २०; १८.१२; २०.१०; २१.७^{३}; ८; २२.१^{२}; ५; ७; २३.४; २४.३; ४; ८; २६.३; ४; २७.३^{३}; ३०.३; ८; १०; १३; २३; ३१.६; ३२.८; १३; ३३.४^{३}; ७; ३५.२; ९; ३६.१; ३; ३९.४; ४१.११; ४२.६^{२}; ४३.५^{२}; ७; ४४.२; ५–७; ४५.५; ५१.६; ५४.३; ४; ५५.२; ५६.१; ५७.५; ५८.१; **५.१.३**; ४; २.२; ३.१^{२}; २^{२}; ३^{२}; ८; ४.६; ६.४; ७.३; ४; ८; ९.५; १५.४^{२}; २५.७; २९.२^{२}; ५; ६; ८^{२}; ९; ३०.५; ७; १०^{२}; ११; ३१.३; ५–८; ३२.१; ५; ७^{२}; १०; ३३.३; ४; ३४.२; ८; ३५.२^{३}; ३८.२; ३९.१–३; ४०.५; ६; ४२.२^{२}; ४; ४४.१२; ४५.८–१०; ४७.५^{२}; ४८.१; ४९.४; ५३.१; ७; १३; ५४.४–६; ८; १०; १२; ५५.६; ८^{४}; ५७.३; ५८.६; ५९.४; ६०.३; ६^{३}; ७; ६२.९; ६४.३; ४; ६६.६; ६७.२; ७३.१^{४}; ४–८; ७४.४; १०; ७८.४; ७९.५; ८२.५; ८३.२–४; ९^{२}; ८४.३; ८५.६; ७; ८^{३}; **६.२.३**; ९; ३.३; ५.६; ७.४; ५; ९.६; ११.३; ५; १२.५; १३.५; १५.१; ९; १४^{२}; १६.३६; १७.८;

९; १८.१३; १५; २०.२; ३; ५; १०; १२; २३.१; २^{२}; ५; २५.४^{२}; ७; २६.१; ५; ७; २७.४; ५; ३०.३; ३३.४; ३४.३; ४; ३५.२; ३; ५; ३६.१; ४०.५^{३}; ४४.६; ४५.२२; २३; ४६.७^{२}; ८^{२}; ११; १३; ४७.१०; १५; ५०.४; ५; ५१.७; ५६.४; ५७.४; ६२.३; ८; ६३.२; ६५.४; ६६.२; ४; ६७.२; ४; ५^{२}; ७^{२}; ८–१०; ११^{२}; ६८.४; ६९.८; ७०.२; ७४.३; ७५.१; ७.३.४; ६; ९; ५.३; ८.४; ६; १३.३; १६.४; १८.१; १९.२; ५; २०.१; ७; २३.२; २५.१; २६.१; २; २७.१; ३; २८.२^{२}; ३–५; २९.५; ३०.३^{२}; ५; ३२.७; १८; २१; ३३.४; १०^{२}; ३४.२०; ३६.६; ४०.१; २; ६; ५०.२; ३^{३}; ५२.२; ५३.३; ५४.१; ५५.२; ५६.४; १०; २१; २२; ५७.१; ४; ५८.५^{२}; ६०.१; ८; ६१.२; ६३.२; ६६.४; १२; १४; ६७.४; ६८.४–६; ६९.४; ७०.१; ४; ७१.४; ८१.५^{२}; ८२.५; ६; ८; ९; ८६.४; ८८.२; ३^{३}; ५; ८९.२; ५^{२}; ९२.२; ९३.३; ५; ७; ९४.९; १०; ९६.२; ९८.२; ४^{२}; ६; १००.६^{२}; १०३.२; ३; ४^{२}; ५^{२}; ७; १०४.१२; ८.१.३; ११; २८; ३१; २.६; ३.११; १२; ४.१; २; ५.१; २२; २४; ६.२; ३; ५; ८; १३; २४–२६; ३०; ७.१; २; ४; ५; ११; १४; २१; २६; २८; ३१; ८.६; १०; १४^{२}; ९.२^{३}; ५^{३}; ६^{२}; ९^{२}; १०^{४}; १२^{४}; १३^{२}; १५; १८; १९^{२}; २१^{२}; १०.१^{३}; २; ५^{३}; ६^{३}; १२.७; १३–१५; १६^{३}; १७; १८; २५; ३२; १३.५; ६^{२}; १५^{३}; १९; २९; १४.१; २; ४; ५; ७; १३; १५.१२; १८.३; १२; १९.१५; २५; २०.४; २५^{४}; २२.१०; ११; २३.१३; २४.३०; २५.१३^{२}; २६.१७; २७.९; १९^{३}; २०; २१^{२}; ३४.१६; ४०.७; ४१.८; ४३.६; २८; ३३; ४४.२३; ४५.६; ७; १४; १८; १९; ३१; ३३; ३९; ४१^{२}; ४६.३१; ४७.१०^{४}; १३^{२}; १४^{२}; ४८.९;

४९.७^{३}; ५०.२; ३; ७^{२}; ५४.५; ५९.१; ६; ६०.१४; ६१.९; ११; ६२.१; ५; ८; ६३.७; ६५.१; २^{२}; ७; ६६.५; ६७.६^{२}; १८; ६९.६; ७; १०; १७; ७०.५; १४; ७२.६; १८; ७३.५; ७५.३; ७६.११; ७९.२^{२}; ६; ९; ८३.५; ८८.३; ६; ८९.५; ६^{२}; ९१.६; ९३.४; ५; १४; १७; २८–३०; ९६.५; १२; ९७.४^{२}; ५^{३}; ११; ९९.६; १००.५; ६; १०; १०१.८; १०२.२०; २१^{२}; ९.२.४; ६.७. ७.४; ५; १९.१; २४.५; ४३.५; ४७.३; ५०.२; ५६.२; ६१.२७; ६४.१९; २०; ६५.६; ६६.९; १३; ६७.२१^{२}; २३; २४; ६८.६; ७०.१; ६; ७१.५; ७२.२; ७४.१; ७; ८१.१; २; ८६.१५; ४७; ८७.३; ९२.५; ९४.१; ३; ९५.५; ९७.३१; ४१; ९९.७; १०२.२; ४; ५; ७; ११०.८; ९; १११.१; ३; ११४.४; १०.१.३; २.३–५; ३.२; ८.५; ९.८^{३}; १०.२; ४; ११^{२}; ११.३; ५; ८^{२}; १२.१; ३; ४; ६; १३.२; १५.६; १६.६; १७.२; १८.२; १९.४^{२}; २०.४; २२.७; ११; १४; २३.६; २४.४; २५.९; २७.१; ४; ५; ९; १०; १२; २८.३; २९.४; ३०.५; ६; १३; ३१.५; ८; १०^{३}; ३२.१; ३; ४^{२}; ३३.८; ३४.५; ३५.८; ३६.१०; ३७.२; ३; ५; १२; ४०.११; ४१.३; ४२.९; ४३.५; ७; ४५.२; ६; ८; ४७.८; ४८.४; ८; ९; ४९.४–७; १०; ५१.७; ५२.१; ३; ५४.१^{२}; २; ३; ५५.१; २; ४^{२}; ६; ५८.१; २^{२}; ३–६; ७^{२}; ८^{२}; ९–१२; ५९.८–१०; ६१.१; ४–७; ११–१३; १७; २०; २३; ६८.७; ६९.१; ३^{२}; ४; ९; ७०.९^{२}; ७१.१^{३}; ६; ८; ७२.६; ७; ७३.१; ३; ९^{२}; १०; ७४.६^{२}; ७५.२^{२}; ३; ४; ७६.२; ७७.६; ८१.४; ८२.५; ८५.३; ५; ७; ९; १०; १४–१६; ३०; ८६.२०; २२; ८७.६; १३^{२}; ८८.४–६; १५; ८९.६; १४^{२}; ९०.२^{३}; ६; ११; १२; १५; ९१.५; ७; ९; ९३.५; ९४.१; ६; ९५.७–९; १२;

१३; १६; ९६.९; ९७.५; ९-११; ९८.१[२]; ७; ९९.३; ८; ११; १०२.२; १२; १०५.३; ९; ११[३]; १०७.७; ८; १०८.१०; १११.७[२]; ११३.१; ३; ६; ११८.२; १२०.३; १२१.७; १२३.६; ८; १२४.२; १२६.७; १२९.१; ३; ४; १३०.३; १३१.५; १३२.३[२]; ५; १३४.१; ४; १३५.७; १३६.२; ७; १३७.२; ३; १३८.६; १३९.५[२]; १४२.४; ५; १४३.४; १४६.२; १४७.१[२]; १५५.३; ४; १५७.४; १६४.३[२]; ४; १६५.१; ४[२]; १७२.१; १८१.१; २[२]; १८६.३

यतः १.२२.१६; १९; २५.१७; १२८.४; १४१.१; २.२४.६; ३.४.९; १०.६; १३.४; २९.१०; ४.१८.१; ५.४८.५; ७.२.९; ४.२; ७.३; ७६.३; ८.६.२९; ६१.१३; १०.३१.७; ४५.२; ७३.१०; ८१.२; ४; ८४.५; ८५.३१; १२०.१; १२९.६; ७

यतः १.१६९.१; ५.५३.१६; ६.४६.१४; ७.६१.३; ९.२४.३; २८.४; ६४.१५; २९; ६८.४; ७; ८६.२०; २२; ९५.१; ९९.८; १०८.१५; १०.१११.७

यततम् ८.३५.१२

यतति ७.३६.२

यतते १.१८६.११; ३.१६.४

यतते १.९५.७; ९८.१; ५.३७.१; ९.९२.३; १११.३; १०.७५.३

यतथः ५.६५.६

यतथः ५.७४.२; ६.६७.३; १०

यतन् ५.४८.५

यतन्ताम् ५.५९.८

यतन्ते ८.४३.४

यतन्ते १.१६३.१०; ७.७६.५; ७९.२; १०.२९.८; ९१.७

यतम् ९.३४.३

यतमः १०.८७.८; १७

यतमानः ५.४.४

यतमाना १०.६२.११

यतमानाः १.१२३.१२; ३.५८.८; १०.१८.६

यतमाने इति १०.१३.२

यतमानौ १०.११३.७

यतम्ऽकरः ५.३४.४

यतयः ८.६.१८; १०.७२.७

यतये ७.१३.१

यतरत् ७.१०४.१२

यतऽरश्मयः ५.६२.४

यतऽस्रुक् ४.२.९; १२.१

यतऽस्रुचः १.१४२.५; २.३४.११; ३.२.५; ८.७; २७.६; ८.२३.२०; ४६.१२; ७४.६

यतऽस्रुचा १.८३.३; १०८.४

यतऽस्रुचे १.१४२.१

यतस्व १.१६९.६

यता ४.६.३

यतानः ९.९७.३०

यतानाः ३.८.९; ५.३३.१०

यति ७.४३.४; १०.१५.१३; १८.६; ६३.६

यतिः ९.७१.७

यतिऽभ्यः ८.३.९

यत्ऽइव १.१६४.३७

यती ५.४५.७; ५९.२; ७.९५.२; १०.४०.५

यतीऽइव ७.७६.३

यतीः ८.६.३४; १३.८; ९१.४; ९.२४.२

यतीःऽइव ५.५३.५

यतीनाम् १.१५८.६

यतीषु ४.३८.७

यतुनस्य ५.४४.८

यते १.४१.४; १८८.२; ५.२७.४; ८.२७.२०; ९.६९.३; ७४.३; ७७.५; १०.७८.२

यतेते इति १०.१३.५

यतेम ६.१.१०

यतेमहि ५.६६.६

यतैते इति ७.९३.५

यत्ऽकामाः १०.१२१.१०

यत्ऽयत् ८.६१.६

यत्र १.१३.५; २२.४; २३.१८; २८.१-४; ८३.६; ८९.९[२]; ११३.१६; ११५.२; १२१.९; १३३.१; १३५.७; १५१.६; १५४.५; ६; १६३.४; १६४.२; ३; २१;

यद्दा १.८२.१; १०३.८; ११५.४; १६१.४; १६३.७; १६४.३७; ३.५३.४; ४.१७.१०; २४.८; १०; ३३.२; ३८.८; ५.८५.४; ८७.४; ७.३.२; ४२.४; ९८.५; ८.१२.२६–३०; २१.१४; ५१.८; ८०.९; १००.१; १०.७.२; १६.१; २[२]; २३.३; २७.३; ६७.१०; ६८.६; ८२.१; ८८.११[२]; ९२.३; ११४.१०; १४२.४

यदि १.११.३; २७.१३; ३०.८; ५६.४; ७९.२; १६१.२; ८; १६८.८; १७३.८; १७८.३; २.५.६; ३.५.८; १०; ६.३; २९.६; ३१.२; ६; १३; ४.५.११; २१.६; ८; २६.५; २७.३; ४१.३; ५.२.११; ३.१०; ४८.४; ७४.५; ६.२२.४; २५.६[२]; ३४.३; ४२.३; ४६.१४; ७.५६.१५; ८२.८; १०४.१४; १५[२]; ८.१.१५; १२.८; १३.२१; १९.२३; ३२.६; ३३.९; ६१.१०; १००.३; ९.१४.२; ३; १५.३; ४७.४; ७०.२; ७२.२; ८६.६; ४६; ९७.२२; ९९.२; १०.११.४; १२.३; १६.३; २२.१०; २७.२; ६१.२५; ९५.४; ११५.१; १२९.७[३]; १४३.१; १६१.१; २[३]; १६७.४; १७९.१[२]

यदुः १०.६२.१०

यदुम् १.३६.१८; ५४.६; १७४.९; ६.२०.१२; ४५.१; ८.४.७; ७.१८; ९.६१.२; १०.४९.८

यदुषु १.१०८.८

यदौ ८.९.१४; १०.५; ४५.२७

यन् १.१७३.३; १८३.२; ४.२४.९; ५.३१.७; ६.३.७; ८.२.४०; ४३.७; ९.९३.२; १०.१२.१; ८८.१२; ९९.३; ११७.७; १२४.२

यन् ३.४.५

यन्ऽइव ९.३.४

यन्त ८.२७.४

यन्त १.८५.१२; ५.४६.२; ६.५१.५; ८.१८.२१

यन्तः १.१४०.१३; ६.२९.१; ७.७४.५; ८.४५.११; ६१.४; ९८.७; १०.१२३.४

यन्तन ५.५५.९; ८.४७.३; १०

यन्तम् १.१०५.१८; ५.५४.६; ६.१.३

यन्तम् ५.६७.२; ६.६७.२

यन्तम् ४.५५.४; ५.६४.२; ८.५.१२; ८५.५

यन्तवे ८.१५.३

यन्ता १.२७.७; १३१.३; १८३.५

यन्ता २.२३.१९; २४.१६; ३.१३.३; ८.७९.३; १०.२२.५; ४६.१

यन्तारः ७.१६.७

यन्तारम् ३.३.८

यन्तारा १.१६२.१९

यन्ति १.९७.५; १००.३; १२२.१३; १२३.१२; १९०.४; ७; २.३५.३; ३.९.३; १४.६; ४.४७.२; ५.६.१; ८.२.१८; ५.३९; ७९.५; ९.९५.३; १०.१८.५; २६.१; ८५.२३; ३१

यन्ति १.५.५; २३.१६; २५.१६; ३१.१०; ३२.८; ५०.२; ७१.३; ८३.२; ९२.१; ११३.११; ११५.३; ११९.२; १२३.८; १२; १२५.४; १४०.७; १६३.१२; १८०.४; २.१३.२; २८.४; ३०.२; ३५.३; ४; ९; ३.८.९; १२.७; ३१.१४; ४०.४; ५१.२; ४.१३.२; ५.१०.५; २१.२; ४१.१३; ४४.१४; १५; ४७.२; ६; ५१.७; ५३.६; १०; ६.९.५; १३.१; २८.४; ३४.१; ७.१.३; १०.३; १५.९; २१.२; ४७.३; ४९.१; ८.३९.१०; ४०.८; ४६.३०[२]; ९३.२२; १००.१; १०३.६; ९.३३.१; ५७.१; ६२.२८; ६९.४[२]; ९; ७२.६; ८१.१; ८६.५; ६; ४७; ९६.२४; ९७.३४[२]; ११३.५; १०.२५.४; ३१.३; ८२.३; ९२.५; ९४.५; १३६.२

यन्तु ७.१०४.५

यन्तु १.४०.१; ८९.१; ९१.१८; १२५.७; १३९.१; १६७.१; ३.२६.४; ३०.२१; ४.५७.८; ५.४३.१; ५८.३; ६२.४; ८७.१;

७.३४.१८; ३७.८; ८.२३.१०; ४४.५; ७१.१०; १००.१२; ९.१०६.१; १०.३१.५; ६४.९; ६६.१०; ८४.१; ८७.१५; १०३.८; १०; १०८.११; १२८.६

यन्तुरम् ३.२७.११; ८.१९.२

यन्तौ १.१३९.४

यन्त्रम् १.३४.१

यन्त्रैः १०.१४९.१

यन्धि ७.८८.६

यन्धि १.१२१.१४; ३.३६.९; १०; ४.२.२०; ३२.७; ६.२४.९; ७.७५.२; ८.६८.१२

यम् १.१.४; १८.४; २४.१२; २५.१४; २७.७[२]; ३०.९; ३१.१६; ३६.१; १०[४]; ११; १९; ४१.१; २; ५; ४९.२; ५२.४; ५८.७; ५९.६; ६०.३; ६४.१३; ७०.४; ७१.६; ९४.१५; ९५.६; १०१.६; १०२.३; ११६.६; १२१.१२; १२७.२; १२८.२; १२९.१; ४[२]; १३५.८; १४३.४; १४४.४; १४८.१; ३; ५; १५१.१; १६६.८[२]; १७२.२; १७६.२; १८२.७; १८६.५; १९०.७; २.२.११; ५.८; ११.१३; १२.५; ८; ९; १७.६; २३.५; २४.४; २७.१२; ३०.६; ३५.११; ३७.२; ३.२.१३; ४.२; ८.११; २९.७; ४३.७; ४६.५; ४९.१; २; ५३.२१; ४.३.२; ३; ६.८; ७.१; ११.६; १३.३; १७.९; १८.४; ३४.३; ३५.४; ३६.५[२]; ६[२]; ३७.६; ३८.३; ३९.२; ४३.२; ५.६.१; २; ७.२; ६; ९.२; ३; १६.१; २०.१; २५.२[२] २८.२; ३१.१; ४०.९; ४३.७; ५३.६; १५; ५४.७; ६२.६; ६३.१; ८६.१; ६.३.१; ९.२; १०.२; ६; ११.४; १३.३; १५.२; १७; १६.४०; १७.१; ११; २४.७; ३४.३; ३८.४; ४४.५; ४८.५; ५८.४; ६६.७; ८[२]; ६८.६; ७.१.५; ६; १२; १६[२]; २३; ४.३; ७.५[२]; २२.१; ३७.७[२]; ३८.३; ४; ४०.३; ४१.२[२]; ४७.१; ५६.१५; ५९.१[२]; ७८.४; ९०.३; ८.२.५; ३५; ३.१०; २१; ४.१६; १२.१३; २४; १३.२३; ३२; १९.२१; ३४; २२.१; २३.८; २७.१७; ३६.१–६; ४३.२७; ४५.९; २१; ४६.४[२]; ४७.१; ६; ४८.१; ४९.५; ५०.५; ५८.१; ६१.१२; ६३.६; ६६.२; ६८.५; ७१.४; ५; ७४.२; ६; ११; १२; ७७.७; ८२.९; ८४.२; ९; ८८.४; ९५.६; ९७.२; १०३.४; ९.६.५; १४.६; ७७.२; ७८.४; ८०.२; ८८.१; ९७.३७; ९८.६; ९९.३; १०२.६; १०.२.७[२]; ४.२; ५; ६.५; ७.४; १६.१३; २०.३; २१.४; २३.३; २८.५; २९.८; ३०.४; ३२.९; ३५.१४[२]; ३९.११; १२; ४२.८; ४६.९[२]; १०; ५३.१; ६३.६; १३; १४[२]; ६९.४; ८५.३; १३; ८६.४; १५; ८८.४; ९; ९६.२; ९७.१७; ९८.८; १०२.१०; १०४.२; ११२.६; १२०.१; १२१.६; १२५.५; १२६.१; १३५.३; ४; १४३.२; १४४.४; ५; १६४.५; १८४.३

यमं १०.१४.५

यम १०.१०.१३; १४.४; ११; १५४.४; ५

यमः ५.६१.२

यमः १.६६.४[२]; १६३.३; १०.१३.४; १४.२; ३; ९; १५.८; १८.१३; ५१.३; ९२.११; ११४.१०; १३५.१

यमः १०.१३४.६;

यमत् ५.३४.२

यमत् ५.४६.५; ८.११.७; ३३.८; ९२.३; ९.४४.५; १०.१४.१४

यमति १.१४१.११

यमति १.१००.९

यमतुः ६.६७.१

यमते १.१२७.३; ६.४५.२३; ७.२७.४; ३७.३; ८.२.२६

यमन् ३.४५.१; ४.४४.५; ७.६९.६; ८.९२.३१

यमम् १.७३.१०; २.५.१; ३.२७.३; ८.२४.२२; १०३.१०

यमम् १.१६४.४६; १०.१४.१; ७; १३; ५८.१; ६४.३

यमम् १०.४९.३

यमय ८.३.२
यमयन्ति १.१६२.१६
यमयोः १०.८.४; ११७.९
यमऽराज्ञः १०.१६.९
यमसानः ६.३.४
यमऽसूः ३.३९.३
यमसे ५.३३.३
यमस्य १.३५.६; ३८.५; ८३.५; ११६.२; १०.१०.७; ९; १२.६; १४.१२; १७.१; २१.५; ५२.३; ९७.१६; १२३.६; १३५.७
यमा २.३९.२; ३.३९.३; ९.६८.५
यमाः १.१६४.१५
यमाःऽइव ५.५७.४
यमात् १०.६०.१०
यमाय १०.१४.१३[२]; १४; १५; १६५.४
यमि १०.१०.१४
यमितवैऽइव १.२८.४
यमिष्ट ५.३२.७
यमिष्ठा ६.६७.१
यमिष्ठासः १.५५.७
यमीः १०.१०.९
यमीमहि १०.३६.८
यमुः ५.६१.३
यमुना ७.१८.१९
यमुनायाम् ५.५२.१७
यमुने १०.७५.५
यमे १०.१४.१६
यमे इवेति यमेऽइव १०.१३.२[२]
यमेन १.१६३.२; ७.३३.९; १२; १०.१४.८; १०
यमौ ६.५९.२
यम्यः ५.४४.४
यम्यम् १०.१०.७
यम्ऽयम् २.२५.१–५
यंयमीति १.९५.७
यम्या ३.५५.११; ५.४७.५; ९.६८.३
यम्याः ४.२२.८; ६.२३.८
यय ८.३४.१–१५
ययु ५.६१.२

ययथुः १.११७.१६
ययन्थ १.५९.१
ययस्तु ७.१०४.२
यया १.६३.८; १२०.५; १७८.१; २.३४.१५[२]; ३.६०.२; ४.२०.९; ५१.६; ५.४५.६[२]; ११; ६.२२.१०; ३७.४; ४१.२; ७.५.८; ८.४२.३; ९.३५.१; ४५.६; ४९.२; ६३.७; १०.९८.३; १०५.१०; १४५.१[२]; १५६.२
ययातिऽवत् १.३१.१७
ययातेः १०.६३.१
ययाथ ३.३३.१०; १०.१७.८
ययाथु ५.२९.९; ६.४०.४
ययाम ७.३८.१
ययिः ५.७३.७; ८७.५
ययिना १०.९२.५
ययिम् १.५१.११; ८७.२
ययियः १०.७८.७
ययिऽवान् ९.१५.६
ययुः २.५.५; ५.८१.३; ७.७४.६; ८.७.२९; ९.८६.४६; १०.१७.४; १५४.२
ययुः १.१६८.४; ४.१९.५; ५.५३.२; १२; ६.६५.२; ७.८३.१; ८.७.२३; ९.६९.९
ययोः २.३२.१; ३.४४.३; ५०.२; ५४.२; ६.६०.४; ७.६५.१; ८.१०.३; ४; ४०.४; ५९.२; ९.५८.४; १०.२२.५; ६५.५[२]
ययौ ३.३३.९
ययौ ४.२६.५; ९.८७.८
यय्यम् २.३७.५
यवऽअदः १०.२७.९
यवऽआशिरः १.१८७.९; ८.९२.४
यवऽआशिरम् २.२२.१; ३.४२.७
यवः १.६६.२; १३५.८; २.५.६
यवन्त ५.२.५
यवम् १.२३.१५; ११७.२१; १७६.२; ५.८५.३; ७.३.४; ८.२.३; २२.६; ६३.९; १०.२७.८; ४३.७; १३१.२
यवऽमत् ८.९३.३; ९.६९.८; १०.४२.७
यवऽमन्तः १०.१३१.२
यवम्ऽइव १०.६८.३

यष्टवे १.१३.६; ४.३७.७

यष्टा २.९.६; १०.६१.१७

यष्टा ६.५२.१

यस्मात् १.१८.७; २.९.३; १२.९; १६.२; ८.४७.१८; १०३.३

यस्मिन् १.५.९; ३३.१४; ४०.५; १३२.३; १६४.२२; ३९; १६८.६; १७४.५; २.२.११; ५.२; १९.१; २०.४; ३.३.३; १६.२; २२.१; ३१.१३; ४९.१; ४.५०.८; ५.१६.३; ३७.४; ४४.९; ५६.८; ९; ६.५.२; १२.२; २९.२; ४; ७.४७.२; ८३.२; १०१.४; ८.२.३३; १६.२; ४१.६; ७०.४; ९२.२०; १०३.१; ९.७१.४; ११३.७; १०.६.३; ६; १२.७; ८; ४२.६; ६१.२५; ६२.११; ८२.६; ८८.९; ९१.१४; ९५.४; १२०.७; १३५.१

यस्मै १.९४.२; १५; १६६.३; १२; ३.३०.७; ५.१.९; ४.११; ७.८; ७.५९.४; ६०.४; ८.३.२३; ४७.४; ७; ५१.४; ६; ५२.३; ६; ८; १०.३१.४; ८६.३; ९७.२०; २२; १८५.३

यस्य १.५.४; ११.८; ३०.५; ३३.३; ५१.१; ५२.१; १४; ५४.३; ५७.१; ३; ७४.४; ८६.१; ३; ७; १००.२; ३; १४; १५; १०१.३^{४}; १२२.१२; १२७.३; ८; १३८.३; १५४.२; ४; १७३.१२; १७६.३; ५; १८७.१; १९०.१; २.१.४; ८.३; १२.१; ७^{४}; १४^{३}; १३.९; ३५.७; ३८.९; ३.६.१०; १३.२; ३२.७ ४३.७^{२}; ५०.१; ५४.१४; ४.२.१०^{२}; ६.७; ९.६; १७.१९; २०.७; २१.१; २; ३४.६; ५.७.२; ५; ९.५; १७.३; २७.५; ३१.१२; ३४.४^{२}; ३७.२; ४८.३; ५४.१५; ६५.१; ८१.३; ८३.५^{३}; ६.३.३; ७; ४.३; १२.३; १४.४; ५; १८.११; २१.२; २२.५; २७.७; ४०.२; ४१.३; ४३.१–४; ४४.६; ४५.८; ३२; ४७.२; ४८.२१; ४९.६; ७.३.३; ४; ६.६; ८.१; ११.२; १५.५; १८.२४; २६.४; २७.४; ३१.७; ३२.१०^{२}; ११; ६१.२; ८२.७; ९२.१; ९७.६; ८.१२.१८; १३.१०; १५.२; १६.४; १९.१०; ११; ३०; ३३; २०.१६; २४.२१; ४१.९; ४५.४२; ४६.३; ५१.९; ५२.४; ५८.३; ६३.१; ६८.३; ८; ११; ६९.१२; ७०.२; ७४.४; १०; ७५.१४; ८४.७; ८६.४; ९३.११; १०२.१४; १०३.११; ९.३५.६; ६५.८; १५; ६६.३०; ८६.९; ९७.३८; १०८.२; १४^{३}; १०.३.५; ६.१; ८.५; ९.३; २०.२; २६.२; २७.११; २९.१; ३३.५; ६; ३४.४; ३७.९; ३९.१२; ४३.६; ५०.१; ६०.४; ६१.५; १४; ८६.१२; १६^{२}; १७^{२}; ८९.१; ६; ९३.८; ९४.१०; ९६.९; ९७.१२; १००.११; १०५.२; १०८.३; ४; ११२.४; ५; ११५.४; १२१.२^{४}; ४^{४}; १४८.१; १५२.१; १५८.२; १६५.४; १८१.१

यस्याः १.४८.१३; ४.२२.२; ५.३.५; ६.६१.८; ७५.१५; ८.९४.२; १०.८६.२३; १२७.४

यस्याम् १०.८५.३७^{२}

यहुः ८.६०.१३

यह्वो इति १.२६.१०; ७४.५; ७९.४; ७.१५.११; ८.४.५; १९.१२; ८४.५

यह्व १०.११०.३

यह्वः ३.१.१२; ५.५; ९; ४.५.२; ७.११; ७.६.५; ८.२; ९.७५.१; १०.११.१

यह्वतीः १.१०५.११; ९.११३.८

यह्वम् १.३६.१; ३.३.८; ४.५.६; ५.१६.४; ८.१३.२०; २४; १०.९२.२

यह्वस्य ३.२.९; २८.४

यह्वाः ४.५८.७

यह्वाःऽइव ५.१.१

यह्वी इति १.१४२.७; ५.५.६; ४१.७; ६.१७.७; ९.१०२.७; १०.५९.८; ९३.१

यह्वीः १.५९.४; ७१.७; ७२.८; २.३५.९; १४; ३.१.४; ६; ४.१३.३; ५.२९.२; ९.३३.५; ९२.४

यह्वीभिः ३.१.९

यह्वीषु ७.५६.२२; ७०.३

यह्वर्यः १०.९९.४

या १.२२.२; ३; २५.११; ४६.२; ६; ४८.६; ५९.३[२]; ८३.३; ८५.१२; ९१.४[३]; १९; ९२.८; १०७.१; १०८.५; १२०.५; १२६.६; १२९.८; १४०.१२[२]; १५१.४; १५५.१; २; १६१.७; १६२.८; १३; १६; १९; १६४.१९; १६५.१०; १७८.२; १८६.११; २.१३.११; २४.५; ३२.६; ७; ८[४]; ३३.१३[३]; ३४.१५; ४१.१८; ३.३७.९; ३९.१; ५४.५; ५७.१; ५; ६; ४.३८.१; ५०.३; ९; ५.२९.१३[२]; १४; १५; ३०.३; १४; ३१.६; ४१.१५; ४३.४; ९[२]; ४५.६; ६१.५; ७; ६८.२; ६९.४; ७३.१०; ७९.२; १०; ८४.१–३; ८६.२[३]; ६.१५.१४; २०.१३; २५.१[२]; ४१.२[२]; ४५.१४; ४८.१२[३]; ५३.९; ६१.१; १३; ६२.१; ५; ६४.५[२]; ६५.१; ६७.१; ४[२]; ६९.२; ७४.२; ७५.१५; ७.४६.३; ५६.२३; ६६.२; ७६.३. ८१.३; ४; ८६.५; ९४.११; ९८.५; १०४.१७; २३; ८.५.१३; १०.४; २१.४; २५.६; ७; २७.६; ३१.५; ३३.१४; ४०.५; ८; ४५.२५; ५९.२; ६१.१८; ९०.३; ९१.६; १००.६; १०१.१३; ९.६१.३०; ८६.१८; १०.१७.८; १९.३; २३.२; ५४.५; ५९.७; ६३.१६; ६५.५; ६; ७२.५; ८१.५[२]; ८५.३७; ८७.१३; ९५.६; १०; १०७.९; ११३.७; १३३.३; ७; १४५.३; १४६.१

याः १.२३.१७; ३२.८; ४३.९; ८४.१०; ९१.९; ११३.१०[२]; १८; १४४.१; १६३.५; १६९.४; १८८.५; ८; २.५.५; ११.२; २३.९[२]; २७.१६; ३२.५; ३.२०.३; २२.३[२]; ५७.३; ४.३२.१०; ४७.४; ५.३३.२; ४४.२; ४६.७[२]; ६.२२.११; २८.५; ५८.३; ६०.८; ७.३.८; ३६.६; ४७.४; ४९.१; २[३]; ३; ५०.४[२]; ५५.८[२]; ६०.३; ९१.६[२]; १०१.१; ८.२.२९; ३०; ३.३; ६.२०; ९.१; ४०.९; ५९.४; ८०.१०; ९७.१; ९.९.४; १९.५; ५३.१; ६२.७; १०.१६.४; ३०.२; ३५.५; ८०.६; ८३.२; ९७.१; १५[३]; १८; १९; २१[२]; १००.१०; १०३.११; १०४.९; १०८.५; ११; १११.८; ९; ११४.२; १६९.२[२]; ३; १७४.२; १८८.३

याचत १०.४८.५

याचतात् ९.८६.४१

याचन् ८.१.२०

याचन्ते ९.७८.३

याचन्ते ८.२.१०

याचामहे १०.२२.७

याचामि १०.९.५

याचिषत् ८.१.२०

याचिषामहे ८.६७.१

याद्र १०.६१.२१

यात् १.८०.१५; ६.२१.६; ७.८८.४[२]; १०.६८.१०

यात् ९.५२.२

यात १.३८.११; ३.३३.१२; ४.३७.१

यात १.३७.१४; ८६.१०; ८८.१; १७१.२; ४.३४.१; ५; ३५.१; ५.४२.१०; ५३.८; ७.३८.८; ५९.४; ८.२७.८; ५७.३; ९.९७.२०

यातः १.३२.१५; १४१.८

यातः १०.८५.१८

यातन ७.५९.५

यातन १.१६५.१३; ४.३४.६

यातम् १.४६.७; १०८.६–१२; ११७.१०; १८४.५; ४.१३.१; ४१.११; ६.६०.३; ८.५.७; ९.११; २२.७; २६.१५; १०.१३१.३; १४३.५

यातम् १.२.५; ६; ३.३; ३०.१७; ३४.४; ११; ४७.२; ९३.११; १०८.१; ४; ११७.१; २; ११८.२; १०; ११; १३७.१; २; १८३.५; ६; १८४.६; २.३९.३; ५; ८; ४१.३; ७; ३.२५.४; ५८.२; ५; ४.१४.१; ४४.४; ५; ४७.३; ५.४३.८; ७५.७; ७६.१; ३; ४; ६.६२.७; १०; ११; ६७.३;

६९.३; ७.५३.२; ६४.२; ६६.१७–१९; ६७.३; ७; ६८.१; ६९.३; ६; ७०.५; ६; ७१.४; ७२.१; २; ५; ७३.५; ७४.३; ४; ९१.५; ६; ९३.६; ८.५.२४; ३२; ८.२–६; ११; १४; ९.११; १४; १०.१; ६; २२.८; १२; २६.७; १४; ३५.७–९; १३–१५; २२–२४; ५७.४; ७३.२; ८५.८; ८७.३; ५; १०१.७; १०.३९.१२; १३; ४१.३; १०६.११

यातय १०.१२७.७

यातयति ३.५९.१

यातयत्ऽजनः १.१३६.३[2]; ३.५९.५

यातयत्ऽजनम् ८.१०२.१२

यातयत्ऽजना ५.७२.२

यातयन् ९.३९.२; ८६.४२

यातयन्तम् ५.३२.१२

यातयमानः ६.६.४

यातयासे ५.३.९

यातवः ७.२१.५

यातवे १.३७.१०; ४४.४; ११३.१६; १५७.१; ५.२९.१०; ८.७.८; १२.३; २०.६; ९.६२.१७; १८; ६३.८; ९; ६५.१६; ७८.२; ९९.२; १०.७५.२; ६; १०६.१; १४३.१

याता ८.७०.१; १०.९९.३

याताऽइव १.७०.६; ७.३४.५

याताः ५.३३.५

याताम् ४.२८.३; ५.५५.१–९; ७.४८.१; १०.१२.५

यातारम् १.३२.१४

याति १.३५.३[3]; ४.१५.२; २९.२; ६.७५.१; ७.४९.३; ७५.६; ८.४५.७

याति १.३५.२; ३; ४८.५; ७; ५०.९; ७७.५; ११३.१४; १२२.१०; १२३.४; १४०.९; १६१.१४[2]; २.२७.१२; १५; ३०.१; ३.२.१०; ५८.८; ६१.४; ४.१३.५; १४.५; ५.६.३; ३१.१; ८०.२; ६.२.२; ५१.१२; ६६.७; ६८.१०; ७.३८.६; ७८.२; ९५.१; ९८.१; ८.४.९; ९.१८; २७.१७; ९.९.१; १५.१; २५.४; ४३.३; ४४.३; ७१.८; ७८.१; ८६.७; १५; ३२; ३३; ९१.३; ९६.२; ९७.४७; ५६; १०७.८[2]; १११.३; १०.८.१; ३२.५; ८०.५; १३९.१; १६८.१

यातु १.३५.१०; ११८.१; १५७.३; ४.१६.१; २०.२; २१.१; ३; ४८.५; ५.४५.९; ७४.८; ७.४५.१; ६९.१; २; ८.२६.४; २७.८; १०.४४.१; ७०.२; ११६.४

यातुः ८.६०.२०

यातुऽजूनाम् ४.४.५; १०.११६.५

यातुऽधान ७.१०४.१५; १६

यातुऽधानः ७.१०४.१५; १०.८७.८; ११; १५–१७

यातुऽधानम् ७.१०४.२४; १०.८७.१२

यातुऽधानस्य १०.८७.५; १०; २५

यातुऽधाना १०.८७.२४

यातुऽधानाः १०.८७.९; १८; १२०.४

यातुऽधानात् १०.८७.७

यातुऽधानान् १.३५.१०; १०.८७.२–४; १३; १४; १९

यातुऽधान्यः १.१९१.८; १०.११८.८

यातुम् ५.१२.२

यातुऽमतीनाम् १.१३३.२; ३

यातुमत्ऽभ्यः ७.१०४.२०; २५

यातुऽमावतः १.३६.२०

यातुऽमावताम् ७.१०४.२३; ८.६०.२०

यातुऽमावान् ७.१.५

यातूनाम् ७.१०४.२१

यात्याः १०.८५.१२

यात्ऽराध्यम् २.३८.८

यात्ऽश्रेष्ठाभिः ३.५३.२१

याथ ६.५०.५

याथ १.३९.१; २.३४.३; ३.६०.४

याथः १.३४.२; १८३.३; ४.४५.७; ६.४९.५; ८.९.१२

याथः १.१३५.७[2]; १८०.९; १८२.२; ३.३३.२; ५.७४.३; ७५.५; ६.६२.२; ६३.२; ८.२६.२

याथन १.२३.११
याथुन १.३९.३; ५.५५.७; ५७.२
यादमानः ३.३६.१; ७.६९.३
यादमानाः ३.३६.७; ६.१९.५; ७.७६.५
यादुरी १.१२६.६
यादृक् ५.४४.६
यादृश्मिन् ५.४४.८
याद्वः ८.१.३१
याद्वम् ७.१९.८; ८.६.४८
याद्वानाम् ८.६.४६
यान् १.७३.८; १२१.१२; २.३४.१४; ३८.३; ३.८.६; ३५.९; ४७.३; ४.३५.७; ६.६६.३; ८.४०.८; १०.१४.३; १५.१३[२]
यानम् ४.४३.६
यानान् १०.७३.७; ११०.२
यानि १.१५.८; ३२.१; ३६.५; ५२.७; १०८.५[२]; १६५.९; १०; २.३०.१०; ३३.१३; ३.१४.७; ४.३२.११; ५.३०.३; ६.३०.२; ५९.१; ७.२६.३; ७०.३; ८.५९.६; ९६.२; ९.६६.३; १०.५०.६; ५४.२; ५; ५६.४; ९१.३; १२८.४
यान्तः ४.२५.८; ८.८३.६
यान्तम् ३.३२.१४; १०.४०.१
यान्ता १.११७.१२
यान्ति १.३७.१३; ८.७.४; २८
यान्तु १.८८.२; १६१.१४
यान्तु १.१६७.२
याभिः १.२३.१७; ३०.१३; ४५.५; ४७.५; ११२.१–३; ४[२]; ५[२]; ६[३]; ७[२]; ८[२]; ९[३]; १०[२]; ११[२]; १२[३]; १३[२]; १४[२]; १५[३]; १६[४]; १७[२]; १८[२]; १९[३]; २०[३]; २१[२]; २२[३]; २३[२]; १४४.२; २.२४.८; ३२.५; ३.६०.१; २; ६.२८.३; ७.३.८; ३७.५; ९२.३; ८.१.८; ८.२०[३]; २१; २०.२४[३]; २२.१०[३]; १२; ९.२.७; ३८.३; १०.३०.४; ५; ५३.१०; ७५.६; १०४.८
याभ्यः ६.४७.३; ७.४७.४
याभ्याम् ८.३८.१०
याम् १.१७.९[२]; ३२.१३; ८०.१६; ३.३८.८; ५३.१६; ६.५३.८; ७.२२.३; ३८.१; ७७.६; ७९.४; १०४.६; १०.१७.९; ६४.१२
यामे २.३४.१०
यामः १.३४.१; १००.२; १६६.४; १७२.१; ४.५१.४; ६.६६.७; १०.२०.९
यामुः ३.३३.६
यामुऽकोशाः ३.३०.१५
यामन् १.३३.२; ३७.३; ८५.१; ११२.१; ११६.१३; १३१.७; १६६.१; १८१.७; २.३६.२; ३.२.१४; २९.६; ३०.१३; ४.२४.२; ५.४४.४; ५२.२; ५८.७; ७३.९[२]; ६.१५.५; ३८.१; ४; ७.५८.२; ६५.१; ६६.५; ८५.१; ८.२२.१४; १०.३.४; ४६.१०; ७७.८; ७८.६; ९४.१३; १२७.४
यामनः ५.५७.३
यामनि १.२५.२०; १३८.२; १६८.५; ३.५४.१४; ४.२७.४; ५.५३.१६; ७.३२.२६; ९.४५.४; १०.६४.१; ७७.४; ८०.५; ९२.१३
यामनिऽयामनि ९.६७.१०
यामऽभिः १.३७.११; ५.५६.४; ६६.५; ८१.५
यामम् ७.५६.६; ६९.२; ८.७.२; ४; १४; ९६.१
यामऽश्रुतेभिः ५.५२.१५
यामऽहूतमा ५.७३.९; ८.७३.६
यामऽहूतिषु ५.६१.१५; ८.८.१८
यामऽहूतौ १०.११७.३
यामात् ३.५३.१९
यामाय १.३७.७; ३९.६; ८.७.५
यामासः ५.३.१२; १०.३.४
यामि १.५८.७; ३.५४.३; ८.३.११; ५३.८; ६१.६; १०.४७.८
यामि १.२४.११; २.१६.७; ५.५४.१५; ७३.२; ६.५१.४; ८.३.९; २७.१; ७३.६; १०.४९.७; ८७.१; ११९.१३
यामे ५.५४.५
यामेन ५.५३.१२

युक्तेन ५.२७.३
युक्तैः १०.११२.४
युक्तौ १०.२७.२०
युक्त्वा १.१६१.७; १७७.१; ३; ५.४०.४
युक्त्वाय १०.९३.१४
युक्ष्व १.१०.३; १४.१२; ८१.३; ९२.१५; ६.१६.४३; ७.४२.२; ८.३.१७; २६.२०; ७५.१; १०.४.६; ११.९; १२.९
युगम् ३.५३.१७; १०.६०.८; ७२.९
युगस्य ८.९१.७
युगा १.१४४.४; १८४.३; २.२.२; ५.५२.४; ७३.३; ६.१६.२३; ८.४६.१२; ६२.९; ९.१२.७; १०.२७.१९; १०१.३; ४; १४०.६
युगाऽइव २.३९.४
युगानि १.९२.११; १०३.४; ११५.२; १२४.२; ३.३३.८; ७.७०.४; १०.१०.१०
युगाय ७.८७.४
युगे १.१५८.६; १६६.१३; १०.७२.१–३
युगेऽयुगे १.१३९.८; ३.२६.३; ६.८.५; १५.८; ३६.५; १०.९४.१२
युगेषु ७.९.४
युङ्क्ते १.१२४.११
युङ्क्ते १.८४.१६; १३४.३
युङ्ग्ध्वम् ५.५६.६[२]
युच्छतः १.२५.६
युच्छन्ति ५.५४.१३
युच्छन्तु ८.३९.२
युच्छसि ८.५२.७
युजः ४.३२.६; ८.८३.२
युजः १.१०.९; ९.७.३
युजत ५.५२.८
युजन्त ६.६६.६; ८.२०.४
युजम् १.७.५; ३३.१०; १२९.४[१]; २.२५.१–५; ४.३७.५; ५.२०.१; ३०.८; ३४.८; ६.४५.१९; ८.६२.६; ७७.७; ९.६५.१२; १०.४२.४; ८९.८; ९२.७
युजा १.८.४; २३.९; ३९.४; १०२.४; २.२३.१०; १८; ४.२८.१; २; ६.४४.२२; ५६.२; ७.१.१३; ३१.६; ३२.२०; ४३.५; ४८.२; ९५.४; ८.१७.३; २१.११; ६३.११; ६८.९; ९२.३१; ३२; ९६.१५; १०२.३; ९.११.९; १४.४; १०.३३.९; ५५.८; ६२.७; ८३.१; ३; ८४.४; १०२.१२
युजाऽइव २.२४.१२
युजानः २.१८.५; ३.५७.४; ४.२.३; ६.३४.२; ३९.२; ४७.१९; ४९.५; ७.६९.५; ७०.२; ८.१३.२७; ५०.७; ९.६४.१९; ८६.३७; ९७.२८; १०.२२.४
युजानम् १.६५.१
युजाना ५.८०.३; ७.७५.४
युजानाः १.१६५.५; ३.४३.६; ६.२९.२; ४४.१९
युजे ७.२३.३; ८.४१.६; १०.१३.१
युज्महे १.१६५.५
युज्यः १.२२.१९; २.२८.१०; ७.२२.२
युज्यते ४.४५.१
युज्यते ५.१.३; ९.७२.१
युज्यध्वम् १०.१७५.१
युज्यन्ते १.१४०.४
युज्यम् १.५२.७; १५६.२; ४.२५.२; ६.५२.१०; ७.३६.७; ८.४.१२; ४६.१९
युज्यमानम् २.४०.३; ७.७८.४
युज्यमाना ३.३५.१
युज्यसे १.२८.५
युज्या ८.९०.२
युज्याताम् ७.४२.१
युज्याभिः ७.३७.५
युज्याय २.२८.३; ७.१९.९; ८.४.१५; ९.६६.१८; ८८.१
युज्याव ८.६२.११
युज्यासः १०.९९.४
युज्येन ६.२१.७
युज्येभिः १.१४५.४; १६५.७; ६.३.८; ७.३९.६
युञ्जते १.४८.४; ८७.३; १३९.४; २.३४.८; ५.८१.१

युवसे ६.४७.१४; ६०.२; १०.१९१.१
युवस्वं ४.४८.५; ८.२६.२०
युवस्व ६.६.७; ३९.१; ७.५.९; ९२.३
युवा १.११.४; १२.६; ८७.४; १४४.४; १५५.६; २.४.५; २०.३; ३.८.४; २३.१; ४.१.१२; ५.१.६; ४४.३; ४५.९; ६०.५; ६१.१३; ७४.५; ६.४५.१; ७१.१; ७.१५.२; २०.१; ८.२१.२; २९.१; ४५.१–३; ६४.७; १०२.१; ९.१४.५; १०.४०.११; ४६.३
युवाकवः १.३.३
युवाकु १.१७.४^{२}; १२०.९
युवाकुः १.१२०.३; ३.५८.९; ७.६०.३; ६७.४; ६८.७
युवाकोः ७.६८.१
युवाऽदत्तस्य ८.२६.१२
युवानः १.६४.३; १५२.५; १६५.२; १६७.६; ३.५४.१०; ५.५७.८; ५८.८; ८.२०.१७; १८
युवानः १.१८६.१; ५.५८.३. ६.४९.११
युवानम् १.७१.८; ११७.१३; ११८.६; २.१६.१; ३३.११; ३५.४; ३.३२.७; ६.५.१; १९.२; ८.४४.२६; ९.९.५; ६७.२९; १०.३२.८; ३९.४; ५५.५; ९२.१४
युवाना १.२०.४; ११०.८; ४.३३.३; ३५.५; ३६.३; ६.६२.४
युवाना १.११७.१४; ३.५८.७; ७.६२.५; ६७.१०; ६९.८
युवाऽनीतस्य ८.२६.१२
युवाभ्याम् १.१०९.४; २.४०.५; ५.६४.४; ८.५.३; १८; २६.१६; १०१.८
युवाम् १.४७.४; १०९.५; ११७.१९; ११९.५; १३९.३^{२}; १५१.८; १८०.८; १८१.९; १८३.५; २.४१.१९; ४.४१.७; ४७.२; ५.७३.९; ६.६०.७; ७.७४.४; ८२.४^{२}; ८३.१; ६; ८.५.१७; ५७.२; १०.३९.३; ४०.४; ५
युवामहे ६.५७.६
युवाऽयवः १.१३५.६
युवाऽयुजम् १.११९.५
युवाऽवते ३.६२.१
युवासे ६.३५.३
युवे ८.१९.३३
युवेथे इति १.१८०.६
युवोः १.३४.१; १०; ४६.१४; ११२.२; ११७.१३; ११९.३; ५; ८; १३९.२; ३; १५२.१; १८०.१; २.२४.१२; ३.१२.८; ५४.३; ५८.२; ६; ४.४४.२; ५.७३.६; ६.५९.९; ६७.११; ६८.१०; ७०.३; ७.६९.४; ७२.२; ८२.८; ८४.२; ९३.८; ८.२२.४; २६.१; १०.४०.६; ७^{२}; ६१.२५; १३२.२; ६
युष्मत् ५.५८.४^{२}; ७.६०.१०; ९५.५
युष्मभ्यम् १.८८.३; १७१.४
युष्मऽयन्तीः २.३९.७
युष्माऽइषितः १.३९.८
युष्माऽऊतः ७.५८;४^{३}
युष्माकं ७.५९.९; १०
युष्माकम् १.३९.२; ४; ११०.७; १२४.१३; २.२७.५; ५.५३.५; ७.५९.२; ८.१८.१७; १०.७७.४; ८२.७; १२६.४
युष्माकाभिः १.३९.८
युष्माकेन १.१६६.१४
युष्माऽदत्तस्य ५.५४.१३; ८.४७.६
युष्मान् १.१६१.१४; ४.२.३; ८.७.६^{३}
युष्माऽनीतः २.२७.११
युष्माभिः ८.६३.१०
युष्मावत्ऽसु २.२९.४
युष्मे इति ४.१०.८; ३७.३; ६.१८.५; ८.१८.१९; ४७.८; ६८.१९
यूथम् ४.३८.५; ५.२.४; ८.४६.३०
यूथस्थे ५.४१.१९; १०.३२.४
यूथा १.८१.७; ८.६१.८; ९.७१.९; ७६.५; ९६.२०
यूथाऽइव १.७.८; ४.२.१८; ५.३१.१; ६.१९.३; २९.५; ४९.१२; ७.६०.३; ८.२५.७
यूथानि ८.४.२०

यूथे १.५८.५; १६४.१७; ३.५५.१७; ९.७७.५; ११०.९
यूथेन १.१०.२
यूथेषु १०.८६.१५
यूथ्यः ९.१५.४
यूथ्या १०.२३.४
यूथ्याम् ८.५६.४
यूनः १.११२.२१; ३.४६.१; ६.५१.४; ८.२०.१९
यूना ९.६८.५
यूने १.५३.१०; ६३.३; ९१.७; १७४.२; ५.३६.६; १०.३०.६
यूपः १.५१.१४
यूपऽव्राहाः १.१६२.६
यूपऽव्रस्काः १.१६२.६
यूपाऽइव ४.३३.३
यूपात् ५.२.७
यूयम् १.१५.२; ३८.४; ८६.९; १६६.६; १७१.२; २.२८.३; २९.२^{३}; ३; ४; ४.३६.८; ३७.६; ५१.५; ५.५४.१४^{४}; ५५.५; १०; ५८.४; ५९.४; ६१.१५; ८७.९; ६.२८.६; ५०.७; ५१.६^{२}; १५; ७.१.२०; २५; ३.१०; ४.१०; ७.७; ८.७; ९.६; ११.५; १२.३; १३.३; १४.३; १९.११; २०.१०; २१.१०; २२.९; २३.६; २४.६; २५.६; २६.५; २७.५; २८.५; २९.५; ३०.५; ३४.२५; ३५.१५; ३६.९; ३७.२; ८; ३९.७; ४०.७; ४१.७; ४२.६; ४३.५; ४५.४; ४६.४; ४७.४; ४८.४; ५१.३; ५३.३; ५४.३; ५६.२५; ५७.७; ५८.६; ६०.१२; ६१.७; ६२.६; ६३.६; ६४.५; ६५.५; ६६.१२; ६७.१०; ६८.९; ६९.८; ७०.७; ७१.६; ७२.५; ७३.५; ७५.८; ७६.७; ७७.६; ७८.५; ७९.५; ८०.३; ८४.५; ८५.५; ८६.८; ८७.७; ८८.७; ९०.७; ९१.७; ९२.५; ९३.८; ९५.६; ९७.१०; ९८.७; ९९.७; १००.७; १०१.६; ८.७.१२; १९.३५; २०.१६; २३; ४७.८^{२}; ६७.१९; ८३.३; ९; ९.६९.८; ९०.६; ९७.३; ६; ९८.१२; १०.६४.१२; ६५.१५; ६६.१५; ७७.५; ६; ९७.२; ९; १२२.८; १२६.२; ४; १३६.३
यूयाः ७.१०४.१५
यूयोत् १०.९५.१२
यूष्णः १.१६२.१३
ये १.७.७; ८.६; १४.६; ८^{२}; १९.३–८; २०.२; २४.६; १०; २५.९; ३३.१०; ३४.९; ३५.११; ३७.२; ४८.३; ४; ११; १४; ५१.५; ८; ५३.११; ५४.८; ५५.७; ५७.४; ६०.२; ६७.४; ६८.५; ७२.९; ७७.४; ८३.४; ८५.१; ४; ९४.९; १०१.१०; १०५.५; ९; १०; ११०.६; ११३.११^{२}; ११८.४; १२४.१२; १२६.५; १३५.९^{२}; १३९.११; १४१.१३; १४७.३; १६१.५; १६२.६^{३}; १२^{३}; १६४.३; १९^{२}; २३; ३९; ४५; १६६.४; ११; १६८.२; ३; १६९.५; ७; १७३.७; १७४.१; ६; १७[illegible].२; १७३.२; १९०.५; ६; १९१.७^{३}; २.१.१६; २.१३; ११.१३; १४; १६; १९; २३.१४; १६; २४.६; २७.१०^{२}; २८.७; ४१.१; ३.६.८^{३}; ७.१; ८.७; १६.२; २२.३; २४.४; ३२.३^{२}; ४; ३५.९; ३९.४; ४३.६; ४७.३; ४^{४}; ६१.२; ४.४.१३; ५.४; ६.१०; ८.५^{२}; ६; १६.६; १८.४; २३.५; ३२.३; ३३.१; ३; ८^{२}; १०^{२}; ३४.९^{७}; १०^{२}; ३५.८; ३६.२; ४५.४; ५०.२; ५४.६; ५५.२; ५.२.५; ६.७; ८; १०.३; ४; १५.२; १६.५^{२}; १८.४; ५; २०.२; ३१.५; १३; ३२.१२; ३३.५; ३८.३; ४१.२; ५; ९; १३; ४२.८^{२}; ९; १२; ४९.५^{२}; ५०.२; ५२.१; ४; ५; ७^{२}; १३; १६; ५३.३; ४^{२}; ५६.२; ४; ५८.१–३; ५९.२; ७; ६०.२; ६१.१; ११; ७९.४; ६; ७; ८७.२^{२}; ३; ६.६.४; १०.५; १६.४३; २१.५; ११^{२}; १२; २५.३; ७; २७.१; २; ३६.१; ४६.१०; १४; ४८.८; ५०.२; ५२.९; १३^{३}; १५;

६३.८; ६४.६; ६६.२–५; ९; ६७.९; ७.१.९; १०; २.२; ७.६[३]; १६.७; १०; १८.१२; २१; १९.९; २०.१०; २१.१०; २२.९[२]; २५.२; ३०.४; ३२.१५; १७; ३४.२४; ३५.१४; १५; ३८.५; ४२.२; ५६.१६; ५७.१; ७; ५८.२; ६२.४; ६६.५; ६; १०; ११; १३; ६७.८; ९[२]; ७४.४; ६; ८७.३; ९०.६; ९१.१; ९२.४; ९६.५; १०४.९[२]; १८[२]; ८.१.९[३]; २.३९; ६.१२[२]; १८[२]; ७.१६; ९.३; १३.२८; १८.२२; १९.१७; १८; २०.१८[२]; २०; २८.१; ३०.२; ४; ३४.१७; ४५.१; ४६.१८; ४९.३; ८; ५०.८; ५३.३[२]; ६; ५७.३; ६७.१३; ९३.६[२]; ९४.९; ११; ९६.७; ९७.१; १०३.१३; ९.४१.१; ६१.५; ६५.२२[३]; २३[२]; ७३.५; ६; ७५.५; ७७.३; ८६.४; ९१.४; ५; ९७.२०; २८; ११४.३; १०.२.१; १०.८; १३.१; १४.३; १०; १५.१; २[४]; ३; ८–१०; १३[२]; १४[२]; १९.७; २०.८; २७.६; २८.११; १२; २९.५[२]; ३२.२; ३६.१०; १३; ४०.१०; ४४.६; ७; ४८.६; ५०.३[२]; ७; ५३.५; ८; ५५.७; ६१.१०; १४; २७[२]; ६२.१–३; ६; ६३.१[२]; २[२]; ५; ८; ६४.६; ६५.३; ९[२]; १५; ६६.१; २; १५; ७१.९; ७२.८; ७३.३; ७४.१[२]; ३; ४[२]; ७६.८; ७७.३; ७८.२–५; ८२.४; ८५.१७; ३१; ३२; ८९.८; ९; १५; ९०.७; ८; १०; ९२.७; ९३.१४; ९६.२; १०७.२; ४; ९; १०८.७; १०९.४; ११५.७; ११६.९; १२८.९; १३०.१; ६; १३१.२; १४७.३; १४८.३; १५४.२[३]; ३[३]; ४; ५; १७६.१; १८२.३

ये इति १.१५९.१; १८५.६; ७; ९.६६.२

येजे ६.३६.२

येतिरे १.६४.४; ८५.८; ५.५९.२; ८.२०.१२; १०.७७.२

येन १.८.२; ३४.९; ४२.५; ४७.९; ५०.६; ५६.३; ६१.६; ६२.२; ६३.२; ७२.८; ८०.२; ९२.१३; ११७.२; १६०.५; १६४.२९; ४९; १६६.१४; १७१.५; १८२.५; १८३.१; ३; १८६.५; २.११.१८; १२.४; १७.६; ७; २४.१०; ३०.५; ३.२२.२; २९.९; ३१.९; ६०.२; ६२.१; ४.९.८; ३६.९; ४३.६; ४५.७; ५१.४; ५३.१; ५.४५.७; ५३.१३; ५४.१५; ७७.३; ८७.५; ६.१६.४८; १७.१०; १९.७; ८; २७.४; ४४.३; ४६.५; ४९.१५; ५१.१६; ७.१.२४; २२.२; ५६.२४; ६९.२; १०४.४; ८.३.९[२]; १०; ५.३९; ६.११; ७.१८[२]; ९.४; १२.१; २[२]; ३; ४; १३.२१; १५.५; १७.१०; १९.१६[२]; २०; २४.२५; २७.२२; ४०.१; ६०.१२; ७६.४; ८९.१; ९.७४.५; ९७.३९; ५१; १०१.९; १०८.४[३]; १४; १०९.१४; १०.३७.४; ४१.२; ४४.९; ५१.१; ५२.१; ५३.४; ७; ९; १०; ५५.२[२]; ४; ८५.२४; ८७.१२; १०२.९; ११४.७; ११६.३[२]; १२१.५[३]; १२६.२; १५९.४; १७०.४; १७४.१; ४

येभिः १.१०९.७; १२१.६; १७४.३; २.३७.३; ३.३.१०; ३२.४; ३६.२; ६.१७.५; ७.१.७; ८.५.८; २२.७; ३८.५; ४९.८[२]; ५०.८[२]; ६२.४; ९.७०.३; ७९.२; १०.२.४; ५४.४; ५५.७; ८५.२३; ९२.५; ९; १५; ११२.२; ११३.१०

येभ्यः १०.६३.३; ७; १५४.१

येम ८.२७.२०

येमतुः १.११९.५; ५.६१.९

येमथुः ८.२५.६

येमथुः १.३०.१९; ५.७३.३

येमाते इति ४.४८.३

येमानः ४.२३.१०; ४४.३; ९.७५.३; १०७.१६; १०९.८; १८

येमानम् ४.१.१५

येमिम ८.२१.४

येमिरे १.१३५.१; ८.७.५

येमिरे १.१०.१; २.५९.८; ६०.६; ८.३.६;

४.५०.२; ५.२१.४[2]; ४७.३; ६७.२; ६.१५.१६; १६.३५; ७.४.५; ७०.१; ९७.४; ८.२९.२; ९.१.२; २.२; ८.३; १९.३; २५.२; ६; ३२.४; ३७.२; ३८.६; ४०.२; ५०.४; ६१.२१; ६२.४; ६४.११; १७; २०; २२; ६५.१९; ६६.१२; ७०.७; ७१.६; ८०.२; ८२.१; ९७.४५; १०१.१४; १५; १०७.४; १०.१७.११[2]; १८.७; ३४.११; ६५.७; ६८.४; ९१.४; ९६.२; ९९.२; १०७.९; १२३.२; १४८.५; १६२.१; २; ४; १८४.१

योनिषु १.१५.४; २.३६.४; १०.४०.११; ६३.१५; १२३.५

योनेः २.९.३; ३५.१०

योनौ १.६३.४; ६६.३; ७९.३; १०४.७; १४४.२; १४९.२; १७४.४; १७८.२; ३.१.७; ११; २९.८; ६२.१८; ४.१.११; १६.१०; १७.१४; ६.१६.४१; ७.३.५; ९.१३.९; २५.३; २८.३; ३९.६; ९२.२; १०.८.३; १०.७; ३१.६; ४६.६; ६१.६; ७०.६; ८५.२४; १०१.३; ११०.६; १२३.६

योन्यम् ८.४५.३०

योपर्यन्तः १०.१८.२

योपयामसि १०.१३४.७

योयुवतीनाम् ८.६९.२

योयुवे १०.९३.९

योषणः १.१४१.२; ४.५.५; ९.१.७; ६.५; ३२.२; ३८.२; ५६.३; ६८.७

योषणा ८.८.१०; ४६.३३; १०.११.२; ४०.६

योषणा ५.५२.१४

योषणाः ३.५६.५

योषणाम् ३.५२.३; ६२.८; ४.३२.१६; ९.१०१.१४; १०.३९.७; १४

योषणासु ७.९५.३

योषणे इति ७.२.६; १०.११०.६

योषत् २.१८.८; ३३.९; ४.२.९; ८.१.२७; ३१.१७

योषति ८.३१.१७; ३३.९

योषा १.९२.११; १०१.७; ११९.५; १२३.९; ११; १६७.३; ३.३३.१०; ३८.८; ४८.२; ५.७८.४; ६.७५.४; ७.६९.४; ७५.५; ७७.१; ९.३२.५; १०.१०.४; २७.१२; ४०.२; ९; १२३.५

योषाऽइव १.४८.५; ५.८०.६; ६.७५.३; ९.४६.२; ९६.२४

योषाः ४.५८.८; १०.१६८.२

योषाम् १.५६.१; ११५.२; ११७.२०; ४.२०.५; ९.९३.२; १०.३.२; ५३.११

योषितम् ९.३८.४

योषे इति १.१०४.३

यौ १.२३.५; ९२.१७; ११६.१; ६.६७.३; ७.६८.८; ८४.२; १०.१४.११; ६६.७

यौः २.३२.२

यौषुः १०.२३.७

यौष्टम् ८.८६.१–५; १०.८५.४२

र

रंहते ९.९७.९

रंहमाणः ९.११०.३

रंहमाणा ९.१००.४

रंहयः ९.८६.४७

रंहयन्तः १.८५.५

रंहयन्ते ८.१९.६

रंहिः १०.९५.३; १७८.३

रंह्यः २.१८.१

रंह्यम् १०.१४७.४

रंह्या ४.१.३[2]; ९.२.१; ६.८; १०६.१३; १०.९६.४

रक्ष १.१८.३; ३५.११; ५४.११; ९१.८; १७४.१; ३.१.१५; ४.३.१४; ६.८.७; १६.३०; ७१.३; ७५.१०; ७.१५.१३; ८.८४.३; ९.२९.५; ६१.३०; १०.४.७[2]; ६१.२२

रक्ष १.३१.१२; ९.११४.३; ४; १०.५३.६; ८७.९; २०

रक्षः १.२१.५; ८६.९; १३३.५; ३.३०.१६; १७; ४.३.१४; ६.१८.१०; ७.१०४.१;

रघुपत्मऽजंहाः ६.३.५
रघुऽपत्वा १०.६.४
रघुऽपत्वानः १.८५.६
रघुम् ८.३३.१७
रघुऽमन्यवः १.१२२.१
रघुऽयत् ४.५.९
रघुऽया २.२८.४
रघुऽयामा ९.३९.४
रघुऽवर्तनिः ९.८१.२
रघुऽवर्तनिम् ८.९.८
रघुऽस्यत् ४.५.९
रघुऽस्यदः १.६४.७; ८५.६; १४०.४; ८.३४.१७
रघुऽस्यदम् ३.२६.२; ५.२५.६; ७३.५
रघू इति १०.४९.२
रघ्वी इति ६.६३.९
रघ्वीःऽइव १.५२.५; ४.४१.९
रजः १.५०.७; ५६.५; ५८.१; ५; ६२.५; ८१.५; ८३.२; ८४.१; ९०.७; ११०.६; १३९.४[2]; १४१.७; २.३१.२; ३.१.५; ४.३६.१; ४५.२; ६; ५.४८.२; ५३.७; ५९.१; ६.६१.११; ७.६६.१५; ८७.२; ८.८८.५; ९.२२.४; ५; ६३.६; ६८.९; ७२.८; ७७.२; १०७.२४; १०.३७.३; ५६.५; ६६.११; १०५.७; १२९.१; १४३.२; १४९.२
रजःऽइषितम् ८.४६.२८
रजःऽतुरम् १.६४.१२; ९.४८.४; १०८.७
रजःऽतूः ६.२.२; ६६.७
रजःऽभिः १.११६.२०; ६.६२.२; ६
रजःऽसु ७.३४.१६; ८.७७.५; १०.४३.८
रजतम् ८.२५.२२
रजसः १.६.१०; १९.३; ३३.७; ५२.६; १२; १४; ७९.१; ९२.१; १२४.५; १६०.१; १६४.१९; १६८.६; २.२.३; ४०.३; ३.२६.७; ४९.४; ४.१.११; १७.१४; ५.४७.३; ४८.१; ५९.३; ६९.४; ६.६२.९; ७१.१; ७.३५.५; ६४.१; ८७.६; १००.५; ८.५७.३; ५९.२; ९.६२.१४; ८६.३०; १०.८.६; २७.७; ४९.६. ५३.६; ९५.१७; १२१.५; १२३.१; १३९.५; १४३.५; १८७.५
रजसा १.३५.२; ९; १६४.१४; १०.३२.२
रजसि २.२.४; ९.७४.६; १०.१५.२; ४५.३; ८२.४; १२३.८
रजसी इति १.१६०.४; ४.४२.३; ६; ५६.३; ६.९.१; १५.९; ७.८०.१; ९९.१; ९.६८.३
रजांसि १.३२.१४; ३५.४; १४६.४; १५४.१; १६४.६; १६६.३; ४; १८०.१; १८१.५; १८७.४; २.३९.७; ३.४.४; ३०.२; ५८.५; ६२.१६; ४.४५.७; ५३.३; ५; ५.५४.४; ६३.५; ६९.१; ७३.३; ८१.३; ६.७.७; ३०.३; ३१.२; ४९.१३; ६९.५; ७.२१.६; ६८.३; ८.४३.६; ७३.१३; ८२.९; ९.३.७; ८; १०.७५.७; १११.२; ४
रजिम् ६.२६.६
रजिष्ठम् १.९१.१
रजिष्ठया १०.१००.१२
रजिष्ठाः ७.५१.२; ९.९७.२८
रजिष्ठाम् ९.८९.२
रजिष्ठैः १.७९.३; ८.१०१.१०
रजी इति १०.१०५.२
रज्जुः १.१६२.८
रज्या १०.१००.१२
रण ९.७.७
रण ५.५१.८–१०; ८.१२.१७; १३.९
रणऽकृत् १०.११२.१०
रणत् ८.९३.२०
रणन् ४.३३.७; ५.५३.१६; १०.२५.१
रणन्त ७.५७.५
रणन्ति ८.९२.२०; ९.१११.२
रणन्ति ३.७.५
रणम् ८.९६.१६; १०.११२.१०; ११३.४
रणय ८.३४.११
रणयन् १.१००.७
रणयन्त १.१४७.१; ३.५७.२; ४.७.७; १०.१४८.३

८.२२.४; ७२.६; ९१.७; १०.२६.८; ५९.१; ११४.१०; १३२.४; १६८.१
रथा ७.१८.२२
रथाः १.३८.१२; १८६.८; ४.१४.४; ४५.२; ५.३३.५; ५५.१–९
रथाःऽइव ४.१९.५; ७.७४.६; ८.३.१५; ९.१०.१; २; २२.१; ६७.१७; ६९.९
रथात् ५.३६.३
रथान् १.११२.२२; २.८.१; ५.५३.५; ६.४७.२४
रथानाम् १.४८.३; ४.३८.६; ५.५२.९; ५३.१०; ६६.३; ७४.८; ८६.४; ७.३२.११; ४४.४; ८.२३.२; ६८.४; ९४.१; १०३.१०; ९.९६.१; १०.२६.५; ७८.४; १०३.४; १०; १७८.१
रथान्ऽइव १.१३०.५[२]; २.२३.१३; ५.७३.१०; ८.१२.३
रथाय १.१११.३; १४०.१२; ५.३१.१; ८.६८.१३
रथासः १.१२६.३; २.१२.७; ४१.१; १०.१४२.५
रथिऽतमः ६.४५.१५; ५६.२; ३; ८.४५.७; ६१.१२; ९.६६.२६
रथिऽतमम् १.११.१; ६.५५.२; ८.९९.७
रथिऽतमा १.२२.२; १८२.२
रथिऽतरः १.८४.६
रथिनः १.१२२.८; ६.२७.८. ४७.३१; ९.९७.५०
रथिनम् १०.४७.५
रथिनाम् १.११.१; ८.४५.७
रथिनीः १.९.८
रथिने १०.४०.५
रथियन्तीऽइव १.१६६.५
रथिरः ३.१.१७; ३१.२०; ९.७६.२; ९७.४६; ४८
रथिरम् ३.२६.१; ७.७.४
रथिरा ७.६९.५
रथिरायताम् ९.९३.४
रथिरासः ८.५०.८; ९.९७.३७; १०.७६.७

रथी ८.४.९
रथीऽइव ५.८३.३; १०.५१.६
रथीः १.२५.३; ४४.२; ७७.३; ३.२.८; ३.६; ३०.११; ४.१०.२; ६.५.३; ४८.९; ५५.१; ८.११.२; १०.१०२.२
रथीःऽइव ४.१५.२; ५.६१.१७; ८.७५.१; ९५.१; ९.६४.१०
रथे १.६.२; १३.४; १४.१२; १६.२; ३४.२; ४७.३; ६; ५०.८; ९४.१०; ११८.४; १३४.३; १३९.३; ४; २.१८.३; ३४.७; ३.३५.१; ४१.९; ४.४४.२; ५.१७.४; ४३.५; ५४.११; ५६.६; ७५.४; ६.२९.२; ४७.१९; ५५.६; ५९.५; ७५.६; ७.३२.२; ६६.१५; ८.१.२४; २५; ३१; ७.२८; २०.८; २२.९; २६.२३; ६५.४; ८५.७; ९८.९; ९.२१.४; ६२.१७; ८९.४; ९८.२; १०.३३.५; ६४.१२; ९६.६. १२
रथेन १.२२.४; ३४.१२; ३५.२; ४७.२; ७; ९; ४८.१०; ११३.१४; ११६.१; २०; ११७.१५; ११८.२; ३; १०; १२३.५; ७; १२५.३; १३४.१; २.२७.१२; १६; ३.३३.९; १०; ५३.१; ५८.३; ४.४.१०; १४.१; ३; ४४.४; ५; ४६.५; ४८.१–४; ५.३१.९; ८३.७; ६.४५.१५; ६२.१०; ७.६७.३; ७१.२; ७२.१; २; ७५.६; ७८.१; ८.५.२; ३५; ८.२; ११; १४; २०.१०; २२.१५; ५७.१; ७३.२; ८५.८; १०.३९.७; ७०.३; ८५.२६; १०३.४
रथेभिः १.४८.७; ८८.१; १००.१०; २.१५.४; ५.५.३; ५८.६; ६.७५.७; ८.७०.१; ९.१५.१
रथेभ्यः १.९४.११
रथेऽशुभम् १.३७.१; ५.५६.९
रथेषु १.३९.६; ६४.९; ८५.४; ५; ८७.२; १६६.९; २.३४.८; ५.५३.२; ४; ५६.६; ७; ५७.६; ६०.२; ४; ६१.१२; ८.२०.१२
रथेऽस्थाः १.१७३.४; ५; ६.२९.२
रथेऽस्थाम् ६.२१.१; २२.५; ८.३३.१४; ९.९७.४९

रप्शदूधऽभिः २.३४.५
रप्सुदा ८.७२.१२
रफितार्य १०.११७.२
रभः १.१४५.३
रभःऽदाम् ६.२२.५
रभध्वम् १०.५३.८; १०३.६
रभन्ते ३.२९.१३
रभसम् २.१०.४; ३.३१.१२; ६.६१.१
रभसस्य ९.७३.६
रभसा ३.१.८
रभसाः १.८२.६; ५.५४.३
रभसानः ६.३.८
रभसानि ९.९६.१
रभसाय १.१६६.१
रभसासः १.१६६.१०; १०.९५.१४
रभस्व १०.८७.२; ८; १५५.३
रभस्वतः १.९.६
रभस्वतऽभिः १०.३.७
रभस्वान् १०.३.७
रभामहे ६.५७.५; १०.१३३.६; १३४.७
रभिः ८.५.२९
रभिष्ठाः ५.५८.५
रभे ३.५३.२
रभेमहि १.५३.४; ५[2]; ८.३२.९
रभ्यसः १.१२०.४
रमते ८.१०१.४
रमते २.३८.२; १०.१४५.४
रमध्वम् ३.३३.५
रमन्ते २.३०.१; १०.१११.९
रमय ५.५२.१३
रमय १०.४२.१
रमयः १.१२१.१३
रमयत् १.५६.३
रमयन्ति ७.५६.१९
रमस्व १०.३४.१३
रम्वते १०.८६.१६; १७
रम्भम् ८.४५.२०
रम्भिणीऽइव १.१६८.३

रम्भी २.१५.९
रम्ऽसु २.४.५
रम्ऽसुजिह्वः ४.१.८
रयिः १.६६.१; ७३.१; १२७.९; २.१.१२; ३.६२.३; ४.२.५; ७; ११.४; ३६.५; ५.२५.७; ५०.५; ६.१३.१; १४.५; १५.१२; २०.१; २१.१; ६८.७; ७.४.९; १५.५; ३२.२१; ८४.३; ८.३१.११; ५१.९; १०; ९.५.३; १०१.७; १०.१९.३; ११७.१
रयिःऽइव १.१२८.१
रयिणा १०.१२२.३
रयिऽदौ ३.५४.१६
रयिम्ऽतमः ६.४४.१
रयिऽपतिः १.६०.४; ७२.१; २.९.४; ४०.६; ९.९७.२४
रयिऽपते ६.३१.१
रयिऽभिः १.६४.१०
रयिम् १.१.३; ८.१; १२.११; ३०.२२; ३४.५; १२; ४७.६; ४८.१३; ५८.६; ६४.१५; ६८.३; ७९.८; ९; ८५.१२; ९२.८; ९७.१; ११६.३; १९; ११७.२३; १२९.७; १३३.७; १४१.११; १५९.५; १६२.२२; १६९.४; २.२.६; ४.८; ७.१; ११.१३; १५.५; १९.५; २५.२; ३०.११; ४०.६; ४१.९; ३.१.१९; १४.६; २४.५; ४५.४; ५१.५; ५४.१३; ५५.२२; ४.१२.२; ३३.८; ३४.२; १०; ३५.६; ३६.८; ९; ३७.५; ८; ४४.६; ४९.४; ५०.१०; ५१.१०; ५३.७; ५.४.७; ११; ९.७; १०.७; २०.१; २३.१; २; २४.१; ३३.६; ४१.५; ४२.१८; ४३.१७; ५४.१४; ७६.५; ७७.५; ८०.३; ८६.६; ६.१.३; ५.७; ६.७; ८.५; १०.५; १६.२०; २८; २९; २८.२; ४७.६; ४९.१५; ५९.९; ६४.४; ६५.६; ६८.५; ६; ८; ७०.६; ७.१.५; २४; ५.९; १६.९; २०.७; ३६.७; ३७.६; ३९.६; ४२.६; ७५.२; ७६.७; ७७.६; ८४.४; ९२.३; ९३.४; ९७.१०;

राधसा १.४८.१४; ५४.७; ९४.१५; १३५.४[२]; ३.३०.२०; ५०.४; ४.५५.१०; ५.४३.९; ६.४.७; १०.५; ८.१.१४; २३; २४.१३; ८१.४; ५; ९७.६; १०.२३.१

राधसाम् ८.९०.२

राधसि ४.३२.२१

राधसे १.१७.७; ८१.८; १३९.६; ३.४१.६; ५१.१२; ४.२०.२; २४.१; २९.३; ५.३५.४; ६.३८.५; ४५.२७; ७.७९.५; ८.१.६; २.२९; २४.१०; १२; ४५.२४; ४९.३; ६४.१२; ६८.७; ७०.९; ९३.१६; ९.८.३; ६०.४; ९७.४२; १०.१७.१३

राधांसि १.२२.८; ८४.२०; ५.८९.६; ७; ६.४४.१२; ४८.९; ७.१५.११; १६.१०; ३७.२; ८; ८.६.४६; ८.१३

राधानाम् १.३०.५; ३.५१.१०

राधाम् १.४१.७; ८.७०.१३

राध्यः १.१५६.१

राध्यम् १.११६.११; ८.९२.२८

राध्यस्य १०.७७.६

राध्या २.२४.१०

राध्यानि ४.११.३

रान्द्र्या ६.२३.६

राम् १०.१११.७

रामम् १०.३.३

रामीः २.३४.१२

रामे १०.९३.१४

राम्याः २.२.८

राम्याणाम् ३.३४.३; ७.९.२

राम्यासु ६.६५.१

राय ७.५५.३

रायः १.३१.१०; ६२.१२; ६८.५; ९८.३; १२३.१३; १६७.१; १६९.५; ३.१६.२; ४.८.७; ४१.१०; ४८.१; ५.४२.८; ५४.७; ६.१.५; १४.३; १९.५; ३६.१; ५; ४७.९; ७.१८.२०; ३४.२२; २३; ३५.२; ३७.८; ८.५२.१०; १०.११७.५; १४०.४

रायः १.४.१०; १७.३; २४.५; ३३.१; ३६.१२; ५१.१४; ७२.८; ७३.९; १०; ८१.७; ९१.२३; ९६.६; ११३.४; १२५.१; १२७.११; १३८.३; १४९.१; १६६.३; २.१.१०; २.१२; ९.५; ११.१२; २४.१५; २७.१७; २८.११; २९.७; ४०.४; ३.२.१५; १६.१; ३; १९.३; ३०.१८; ३६.१०; ५४.२१; ५६.६; ४.२.२०; ४.६; १२.३; १७.११; २०.७; ८; २१.४; १०; २९.५; ३३.१०; ३६.६; ४१.१०; ५.१२.३; १५.१; ५; २५.३; ३३.१०; ३६.४; ४१.५; ८; ४२.५; ४९.४; ५४.१३; ६८.३; ६.४.८; ११.६; १२.६; १५.३; २२.३; २३.१०; ३६.४; ४४.२; ४८.९; ५०.११; ५४.८; ५५.२; ३; ७.४.६; ७; ८.३; १८.३; २०.९; २८.५; २९.५; ३०.१; ५; ३२.१९; ३४.२४; ३७.५; ४०.३; ५६.१५; ५७.६; ६०.११; ७५.५; ९३.२; ९५.२; ९७.४; १००.२; ८.३.२२; ४.१६; २३.२७; २९; २६.२२; ३२.१३; ४६.६; ४७.४; ४८.७; ५१.६; ५२.६; ५३.१; ५६.२; ५९.७; ७१.४; ९२.९; ९५.४; ९७.१५; ९.३३.६; ३५.२; ६१.२६; ८९.७; ९४.३; १०.१७.९; २२.१५; ३०.१२; ३५.७; ३६.७; ४३.३; ९३.६; १२२.८; १३९.३; १४१.२; ६; १४७.४; ५

रायःऽकामः १.७८.२; ७.३२.३; ४२.६

रायतः १.१८२.४

रायसि ७.५५.३; ४

राया १.४८.१; १६; ५३.५; ७१.६; १२९.९; १०; ३.१६.६; २३.२; ४.२.९; ५.१५; ८.६; ३१.१२; ४२.१०; ५.३.६; १०.१; ३०.१; ५०.२; ६.५.५; १३.३; १५.११; १८.७; ११; १९.१३; २०.६; ३५.१; ४९.१३; ७.४३.५; ६६.८; ६७.९; ७२.५; ७३.५; ९५.४; ८.५.३२; २४.१५; २६.७; ४६.५; ९७.६; १०.४२.९; ९३.१०; १३

रायाम् ९.१०८.१३

राये १.५.३; ९.६; १०.६; ५४.११; ७३.८; ८४.१७; १००.१६; ११३.५; ११६.९; १२०.९; १४२.१०; १८९.१; २.३.४;

रिपुणा ४.५८.५
रिपुम् ५.७९.९; ६.५१.१३; ८.१८.१४; ९.८३.४
रिपूणाम् ८.६७.९
रिपोः ४.३.१३; ८.११.४
रिप्तम् १.१६२.९
रिप्रम् ९.७८.१; १०.१७.१०
रिप्रऽवाहः १०.१६.९
रिभ्यते ७.७६.७
रिरिक्वांसः १.७२.५; ४.२४.३
रिरिक्षतः ७.३६.४
रिरिक्षति ८.१८.१३
रिरिक्षन्तम् १.१२९.१०
रिरिक्षे ८.८८.५
रिरिक्षोः १.१८९.६
रिरिचथुः ४.२८.५
रिरिचाथे इति १.१०९.६
रिरिचानः १०.८९.१
रिरिचे ६.२१.२
रिरिचे १ ५९.५; ६१.९; १०२.७; १६४.२५; ३.४६.३; ६.२४.३; ३०.१; ७.४२.३; १०.३२.५; ८९.११
रिरिच्यात् ४.२४.५
रिरिच्याम् १०.१०.७
रिरित्रे १०.७७.३
रिरिपुः ५.८५.८
रिरिषः १.१०४.६; ११४.७; ८; ७.४६.३; ८९.५; १०.१८.१; १२८.८
रिरिषत् ३.५३.२०
रिरिषत १.८९.९
रिरिषीष्ट ६.५१.७; ८.१८.१३
रिरिषेः १.१२९.१०
रिरिह्वांसम् १०.७९.३
रिरीहि ६.३९.५; ४६.८; ६५.६; ९.११.९; ९१.६; १०.९८.१०; १६९.३
रिरेच ४.१६.६
रिरेभ १.१२०.६
रिशन्ताम् १०.१६९.१
रिशन्तीः ६.२८.७

रिशादसः १.१९.५; २६.४; ६४.५; १८६.८; ६.५१.४; ८.२७.४; १०.७७.३; ५
रिशादसः १.३९.४; ५.६०.७; ६१.१६; ७.५९.९; ८.२७.१०; ३०.२; ८३.५
रिशादसम् १.२.७; ५.६४.१; ७.६६.७
रिशादसा ५.६६.१
रिशादसा ५.६७.२; ७१.१; ८.८.१७
रिशादाः १.७७.४; ९.६९.१०
रिषः १.४१.२; ९८.२; २.२६.४; ३४.९; ३५.६; ३.३१.२०; ५.५२.४; ६७.३; ६.२४.१०[२]; ६३.२; १०.३६.२; ८७.१
रिषण्युः २.११.१; ७.९.५; १०.२२.१५
रिषण्यत ८.१.१; २०.१
रिषण्यति २.२३.१२
रिषण्यवः १.१४८.५
रिषत् ६.५४.७; ८.६५.१०; ६७.११; १०.६२.११; ९७.२०
रिषतः १.१२.५; ३६.१५; ७.१५.१३; ८.४४.११
रिषते १.१८९.५; ५.३.१२
रिषन् ८.१०३.१३
रिषन्तम् २.३०.९
रिषम् १०.१८.१३
रिषयध्यै १.१२९.८
रिषाथ ७.३३.४
रिषाथन १०.४८.५; ९४.१०
रिषाम १.९४.१–१४; ४.१२.५; ६.४४.११; १०.१७८.२
रिषे ५.४१.१६; ७.३४.१७
रिष्टम् १.१३१.७; ९.११२.१
रिष्यति १.१८.४; ५.४४.९; ५४.७; ६.५४.३
रिष्यथ ५.५४.४
रिष्यन्ति १०.१०७.८
रिष्यसि १.१६२.२१; ८.३१.१६
रिष्याः १०.५१.७
रिष्याति १०.९७.१७
रिष्येत् ८.४८.१०
रिष्येत् १.९१.८
रिष्येम ६.५४.९

६.५०.१२; ७.३५.६; ४०.५; १०.६५.१; ६६.३; ९३.४

रुद्रम् १.४३.४; ११४.४; २.३३.५; ३.२.५; ४.३.१; ५.४२.११; ५२.१६; ६.४९.१०[२]; ७.१०.४; ४१.१; ८.७२.३; १०.६४.८; १२६.५

रुद्रवर्तनी इति रुद्रऽवर्तनी ८.२२.१४

रुद्रवर्तनी इति रुद्रऽवर्तनी १.३.३; ८.२२.१; १०.३९.११

रुद्रस्य १.६४.२; १२; ८५.१; २.३३.६; ८; १३; १४; ५.४२.१५; ५९.८; ६.२८.७; ५०.४; ६६.३; ११; ७.५६.१; ५८.५; ८.१३.२०; २०.१७

रुद्रा ५.७३.८; ७५.३

रुद्रा १.१५८.१; १०.९३.७

रुद्रा २.४१.७; ५.७०.२; ३; ८.२६.५

रुद्राः १.३९.७; ८.७.१२; १०.६६.१२

रुद्राः १.६४.३; १६६.२; २.३४.१३; ३.८.८; ५.६०.२; ७.३५.१४; ८.३.७; ५४.३; ६३.१२; १०.९२.६; १२८.९

रुद्राः २.३४.९; ५.५४.४; ६०.६

रुद्राणाम् १.१०१.७; ८.१०१.१५; १०.६४.११

रुद्रात् २.३३.९

रुद्रान् १.४५.१; ३.२०.५; १०.६६.४

रुद्राय १.२७.१०; ४३.१; ११४.१; ६; १२२.१; १२९.३; ४.३.६; ७; ५.४१.२; ७.३६.५; ४६.१; १०.९२.९; १२५.६

रुद्रासः १.३९.४

रुद्रासः १.८५.२; ५.८७.७; ८.१३.२८; ९.७३.७

रुद्रासः ५.५७.१; ८.२०.२

रुद्रियम् १.४३.२; ७.४०.५; १०.६४.८

रुद्रिया १.७२.४

रुद्रियाः ३.२६.५

रुद्रियाः २.३४.१०

रुद्रियाणाम् ८.२०.३; १०.४८.११

रुद्रियाय ५.४१.११

रुद्रियासः १.३८.७; ५.५८.७

रुद्रियासः ५.५७.७; ६.६२.८; ७.५६.२२

रुद्रियेषु २.११.३

रुद्रेण १०.९२.५; १३६.७

रुद्रेभिः १.५८.७; १००.५; १०१.७; ३.३२.३; ७.५.९; १०.४; ३५.६; ८.१०३.१४; १०.३२.५; ६६.३; ९९.५; १२५.१

रुद्रेषु १०.६४.८

रुद्रैः २.३१.१; ३.३२.२; ८.३५.१; १०.१५०.१

रुद्रौ ८.२२.१४

रुधत् १०.१०५.१

रुधतः १.१७९.४

रुधिऽक्राम् २.१४.५

रुध्यसे ८.४३.९

रुपः ४.५.७; ८; १०.१३.३

रुमे ८.४.२

रुशत्वान् १.१४९.३

रुशक्षणिम् ९.४८.२

रुरुचन्त ४.५५.२

रुरुचानम् ३.२.३

रुरुचुः ४.१६.४; ६.६२.२; ८.३.२०; १०.१२२.५

रुरुचे ६.१५.५

रुरुचे ३.६१.५; ७.७७.१

रुरुच्याः ६.३५.४

रुरुध्रे १०.८४.३

रुरुऽशीर्ष्णी ६.७५.१५

रुरुहुः ५.७.५; ६.७.६; २४.३; ९.७९.४

रुरोच ४.५.१५

रुरोज ६.१८.१०; १०.८९.७

रुरोज ४.५०.५; ६.३२.३

रुरोजिथ ६.१६.३९

रुरोजिथ ८.६४.५

रुरोधिथ १.१०२.१०

रुव १.१०.४

रुवण्यः ८.९६.१२

रुवण्युम् १.१२२.५

रुवत् १.१७३.३; ४.५६.१

रुवति ९.७०.७

रोदसी इति १.५२.१०; १०५.१–१८; १८५.३; ३.२६.९; ५४.३; ४; १०; ४.५५.६; ५६.४; ६.५०.३; ६२.८; ७०.२; ३; ९.७.९; ९८.९; १०.१२.४; ६७.११; ७९.४
रोदसीभ्याम् १.१३६.६
रोदसोः ९.२२.५
रोदस्योः १.३३.५; ५९.२; ९६.४; ११७.१०; १२२.१; १४९.२; १५१.३; १६८.१; ३.३१.१३; ४.३.१; ६.२.११; १४.६; १६.४६; २४.३; ७.६.२; ६; ८.७२.१३; ९.९०.१; १०.१.२; ७४.१
रोधः ४.५.१; १०.४८.२
रोधऽचक्राः १.१९०.७
रोधत् १.६७.५
रोधति ८.४३.६
रोधना १.१२१.७
रोधनाः २.१३.१०
रोधस्वतीः १.३८.११
रोधांसि २.१५.८; ४.२२.४
रोपणाकासु १.५०.१२
रोपुषीणाम् १.१९१.१३
रोम १.६५.४; ९.९७.११
रोमण्ऽवन्तौ ९.११२.४
रोमशम् ८.३१.९; १०.८६.१६; १७
रोमशा १.१२६.७; ८.९१.६
रोमाणि १.१३५.६; ९.६२.८; ७५.४
रोरवीति ३.५५.१७
रोरवीति ४.५८.३; ६.७३.१; ७.१०१.१; १०.८.१
रोरुचानः ४.१.७
रोरुवत् १.५४.१; ५; १४०.६; ६.६१.८; ९.६५.१९; ६८.२; ७१.२; ८५.९; ८६.७; ९१.३; १०.२८.२; ७५.३; ८६.१५; ९२.५
रोषति ८.४.८; ९९.४
रोह १.५६.२; ३.८.११; ९.६३.२२; १०.८५.२०
रोहणम् १.५२.९
रोहतु १०.१८.६
रोहति १.१४१.४; ८.४१.८
रोहतु १०.१६.१३; ६२.८
रोहते २.५.४; ८.१३.६
रोहथः ५.६२.८
रोहन् ९.१७.५
रोहन्ति ६.४४.६
रोहन्तु १०.१८.७; १४२.८
रोहय ८.९१.५
रोहयः ८.८९.७; ९.१०७.७; १०.१५६.४
रोहयत् १.७.३
रोहयन्तः १०.६५.११
रोहसि ९.३६.६; ८०.२
रोहसे १.५१.१२
रोहांसि ६.७१.५
रोहिणीषु १.६२.९; ८.९३.१३
रोहिण्या ८.१०१.१३
रोहित् १.१००.१६
रोहितः १.३९.६; ८.७.२८
रोहितः १.१४.१२; ५.५६.६; ७.४२.२
रोहितम् ८.३.२२
रोहित्ऽअश्व ८.४३.१६
रोहित्ऽअश्व १.४५.२; १०.९८.९
रोहित्ऽअश्वः ४.१.८; १०.७.४
रोहितस्य ८.३.२४
रोहिता १.९४.१०; १३४.३; २.१०.२; ३.६.६; ४.२.३; ५.६१.९; ८.६८.१५; १०.६०.६
रोहितासः ४.६.९
रोहितौ ५.३६.६
रौद्रः १०.३.१
रौद्रम् १०.६१.१
रौद्रौ १०.६१.१५
रौहिणम् १.१०३.२; २.१२.१२

ल

लक्षम् २.१२.४
लक्ष्मण्यस्य ५.३३.१०
लक्ष्मीः १०.७१.२

लयन्ताम् १०.८४.७
ललामीः १.१००.१६
लाङ्गलम् ४.५७.४
लायम् १०.४२.१
लिबुजाऽइव १०.१०.१३; १४
लोकः ३.३७.११
लोकुऽकृत् ९.८६.२१; १०.१३३.१
लोकुऽकृत्नुम् ८.१५.४; ९.२.८
लोकम् १.९३.६; २.३०.६; ३.२.९; ४.१७.१७; ५.४.११; ६.२३.३; ७; ४७.८; ७३.२; ७.२०.२; ३३.५; ६०.९; ८४.२; ९९.४; ८.१००.१२; ९.९२.५; १०.१३.२; १४.९; १६.४; ३०.७; ८५.२०; १०४.१०; १८०.३
लोकाः ९.११३.९
लोकान् १०.९०.४
लोके ३.२९.८; ५.१.६; ९.११३.७^{२}; १०.८५.२४
लोगम् १०.१८.१३
लोगेन १०.२८.९
लोधम् ३.५३.२३
लोपामुद्रा १.१७९.४
लोपाशः १०.२८.४
लोमऽभ्यः १०.१६३.५
लोम्नःऽलोम्नः १०.१६३.६

व

वंशाम्ऽइव १.१०.१
वंसगः १.७.८; ५५.१; ५८.५; १३०.२^{२}; ५.३६.१; ६.१६.३९; ८.३३.२; १०.१४४.३
वंसगम् १०.१०२.७
वंसगाऽइव १०.१०६.५
वंसत् ६.६८.५
वंसत् १०.२६.२
वंसते ८.१०३.९
वंसाम ६.१९.८; ८.६०.१२
वंसि ५.७०.१
वंसीमहि ६.१९.१०
वंसु ९.५७.३; ८६.३५
वंस्व १.४८.११; ७.१७.५; ८.२३.२७^{२}; ६०.१४
वंस्व ६.४८.४
वः १.७.१०; १४.४; २०.५; ३०.१; ३६.१; ३७.१; ४; ६; ७; १२; १४; १५; ३८.२^{२}; ३–५; १२; ३९.२; ४; ६; ७; ४०.२; ६; ४१.४; ५; ८^{२}; ६२.९; ५; ६३.५; ६४.९; १३; ६६.५; ८५.६^{२}; १२; ८७.२; ८८.३–६; ९५.४; १०५.१; ५^{२}; ६; १०७.१; ११०.३; १२२.१; ४; ५^{२}; १२६.५; १२७.१०; १२९.४; ८; १३९.८^{२}; १४३.७; १५५.१; १६१.२^{२}; ३; १२^{२}; १६५.६; १३–१५; १६६.४^{२}; ५; ६; ९^{३}; १२^{२}; १३; १५; १६७.६; ९; ११; १६८.१^{३}; ५; ७^{२}; १०; १७१.१; २; १७२.१; २; १८६.३; ४; ११; १८८.८; १९१.६; ७; २.४.१; १४.९; ११; १६.१; २४.५; २७.५; ६; ८; १४; १६; २९.१^{२}; ३–६; ३०.११; ३१.६; ७; ३३.१३; ३४.२; १०; ११; १५; ४१.१४; ३.८.६; १३.१; ३; २७.१; ३३.९; ११; १३; ५४.१७; ५७.२; ६०.१; ४; ६१.५^{२}; ४.३.१; ८.१; १६.१६; ३३.५; ११; ३४.१^{२}; २; ३^{२}; ४^{२}; ५; ११; ३५.१^{२}; ६; ९; ३६.१–४; ७^{२}; ३७.२^{२}; ३^{२}; ४; ५१.४; १०; ११; ५५.१^{२}; ५.७.१; १८.३; २१.४; २५.१; ३९.४; ४१.५^{२}; ६–८; १३; १७^{२}; १८; ४२.१०; ४४.४; १२; ४५.४; ११; ४९.१; ५२.४; ५३.९^{४}; १०; ११; १३; ५४.२; ५; १०; ११; १५; ५५.४; ५; ७; ५६.३; ७; ९; ५७.१; ३; ६^{४}; ७; ५८.३; ५९.१; ४; ६०.२; ३; ६१.२; ६४.१; ६८.१; ८७.१; २; ५; ६; ६.५.१; १०.१; १५.१; ४; ६^{३}; १६.२२; १९.४; २२.७; २३.९; २८.६; ७^{२}; २९.१; ३८.३; ४४.४; ६; ४५.२२; ४८.१; १४; ५०.१; ५१.३; ७; ९^{२};

५९.८; १४^{२}; ६५.४; ६६.७; ६७.१; ७.२.३; ३.१; ७; ४.१; ७.१; ९.४; १६.१; ११^{२}; ३१.१; १०; ३२.२०; ३३.३; ४; ८; १४; ३४.९^{२}; ३६.८; ९; ३७.१; ४२.३; ४३.१; ४; ४४.१; ४७.१^{२}; २^{२}; ४८.१; २; ५२.२; ५६.७–१०; १२–१४; १७; १८^{२}; २१^{२}; २३; २४; ५७.१; ४^{४}; ५८.२^{२}; ४; ५९.२; ३; ४^{२}; ५; ११; ६६.१२; १३; ८.७.१; ५; ११; १९–२१; ३१; १२.१९; १८.१९^{२}; १९.७; ३५; २०.५; ६; ९; १२; १५; १६; २२^{२}; २१.९; २३.७^{२}; २४.१; १८; २५.१६; २७.६; ७; १०; ११^{२}; १२; १३; १५^{२}; १६; २०; २२; ३०.१; ३१.१४; ३२.४; २७; ४५.२८; ४६.१४; १७; ४७.१^{३}; २^{२}; ३^{२}; ४^{२}; ५^{२}; ६^{३}; ७^{२}; ८^{२}; ९^{२}; १०^{२}; ११^{२}; १२^{२}; १३^{२}; १४^{२}; १५^{२}; १६^{२}; १७^{२}; १८^{२}; ४९.१; ५०.४; ६०.१७; ६६.१; १५; ६७.४; ६; १६; ६८.४; ६९.१^{२}; २^{२}; ७०.८; ७१.२; १२; ७४.१^{२}; ८०.१०; ८३.६; ९; ८४.१; ८८.१; ८९.३; ९२.१; ७; ९३.१६; ९४.८; १०; ९६.१४; ९७.१२; ९९.७; १००.७; १०२.७; ९.८६.१७; ९८.८; १०१.१; ४; १०५.१; १०.२.४; ९.२; ३; १५.४; ६; १६.१०; १८.६; १९.७; २१.१–८; २४.१–३; २५.१–११; ३०.३; ७^{२}; ८; १५; ३२.५^{२}; ९; ३४.१२; १४; ३५.१४; ३६.१०; ३७.१२; ५०.१; ५२.१^{२}; ५^{२}; ६२.१–३; ४^{२}; ६३.२^{२}; ६^{२}; ११; १७; ६४.७; १७; ६६.१२; ७०.८; ७२.६; ७५.१; ७६.१; ५; ८^{२}; ७७.४; ७८.८; ८८.१८^{२}; ९२.१; ९; ९४.१०; १२; ९७.२^{२}; ४; ५^{२}; ९; १४; २०^{२}; १००.७; १०१.१; ८^{२}; ९; १०३.१३^{२}; १०६.४; १०८.२; ६^{३}; १११.८; ११५.३; १६६.३; ४^{३}; ५^{२}; १७५.१; ४; १९१.२; ३^{२}; ४^{४}

वृक्तरिं १०.६१.१२

वक्तवे ७.३१.५

वृक्ता ७.१०४.८; ८.३२.१५; ९.७५.२

वक्त्वानाम् ३.२६.९

वक्त्वानि ६.९.२; ३

वक्मनि १.१३२.२

वृक्मराजसत्याः ६.५१.१०

वक्म्यः १.१६७.७

वक्करी ६.२२.५

वक्करी इति १.१४४.६

वक्का १.१४१.७; ९.९१.१

वक्काः ४.१९.७; १०.१४८.५

वक्षः १.९२.४; १२४.४; ५.३३.२; ६.६४.२; १०.४८.२

वक्षःऽसु १.६४.४; १६६.१०; ५.५४.११; ७.५६.१३

वृक्षणा ५.५२.१५

वृक्षणाः १.३२.१; १६२.५; ३.३३.१२

वक्षणानि ६.२३.६

वृक्षणाभ्यः १.१३४.४^{२}; ८.१.१७

वृक्षणासु ३.३०.१४; ५.४२.१३; ६.७२.४; १०.२७.१६; २८.८; ४९.१०

वृक्षाणिः ८.६३.४

वक्षणीः १०.६४.९

वृक्षणेऽस्थाः ५.१९.५

वक्षत् १०.६१.२३

वृक्षत् १.१३५.४; १५७.३; ३.५.९; ६.२२.७; ८.३४.८; १०.२०.१०; १७६.२

वृक्षतः १.१६.२; ८.२.२७; ४.१४; ६.४५; १४.१२; ३२.३०; ३४.९

वृक्षति १.१.२; १४.९; १२९.८^{२}

वृक्षथः ७.३३.८; १०.११५.१

वृक्षथाय १०.९९.१२

वृक्षथेन ४.५.१

वक्षन् ८.७४.१४

वृक्षन् १.१०४.२

वृक्षयम् १०.४९.८

वक्षांसि १.१२३.१०

वक्षि ३.१.१

वृक्षि १.१८८.३; २.३.११; ३६.४; ३.४.१;

७.९; १४.२; १५.५; ५.१.११; ४.४; ९.१; २६.१; ४३.१०; ६.१५.१८; १६.२; २१.१२; ४७.९; ७.१.१८; ७८.१; ९८.२; ८.५४.६; १०२.१६; १०.३.७; ७०.३; १०; ७३.४

व॒क्ष्य॑ः ५.१९.५

व॒क्ष्यन्ती॑ऽइव ६.७५.३

व॒क्ष्यामि॑ ६.९.६

व॒ग्नुः ७.१०३.२; ९.९७.१३

व॒ग्नुना॑ १.८४.३; १०.३२.३

व॒ग्नुम् ९.१४.६; ३०.२

व॒ग्नून् १०.३.४

व॒ग्व॒नान् १०.३२.२

व॒ग्व॒नुम् ९.३.५

व॒ङ्कुः ५.४५.६

व॒ङ्कु॒ऽत॑रा १.५१.११

व॒ङ्कुम् १.११४.४

व॒ङ्कू इति॑ १.५१.११; ८.१.११

वङ्क्रीः १.१६२.१८

वङ्गृ॑दस्य १.५३.८

वच॑ः १.२६.२; १०; ३०.४; ५४.३; ५७.४; ७५.१; ७८.५; ८३.३; ८४.१९; ९१.१०; ९३.२; ९४.८; १०१.१; ११४.६; १४४.७; १४५.२; २.३१.५; ३.१०.५; ३३.८; ४.३३.५; ५.१.१२; ११.५; २२.४; ३९.५; ५४.१५; ६.४८.११; ७.८.६; ९६.१; १०१.५; ८.८.११; १९.१२; २४.२०; २५.२०; ३९.२; ४३.२७; ४६.१४; ६१.१; ९; ६६.५; ७४.१; १०१.५; ९.१०१.१३; १०३.१; १०.१७.१४; ३७.६; ५०.६; ६४.१०; ९७.१४; १०८.८; १२२.२; १५०.२

वच॑ःऽभिः १.३६.१; १८७.११; ४.४.११; १६.६; ५.१२.५; ४५.४; ६.५.६; ३९.२; ४४.८; ७.१०४.८; १०.६१.२६; ११४.५; १२०.५

व॒चः॒ऽयुजा॑ १.७.२; २०.२; ६.२०.९; ८.४५.३९; ९८.९

व॒चः॒ऽवित् ९.९१.३

व॒चः॒ऽविद॑ः १.९१.११; ९.६४.२३

व॒चः॒ऽविद॑म् ८.१०१.१६

व॒च॒नस्य॑ ६.३९.१; ४९.१२

व॒च॒नाऽव॑न्तः ९.६८.१

व॒च॒नेमि॑ः १०.११३.९

वच॑सः १.१४७.२; २.९.४; १६.७; ३२.१; ४.४.११; ५.८; ५.१२.४; ६.५१.६; ७.३७.६; ८.८६.१

व॒च॒सम् १.११२.२

वच॑सा १.७६.४; २.१८.३; ३२.३; ३.१४.६; ४.१.१५; ५.१४; २५.२; ५.२९.६; ६.६२.५; १०.१५१.१

वच॑सी॒ इति॑ ७.१०४.१२

वच॑से ३.३३.५; ६.६२.९; ९.९०.६

व॒च॒स्य॒ते १.५५.४; ९.९९.६

व॒च॒स्यया॑ ४.३६.६; १०.११३.८

व॒च॒स्यवे॑ १.५१.१३; १८२.३; १०.४०.१३

व॒च॒स्या २.१०.६; ६.२१.१; ४९.८

व॒च॒स्याम् २.३५.१

व॒च॒स्युऽभि॑ः ५.१४.६

व॒च॒स्युव॑म् २.१६.७

वचां॑सि १.१४५.३; ३.३३.१०; ४.३.१६; ३८.१०; ६.३२.१; ५२.१४; ७.२३.१; ८.१०१.७; १०.६५.१३; ६६.११; ९५.१; १०८.६

व॒च्यते॑ १.१४२.४

व॒च्यन्ता॑म् ३.६.२

व॒च्यन्ते॑ १.४६.३; १८४.३

व॒च्यमा॑ना ३.३९.१

व॒च्यमा॑नाः ३.६.१; १०.४७.७

व॒च्य॒स्व॒ ९.२.२; ९७.२; १०८.१०

व॒ज्र॒ १०.८३.१; ८४.६

वज्र॑ः १.५१.७; ५२.१०; ५७.२; ८०.३; १२; १००.१३; २.११.१०; १६.६; ३.३०.६; ६.४१.२; ४७.२८; ८.१२.७; ७०.२; ९३.९; ९६.३; १००.९; ९.४७.३; ७२.७; ७७.१; १११.३; १०.२७.२१; ४४.२; ९६.३; ४; १४४.२

वज्र॑ऽदक्षिणम् १.१०१.१; १०.२३.१

वज्रऽबाहुः १.३२.१५; १६५.८; १७४.५; २.१२.१२; १३; ३.३३.६; ४.२०.१; २९.४; ७.१८.१२; १०.६१.१२
वज्रऽबाहुम् ४.३९.४; ७.२३.६; ९.९७.४९; १०.४४.३; १०३.६
वज्रबाहू इति वज्रऽबाहू १.१०९.७
वज्रबाहो इति वज्रऽबाहो २.३३.३
वज्रऽभृत् १.१००.१२; ६.१७.२
वज्रम् १.८.३; ३२.२; ३; ७; ३३.१०; ५२.७; ८; ५५.१; ५; ६१.६; १२; ६३.२; ८१.४; ८४.११; ८५.९; १२१.३; १२; १३०.४; १३१.३; २.११.४; ६; १६.२; ३; २०.८; ३.३२.१२; ४४.४; ५; ४.१६.७; १७.३; २०.६; २२.३; ४१.४; ५.२९.२; ३१.४; ४८.३; ६.१७.१०; १८.९; २०.९; २२.९; २३.१; ४; ४५.१८; ४७.२७; ७.१८.१८; २०.४; २८.२; ८.६.१४; ७.२२; १५.७; २९.४; ६१.१८; ६८.३; ७६.९; ९६.५; ९; १००.७; ९.१०६.३; १०.२३.३; ४८.३; ६; ४९.२; ५२.५; ७४.५; ९२.७; ९९.१; १०२.३; १०५.७; ११३.५; १५३.४
वज्रऽवाहः ६.४४.१९
वज्रस्य ५.३२.७; ६.२०.५; २७.४; १०.२२.३
वज्रऽहस्त ८.२४.२४
वज्रऽहस्त ३.३२.३; ५.३३.३; ६.१७.१; ४६.२; ५; ७.१९.५; ३२.४; ८.९०.४
वज्रऽहस्तः १.१७३.१०; २.१२.१३; १९.२; ६.२९.१; ७.२१.४; ८.२.३१
वज्रऽहस्तम् ६.२२.५; ७.३२.३
वज्रऽहस्ता १.१०९.८
वज्रऽहस्तैः ८.७.३२
वज्रात् २.११.९; ६.१७.९; १०.१३८.५
वज्राय ८.१००.१२
वज्रासः १.८०.८
वज्रिणः १.७.७; ४०.८; ३.४६.१
वज्रिणम् १.७.५; ८.६.१५; १२.२४; ६६.७; ९.८६.२; १०.९६.६
वज्रिणा ६.५९.३
वज्रिणे १.८.५; ३.५३.१३; ६.३२.१; ७.३२.८; ९७.९; ८.७.१०; २४.१; ६९.६; १००.८; ९.३०.६; ५१.२; ६३.१५
वज्रिन् ५.४०.३; ८.२.१७; १३.३३; ४५.८; ७०.६
वज्रिन् १.३०.११; १२; ५७.६; ६३.४; ५; ७; ८०.१; २; ७; ११; ८२.६; १०३.३; १३१.६; ४.१९.१; २०.३; ५.२९.१४; ३२.२; ३६.५; ६.१९.१२; २०.७; २२.१०; ४१.१; ४७.१४; ८.१२.२६; २१.८; ४९.३; ६; ५०.६; ७०.५; ९२.१३; ९६.१७; ९७.१४; १५; ९९.१; १०.८३.६; १७९.३
वज्रिऽवः १.१२१.१४; ६.३७.४; ४५.१८; ८.१.५; ६.३३; ३७.१-६; ६६.६; ११; ६८.९; ९२.११; १०.२२.४; १०-१३
वज्री १.७.२; ११.४; ३२.१; ५२.५; १०३.४; १३०.३; ४.२०.२; ५.३०.१; ३२.४; ४०.४; ६.१८.६; २९.३; ७.३४.४; ४९.१; ८.१.८; ६.४०; ३३.४; ६६.४; ९७.१३; १०.२२.२; ५५.७
वज्रेण १.३२.५; ३३.१२; १३; ५७.६; ६१.१०; ११; ८०.५; ६; १३; १०३.२; ७; १२१.११; १३०.७; १३१.७; १३२.६; २.१५.३; ६; १७.६; ३.३३.७; ४.१७.३; ७; १९.३; २२.५; ५.२९.६; ३२.४; ६.२१.७; ४४.१५; ६८.३; ८.६.६; ७६.२; ८९.३; ९६.१७; १०.२८.७; १११.६
वटूरिणा १.१३३.२
वणिक् ५.४५.६
वणिजे १.११२.११
वतन्तः ७.६०.६
वतेम ७.३.१०; ४.१०
वत्सः १.९५.४; १६४.९; ३.५५.६; ८.८.८; ११; १५; १९; ९.६; ११.७; ७२.५; ९.६९.१; १०.८.२; २८.९
वत्सःऽइव ९.१०५.२
वत्सऽप्रचेतसा ८.८.७

वनुष्यति ७.८२.१
वनुष्यते ९.७.६
वनुष्यन् ६.६.६
वनुष्यात् ६.५.४
वनुष्व १.१६९.१
वनून् ४.३०.५
वने १.५५.४; ५८.५; १४८.४; २.१४.९²; ४.७.६; ७.१.१९; ९.६.५; ७.३; ४५.५; ६६.९; ७४.१; ७८.२; ८८.२; ५; ८९.१; १०६.११; १०७.२२; १०.४.५; २३.२; २९.१; ३१.९; १०१.११
वनेऽजाः ६.३.३; १०.७९.७
वनेभ्यः २.१.१
वनेम १.७०.१; १२९.७²; २.५.७; ८.१९.२०
वनेम २.११.१२; ७.४७.१; ८.९२.३१; १०.१०५.८
वनेमहि ७.९४.९
वनेऽराट् ६.१२.३
वनेरिति वनेः २.६.१
वनेऽवने ५.११.६; १०.९१.२
वनेषाट् १०.६१.२०
वनेषु १.६७.१; ७०.५; १२८.३; ३.६.७; २३.१; २९.६; ३४.३; ४.७.१; ५.१.५; ८५.२; ८.४३.८; ६०.१५; ९.७.६; २७.३; ६२.८; ८६.३१; ९२.६; ९६.२३; १०७.१०; १८
वनोति १.१३३.७; १०.१०५.५
वनोति ४.२३.१०
वनोषि १.३१.१३; १४
वन्त १.१३९.१०
वन्तारः ३.३०.१८; ७.८.३
वन्दते १.१७३.१२; ४.५०.७; ७.७३.२
वन्दते १०.११५.८
वन्दध्यै १.२७.१; ६१.५; ३.४.३
वन्दनः १.११९.६
वन्दनम् १.११२.५; ११८.६; ११९.७; ७.५०.२; १०.३९.८
वन्दनऽश्रुत् १.५५.७
वन्दना ७.२१.५
वन्दनानि ३.४३.४
वन्दनाय १.११६.११; ११७.५
वन्दनेऽस्थाः १.१७३.९
वन्दमानः १.२४.११; ३.१८.३; ५.३.१०; ७.६.१; ८.२२.१३; १०.१४९.५
वन्दमानम् २.३३.१२
वन्दस्व १.३८.१५; ५.५८.२; ८.२०.२०
वन्दस्व ८.२०.१४; ४२.२; १०.३०.१०
वन्दामहे ४.५७.६
वन्दारु ४.४३.१; ५.१.१२; ६.४.२
वन्दारुः १.१४७.२
वन्दि १०.६१.१६
वन्दिता १०.३३.७
वन्दितारम् २.३४.१५
वन्दितुः ९.९३.५
वन्दिषीमहि १.८२.३
वन्दे ५.२८.४; ७.६.१
वन्दे १.१४७.२; २.३५.१२
वन्द्य १.३१.१२; ७९.७
वन्द्यः २.७.४; ४.५४.१; ९.७.२; १०.४.१; ११०.३
वन्द्या १०.६३.२
वन्द्यासः १.९०.४; १६८.२
वन्द्येभिः ५.४१.७
वन्धुरः १.३४.९
वन्धुरम् १०.११९.५
वन्धुरऽयुः ४.४४.१
वन्धुराऽइव ३.१४.३
वन्धुरे १.१३९.४; ६.४७.९
वन्धुरेषु १.६४.९
वन्धुरेऽस्थाः ३.४३.१
वन्यम् ९.९७.४५
वन्वते २.२१.२
वन्वन् १.१२१.९; ६.१२.४; १६.२०; २६; १८.१; ८.३१.३; ९.८९.७; ९६.८; ११; १०.६१.२
वन्वन् ७.४८.३
वन्वन्तः २.४.९; ६.१६.२७; ९.६१.२४

वन्वन्ता ७.८३.४
वन्वन्तु ७.२१.९
वन्वन्तु १०.३२.२
वन्वानः ३.८.२; ५.२९.९
वन्वानाः ७.८८.७
वन्वे १०.९६.१
वप ८.९६.९
वपः ४.१६.१३
वपत १०.१०१.३
वपति ८.६६.४
वपते १.९२.४; १६४.४४
वपन्त ७.५६.३
वपन्तः १०.९४.१३
वपन्ता १.११७.२१
वपन्ति ६.६.४; ८.७.४; १०.८५.३७
वपन्तु २.३३.११
वपसि १०.१४२.४
वपाऽउदरः ८.१७.८
वपाऽवन्तम् ५.४३.७; ६.१.३
वपुः १.१०२.२; १४१.२; १४४.३; १८३.२; ४.२३.६; ४४.२; ५.४७.५; ७३.३; ६.४४.८; ४९.५; ६६.१; ७.६६.१४; ८८.२; ८.१९.११; ६९.१३
वपुःऽतरः ९.७७.१
वपुःऽतरम् १०.३२.३
वपुःऽतरा २.३.७
वपुःऽभिः १.६२.८
वपुषः १.११८.५; ९.७७.१; १०.३२.३; १४०.४
वपुषाम् ४.७.९; ५.६२.१
वपुषाय ३.२.१५
वपुषि ८.४६.२८
वपुषीऽइव १०.७५.७
वपुषे १.६४.४; ११९.५; १४१.१; १४८.१; ४.२३.९; ५.३३.९; ७३.३; ६.६३.६
वपुष्यः ४.१.८; १२; ५.१.९
वपुष्यतः ८.६२.९
वपुष्यन् ३.१.४
वपुष्या १.१८३.२
वपुष्ये इति १.१६०.२
वपूंषि ३.१.८; १८.५; ३९.३; ५५.९; ११; १४; ५७.३; ४.२३.९
वप्ताऽइव १०.१४२.४
वप्सतः १.१८१.८
वम् १०.२८.७
वमन् १०.१०८.८
वम्रः १.५१.९; ८.१०२.२१
वम्रकः १०.९९.१२
वम्रम् १.११२.१५
वम्रस्य १०.९९.५
वम्रीभिः ४.१९.९
वय १०.१३०.१[२]
वयः १.२४.६; २५.४; ३७.९; ४८.६; ४९.३; ६६.२; ७१.६; ७; ८३.४; ८५.७; ८८.१; १०३.७; १०४.१; ७; १११.१; २; ११८.५; १२४.१२; १२५.२; १२७.८[२]; १३६.२[२]; १४०.९; १४१.८; १५१.९; १५५.५; १६६.१०; १७८.२; २.१.१२; ४.९; १३.११; १९.२; २०.१; २३.१०; २८.४; ३१.१; ५; ४३.१; ३.१८.४; २९.८; ५१.६; ४.१७.१८; ३६.८; ४३.६; ५.४.६; ८.५; १५.३; १६.१; ४१.१३; ४३.१५; ५५.१; ५९.७; ७३.५; ७५.६; ६.१३.५; २२.४; २८.६; ४०.१; ४; ४४.९; ४५.२; ४६.१४; ६३.६; ७; ६४.६; ७.३६.५; ९; ४५.४; ५८.३; ६९.४; ९७.१; १०४.१८; ८.३.२३; ५.३३; ७.३५; २०.१३; २१.५; ३३.७; ३९.४; ४७.२; ३; ६२.१; ७४.१४; ८७.२; १०२.१; ९.१९.७; ६८.१०; ९०.६; ९४.४; १११.२[२]; १०.२७.२२; ३०.१२; ३९.८; ४३.३; ४; ४६.१०; ६८.१; १२; ७३.११; ७७.७; ८०.५; ९५.४; ९६.१०; १००.३; १०४.४; १२७.४; १४०.१; १४४.५; ६; १५६.५
वयःऽइव १.८७.२
वयःऽकृत् १.३१.१०; १०.७.७
वयःऽकृतः ९.२१.२; ६९.८

वयःऽजुवः ९.६५.२६
वयःऽधः ९.८१.३
वयःऽधाः १.७३.१; २.३.९; ३.३१.१८; ४९.३; ४.३.१०; १७.१७; ५.४३.१३; ६.७५.९; ८.४८.१५; ७२.४; ९.९६.१२; ११०.११; १०.७.७
वयःऽधाम् ६.६.७; ४९.९; ९.९०.२
वयःऽधेयाय १०.२५.८
वयःऽधै १०.५५.१; ६७.११
वयःऽभिः १०.४५.८
वयःऽवयः ५.१५.४; ८.५५.४
वयःऽवृधः ५.५४.२
वयःऽवृधम् ८.६०.११
वयःऽवृधा ५.५.६
वयत् १०.२८.९
वयत १०.५३.६
वयतः २.२८.५
वयति ८.२१.१०
वयन्तः ७.३३.९
वयन्ति ६.९.२
वयन्ति ५.४७.६; ९.९९.१; १०.१३०.१
वयन्ती २.३८.४
वयम् १.१.७; ७.५; ८.३; ४^{2}; १७.६; २३.४; २४.२; ५; १५; २६.७; ३०.१०; २१; ३१.१०; ३७.१५; ५०.१०; ५७.४; ६०.५; ६६.५; ७३.८; ८२.३; ८६.६; ८९.२; ३; ५; ९१.११; ९४.१–३; ४^{2}; ५–१४; ९७.४; १०१.११; १०२.४; १०५.१९; ११४.४^{2}; ९; १३०.१; १३२.१; १३६.७^{2}; १४१.१०; १३; १५७.२; १५९.५; १६४.४०; १६५.५; १६७.१०^{3}; १७८.५; १८०.७; १०; १८७.२; ११; १८९.८; १९१.१०–१२; २.२.१०; ५.७; ८; ७.३; ८.६; १२.१५; १७.८; २०.१; २३.९; १०; २७.१४; ३.१.२१; ३.९; ८.११; १४.५; २१.५; २६.५; २७.३; १५; २९.४; ३३.४; ६; ३५.५; ४०.१; ४१.७; ५९.३; ४; ६२.११; ४.२.१४; ३.२; ४.१४; १७.१८; २०.३; १०; २९.५; ३२.४^{2}; १३; १८; ३६.९; ४२.१०; ४४.१; ४९.५; ५०.६; ५१.११; ५७.१; ५८.२; ५.३.६^{3}; ४.७^{2}; ८; ८.४; १६.५; ३०.३; ३३.५; ३५.८; ३९.२; ४८.१; ५; ५५.१०; ५६.८; ६५.५; ६६.६; ७०.२; ७२.१; ७४.३; ८२.१; ६.१.६; ७; ८.६; १५.१९; १६.३८; १९.१३; २३.५; २६.८; ४४.१०; ४५.५; ४६.३; ४७.१३; ४८.१; ५३.१; ५४.८; ९; ५७.१; ५; ५९.३; ७१.२; ७५.८; ७.१.२४; ४.६; १४.१; २^{4}; १५.८; २०.८; २५.५; ३०.४; ३१.४; ३२.२७; ३७.४; ४१.२; ४; ५; ४३.५; ४७.१; ५५.७; ६०.१; ६५.२; ७८.५; ८१.४; ८२.१; ८६.५; ८७.७; ८.२.१६; ३.२; ६.३३; १२.२३; १४.६; १७.३; १९.१६; ३५; २१.१; ४; ६; ७; ११; २२.११; २४.८; २५.१२; २६.९; २२; २७.७; २०; २२; ३२.७; ३३.१; ४०.६; ७; १२; ४३.१२; २३; ४४.२७; ४५.१७; ४६.१; २५; ४७.१८; ४८.९; १३; १४; ५१.५; ६; ५२.४; ५३.२; ७; ५४.८; ६१.१४; ६२.१२; ६४.६^{2}; ६५.६; ७; ६६.५; ७; ११; १३; ६७.१६; ७५.१६; ८३.१; ६; ८७.६; ९२.१२; २७; ३२; १०२.३; ९.८.९; ३१.६; ४५.३; ६१.४; २३; २९; ६५.९; ६६.१४; ७९.२; ८६.३८; ९७.४३; ५८; ९८.५; १२; १०.२.२; ४; ४.४; १२.८; १४.६; १८.९; २६.४; २७.९; ३१.१; ३६.९; ३७.८; ३८.२; ३; ३९.१; ४१.१; ४२.६; १०; ४३.१०; ४४.१०; ५३.८; ५७.१; ६; ७२.१; ८४.४; ८७.२२; ८९.१७; ९४.१; १०१.५; १२०.५; १२१.१०; १२६.२; १२७.४; १२८.१; १३३.६; १३६.३; १५८.५; १६०.५; १६४.५; १६९.४
वयम्ऽवयम् १०.२२.१२
वयसः ८.४८.१

वयसा २.१०.४; ३३.६; ६.३६.५; ८.४.९; ९.९७.४७; १०.१०६.५
वयस्वतः २.२४.२५; ५.५४.१३
वयांसि ३.३.७; ९.९.१; १०.४६.१; १२०.५
वयाः १.५९.१; २.३५.८; ६.१३.१; २४.३; ७.४०.५; १०.९२.३
वयाःऽइव २.५.४; ६.७.६; ८.१३.६; १७; १९.३३
वयाकिनम् ५.४४.५
वयाम् १.१६५.१५; १६६.१५; १६७.११; १६८.१०; ५.१.१; १०.१३४.६
वयाम्ऽइव ६.५७.५
वयायाः १०.१२४.३
वयाऽवन्तम् ६.२.५
वयियोः ८.१९.३७
वयिष्यन् ७.३३.१२
वयुनम् १.१८२.१; ३.३.४; ५.४८.२
वयुनऽवत् ४.५१.१; ६.२१.३
वयुनऽवित् ५.८१.१
वयुनऽशः ६.५२.१२
वयुना १.९२.६; १४४.५; १४५.५; १६२.१८; २.२४.५; ४.५.१३; १६.३; ७.७५.४; १०.४९.५
वयुनानि १.७२.७; ९२.२; १५२.६; १८९.१; २.१९.३; ८; ३.५.६; ६.१५.१०; ७५.१४; ७.१००.५; १०.४४.७; ४६.८; ११४.३; १२२.२
वयुने ३.२९.३
वयुनेषु २.३४.४; ६.७.५; ८.६६.८
वय्यम् १.५४.६; ११२.६; ९.६८.८
वय्याऽइव २.३.६
वय्याय २.१३.१२; ४.१९.६
वरः ९.१०१.१४
वरःऽभिः १०.८९.१
वरत् ४.२.९; ६.४५.२४
वरते ६.२२.११
वरते ४.४२.६
वरत्रया १०.६०.८
वरत्राः ४.५७.४; १०.१०१.५
वरत्रायाम् १०.१०२.८
वरथः ५.३१.९
वरन्त ४.६.६
वरन्त १.१२१.१५; १४०.१३; २.२४.५; ३.३२.९; १६; ५.५५.७
वरन्ते ४.३१.९; ८.६६.२; ८८.३
वरन्ते ४.३२.८; ५.२.१०; ७३.५; ८.२४.५; १०.१७८.३
वरम् १.४.४; ८८.२; ११९.३; १४०.१३; २.५.५; ११.२१; १५.१०; १६.९; १७.९; १८.९; १९.९; २०.९; ३९.२; ६.६४.५; ७.१.४; ६.६; ५४.३; ६५.४; ७०.५; ६; ९.४५.२; ६८.२; ९७.२२; १०.२५.११; ११५.६; ११६.२; १३३.७; १६४.२
वरऽशिखस्य ६.२७.४; ५
वरऽसत् ४.४०.५
वरस्य ८.६३.५
वरस्या ५.७३.२
वरस्याम् ६.४९.११
वरा ५.४४.१२
वरा १०.८५.८; ९
वरांसि १.१९०.२; ४.२१.८; ६.६२.१; २; १०.८९.२
वराःऽइव १.८३.२; ५.६०.४
वराते १.६५.३; ५.३२.९
वरान् १०.३२.१
वराय १.७६.१; १४३.५; ६.२१.४; ४४.२१; ७.५९.२; ८.२७.१६; ८२.३; ८४.४; १०.२९.६; ५०.६
वराहः ९.९७.७
वराहम् १.६१.७; ११४.५; ८.७७.१०; १०.२८.४; ९९.६
वराहुऽयुः १०.८६.४
वराहुम् १.१२१.११
वराहून् १.८८.५
वराहैः १०.६७.७
वरिति वः २.१४.३; ५.३२.१
वरिति वः १.१२१.४
वरिमता १.१०८.२

ववृधध्यै १.६१.३; १२२.२; ६.६७.१; १०.९९.१
ववृधन्त ५.५२.७; ६.६६.२; ६८.४
ववृधन्त १०.९३.१२
ववृधन्तः ४.२.१७
ववृधस्व ६.१७.३
ववृधस्व १.३१.१८; ७.१९.११; १०.११६.६
ववृधाति १.३३.१
ववृधाते इति ७.७.५; ८.१२.२८
ववृधाते इति १०.५.४
ववृधानः १.१३१.७; २.११.२; ४; २०; १९.१; ३.३४.१; ४५.५; ४.२१.१; ५.२.१२; ३.१०; १२; ८.७; २७.२; ७.५.२; ८.६.४०; ५३.२; ७६.३; १०.१४.३; ५४.२; ७९.७; ८१.६; ११६.६; १२०.२
ववृधानम् १.१७३.१; ३.४७.५; ५१.१; ४.३.१४; ५.३२.६; ६.१९.११; २२.६; ३८.५; ७.१.१२; १०४.४; ९.८५.१०
ववृधानस्य ८.१४.६
ववृधाना १.९३.६; ११७.११; ६.६९.६; ८.५.११
ववृधानाः ८.९६.८; १०.७८.८
ववृधानान् ५.४२.९
ववृधानाय ९.४२.३
ववृधानौ ५.६९.१; ८.८७.४
ववृधीथाः १.१३०.१०
ववृधुः २.२०.४; ८.२२.१२; ९५.६; ९.९.४; १०.१४.३; ६६.१
ववृधुः २.८.५; ३४.१३; ५.१४.६; ५५.३; ५९.५; ६; ६०.५; ६.३४.४; ७.६०.५; ८.६.२१; ३५; ४३; १२.२०; ६२.१०; ९.१०६.८; १०.७३.२; ७७.२; १२२.७
ववृधे १.१६७.८; ३.१.८; ३२.१३; ६.१९.२; ४४.१३; ७.५.१; १०.२३.५; ३०.४
ववृधे १.३७.५; ५२.२; ७; ८१.१; ४; १४०.२; १४१.५; २.२२.२; ३.५.२; ३६.१; ५; ४०.७; ६.१९.१; ३०.१; ७.९५.३; ८.३.८; ६.१; १२.८; ९; ११; ४४.१२; ६२.२; ९.८९.२; ९७.४०; १०.२९.७; ६१.२१
ववृधेन्यम् ८.२४.१८
ववृध्वम् ८.२०.१८
ववृध्वांसम् ८.९५.७; ९८.८
ववृमहे ६.४.७; ८.२१.२
ववृमहे १.१८७.२; ३.९.१; ८.१९.३
ववृषस्व ८.६१.७
ववृषाणाः ६.२६.१
ववृषे ९.८८.१
वव्ने १.६१.१५
वव्ने १.३६.१७; ५.७४.७
वव्रः १.५२.३
वव्रम् ५.३२.८
वव्रयामहे ८.४०.२
वव्राज ३.१.६
वव्रान् ७.१०४.१७
वव्रासः १.१६८.२
वव्रिः ५.१९.१; १०.४.४
वव्रिणा १.५४.१०
वव्रिम् १.४६.९; ११६.१०; १६४.७; २९; ५.७४.५; ९.६९.९; ७१.२; १०.५.५
वव्रिऽवांसम् २.१४.२; ३.३२.६; ४.१६.७; ६.२०.२; ९.६१.२२
वव्रुः ७.९०.४; १०.४५.११
वव्रुरिति वव्रुः ४.१.१५; १६.६
वव्रे ४.१.१३; ५.३१.३; ७.१०४.३; १०.८.७
वव्रे १.६२.७; ३.३८.८
वव्रेः ४.४२.१; २; ५.१९.१
वशः १.९१.६; १२९.१; ८.४६.२१; ६१.४; ९३.१०
वशात् ८.६६.४
वशऽनीः १०.१६.२
वशन्ति ८.२०.१७; २८.४
वशम् १.११२.१०; ११६.२१; ८.८.२०; ४६.३३; ५०.९; १०.४.७; ६६.९; ८४.३; १७१.४
वशस्य ६.२४.५
वशा २.२४.१३

वसुऽपतिम् १.९.९; ३.३६.९; ५.४.१; ८.५२.६; ६१.१०
वसुऽपते २.६.४
वसुऽपते १.१७०.५; २.१.११; ३.३०.१९; १०.४७.१; ११२.१०
वसुऽपत्नी १.१६४.२७
वसुऽभिः १.५८.३; ११०.७; १४३.१; ६; २.३१.१; ३.१९.२; ४९.४; ५.३.८; ५१.१०; ७.५.९; १०.४; ३५.६; ४४.४; ४७.२; ७६.२; ५; ९०.६; ८.३५.१; ९.९३.३; १०.३.२; ६६.३; ७९.७; ९८.१; १०८.७; ११०.३; १२५.१; १५०.१
वसुऽभ्यः ५.४९.५; १०.८७.९
वसुम् १.४४.३; १२७.१; ८.७१.१३; १०.१२२.१
वसुऽमत् ९.६९.८; ८६.३८
वसुऽमता १.११८.१०; १२५.३; ४.४.१०; ७.६७.३
वसुमती इति वसुऽमती ३.३०.११
वसुऽमन्तम् १.१५९.५; २.२४.२; ४.३४.१०; ६.६८.६; ७.७१.३; ८४.४; १०.११.८
वसुऽमान् ७.७१.४
वसुऽयन्तः १.१३०.६; ४.१६.१५
वसुऽयवः १.४९.४; ६२.११; १२८.८[२]; २.११.१; ३.२६.१; ५.३.६; २५.९; ७.३२.२; ८.५२.६; ६१.१०; ९.११२.३; १०.२५.२; ४७.१; ९१.१२
वसुऽया १.९७.२; १६५.१
वसुऽयात् ८.८.१६
वसुऽयुः १.५१.१४; १८६.११; २.३२.१; ५.२९.१५; ६.५१.१२; ७.१.६; ३४.२१; ६७.४
वसुऽयुम् ४.४४.१; ७.६७.५
वसुऽरुचः ९.११०.६
वसुऽरोचिषः ८.३४.१६
वसुऽवनिम् ७.१.२३
वसुऽवसु १०.७६.८
वसुऽवाहनम् ५.७५.१
वसुऽवित् १.१८.२; ९१.१२; १६४.४९; ९.८६.३९; ९६.१०
वसुवित्ऽतमम् १.४५.७; ६.१६.४१
वसुऽविदः ८.६०.१२; ९.१०१.११
वसुऽविदम् ७.४१.६; ८.२३.१६; ६१.५; ९.१०४.४; १०.४२.३
वसुऽविदा १.४६.२
वसुऽश्रवाः ५.२४.१
वसू इति १.१५८.१; २
वसू इति १.१२०.७
वसून् १.४५.१; ३.२०.५; १०.६६.४
वसूनाम् १.७.९; ५८.७; ७६.४; ९४.१३; ९६.६; १२३.४; १२७.७; १२८.५; १६४.२७; १७०.५; २.११.१; ३.३०.१९; ३६.९; ४.१७.६; ५.४.१; ३६.१; ६.४७.६; ५२.५; ७.७.७; ८.७; १६.२; २४.५; २५.२; ३२.५; ४३.४; ७५.५; ८.३१.१४; ३९.४; ४६.१६; ५१.५; ६८.६; ७१.८; १०१.१५; ९.५८.२; ९३.४; १०८.१३; १०.४७.१; ४८.११; ५०.७; ७४.१; ९१.३; १२५.३; १३९.३
वसूनि १.१५.८; ४२.१०; ५९.३; ६७.४; ८४.२०; १२३.६; १३४.४; २.३०.१०; ३२.५; ३.५१.५; ५५.२०; ५६.६; ४.२४.१; ३३.११; ५.४२.३; ६१.१६; ६.१.१३; ५.२; ३; ७.३; १६.४८; ३०.१; ३१.४; ४५.८; २०; ७३.३; ७.६.७; ११.३; २४.१; २७.३; ३४.२२; ४५.३; ७७.४; ७९.३; ८४.४; १०३.१०; ८.१२.२१; ७८.८; ९९.३; ९.७.९; १४.८; १५.६; १८.४; २९.४; ६२.११; ६३.३०; ६४.१८; ६५.२; ६९.१०; ८८.२; ९७.५१–५३; १००.२; ३; १०८.११; १०.६.६; २१.६; ४४.५; ४६.१; ५४.५; ६९.६; ८३.३; १११.१०; १८०.१; १९१.१
वसो इति २.७.१; ३.१५.३; ५७.६; ६.२.१; १६.२४; ४८.९; ८.१९.१२; ३३.२; ९.९८.५; १०.७.२

वहातः ३.३५.२

वहाते ५.३७.३; १०.२७.११

वहाथ १०.६४.१२

वहान् १.८४.१८

वहानि १०.५२.१

वहामि १०.३३.१

वहामि ५.४६.१

वहासि १.७४.६

वहासि १०.५१.७

वहिष्ठयोः ६.४७.९

वहिष्ठा १.१३४.३; ५.५६.६

वहिष्ठाः ४.१४.४; ६.२१.१२; ४०.३; ६३.७

वहिष्ठान् १.१२१.१२

वहिष्ठेभिः ४.१३.४

वहिष्ठैः १०.७०.३

वहीयसः १.१०४.१

वहेथाम् ७.७१.३

वहेथे इति १.१८०.९; ८.२६.१९

वहेथे इति १.१३५.८; १८२.२; ४.४५.३; ८.५.३१

वहेयुः ६.३७.३

वह्नयः १.३.९; १४.६; २०.८; ४८.११; २.२४.१३; ३७.३; ३.६.२; ५.७९.४; ६.५७.३; ७.८२.४; ८.३.२३; ६.२; १२.१५; १०.११४.२; १३८.१

वह्नये २.२१.२

वह्निः १.७६.४; ११३.१७; १२८.४; १२९.५^{२}; १६०.३; १८४.१; २.१७.४; ३८.१; ३.५.१; २०.१; ३१.१; ४.२१.६; ५.५०.४; ६.११.२; १६.९; ७.७.५; १६.९; ८.२३.३; ९४.१; ९.९.६; २०.६; ३६.२; ६४.१९; ८९.१; ९७.३४; १०८.१०; १०.११.६; ६१.९; १०१.११

वह्निऽतमः ४.१.४

वह्निऽभिः १.६.५; ४४.१३; ६.३२.३; ७.७५.५; १०.९३.९

वह्निम् १.६०.१; ३.१.१; ११.४; ३१.२; ७.१६.१२; ८.४३.२०; ९.६५.२८; ९१.१; ९६.१७; १०.१०१.१०; ११५.३

वह्नी इति ७.७३.४; ८.८.१२

वह्ने ९.२०.५

वह्नेः ६.३९.१

वह्येऽशयाः ७.५५.८

वा १.६.९; १०^{२}; ८.६^{२}; ११.८; २३.१७; २२^{२}; ३०.२^{२}; ३१.१८^{२}; ३६.१५; ४७.६; ७; ५४.७; ६८.३; ७१.६; ७६.१^{२}; ८३.६^{२}; ८६.२^{२}; ३; ८; ९४.९^{२}; १००.११; १०१.८^{२}; १०८.७; १०९.१; २; ११२.१९; ११६.२^{२}; १२०.७; १४२.१०; १४७.५; १६१.८; १६२.८; ९; १७^{२}; १६३.१; १६४.२३^{२}; १६६.५; १६७.२; १८०.९; १८५.८^{३}; १८९.६; २.२.१०^{२}; ५.३; १०.२; ११.१६; १३.९; २३.७; २८.१०^{४}; ३०.९; ३४.४; १०; ३.४.४; ६; ६.६; ८^{३}; ९; ८.१; ६; १०; २८.२; ३५.१०^{३}; ४.२.६; ८; २१.३^{२}; २५.१; २; २७.३; ४१.२; ४४.३^{३}; ४८.५; ५१.४; ५.३.१२; १८.४; ३४.३; ५^{२}; ३५.२; ४१.१^{४}; २; ३; १५; १९^{२}; ४२.५; ८; ४८.३; ५२.७^{२}; १४; ५३.१; ५४.७^{२}; ६०.६^{३}; ६२.७; ६५.१; ६७.५; ७३.१; ७९.१०^{२}; ८५.७^{५}; ८; ६.३.८^{२}; १३.४; १५.११^{३}; २३.१; २^{२}; २४.१०; २५.४^{२}; ६^{२}; २७.१; ९; ४०.५^{२}; ४५.११; ४६.७; ८; ४८.२०^{२}; ५०.४; ५२.२^{२}; १३; ६६.८; ७.३.८^{२}; ७.६; १६.११^{२}; ३२.१; ३३.१२; ४२.२; ४९.२^{२}; ५५.३; ८२.८; ९८.४; १०४.९^{३}; १४^{२}; १५; १६; १८; ८.१.१८; ४.१; २; ५.२७; ३६; ८.१४; ९.६; ९; १२^{२}; १९; २१; १०.१^{२}; २; ६^{२}; १२.१६^{२}; १७; १८^{२}; १३.१५; १९.११; १२; १३^{२}; २०.१५; १६; २१.१७^{३}; २२.१५; २४.१६; २७; २६.१७; २७.१९; २०; ३१.१५; ३२.६; ४३.२८; ४४.२३; ४७.१५^{२}; ४८.१५; ४९.७^{२}; ५०.७; ६१.९^{२}; ६५.१; २^{२}; ६६.३; ७५.१४; ७८.१०^{२}; ९३.५; ९७.५; ९.११.७^{२};

५२.५; ६५.२२; २३; ७९.२; ९७.२२; ५४^{२}; १०८.१४; १०.९.८^{२}; १०.१४^{२}; ११.५; १५.२; १६.३; ६; १७.१२^{२}; २२.१^{२}; २७.४; ६; ११; २९.१; ३१.४; ३२.५; ३३.८; ३७.१२; ३८.३; ४०.३; १४^{२}; ४१.३^{३}; ४८.८; ५०.२; ६१.१८; ६४.३; ५; ६९.१२; ७०.५^{२}; ७४.१^{५}; ८६.३; १०; ८७.६^{२}; ९१.११; ९८.१^{३}; १०२.३^{२}; १०५.११; ११९.९^{२}; १०^{२}; १२१.९; १२९.७^{३}; १३२.३; ५; १३९.५; १४८.३; १५४.३; १६१.१; २;

वाः १.१३२.३; २.४.६; ४.१९.४; ८.९१.१; ९८.८; ९.११२.४; १०.९३.३

वाःऽइव ४.५.८; १०.१४५.६

वाक् १.१६४.४५; १६७.३; १७३.३; ८.१००.१०; ११; ९.९७.२२; १०.११४.८; ११५.८; १८९.३

वाकम् १.१६४.२४^{२}

वाकस्य ८.६३.४

वाकेन १.१६४.२४

वाघत् ९.१०३.५

वाघतः १.३.५; ५८.७; ८८.६; ११०.४; ३.२.१; ३७.२; ६.१६.१३; ७.३२.१; ८.७८.४; १०.६२.७

वाघतः ३.६०.४

वाघताम् ३.३.४; ८; १०.३३.४

वाघते १.३१.१४; ४०.४; ४.२.१३

वाघत्ऽभिः १.३६.१३; ३.८.१०; ८.५.१६; ९.१०३.५

वाचः १.७९.१०; १९०.२; ५.७६.१; ७.१०१.१; ९.३३.४; ५०.२; ६२.२६; ८५.७; ९७.३४; १०.९१.१२; १६६.३

वाचः १.११३.१७; १४३.१; १६४.३४; ३५; ३७; ४५; २.२१.६; ८.५९.६; ९.७.३; २६.४; ६२.२५; ६७.१३; ८६.१२; ९६.७; १०१.५; १०६.१०; १०.५३.४; ७१.१; ३; ८१.७; ८७.१३; १३७.७

वाचम् १.४०.६; ५३.१; ९२.९; ११२.२४; १२९.१; १३०.६; ९; १६४.१०; १६८.८; २.४२.१; ३.८.५; ३४.२; ४.२१.५; ३३.१; ५७.५; ५.३६.४; ४३.११; ५४.१; ६३.६; ६.२१.११; ४७.३; ६७.१०; ७.२२.३; ३४.९; १०३.१; ४–६; ८; ८.५.३; ७६.१२; ९६.१२; १००.११; १०१.१६; ९.१२.६; ३०.१; ६४.९; २५; २६; ६८.८; ७२.१; ७३.३; ७; ७८.१; ८४.४; ८६.३३; ९५.२; ५; ९७.१३; ३२; ३६; १०६.१२; १०७.२१; ११३.६; १०.१८.१४; ३४.५; ४२.१; ६६.१४; ७१.२; ४; ५; ९; ९४.१; ५; १४; ९८.२; ३; ७; ११४.९; १३०.४; १७७.२; १८७.१

वाचम्ऽईङ्खयः ९.१०१.६

वाचम्ऽईङ्खयम् ९.३५.५

वाचम्ऽवाचम् १.१८२.४

वाचा १.१२०.५; ८.९.१६; २३.७; ७५.६; १०.१२.२; २३.५; ४२.१; ७६.६; ७७.१; ८७.४; ९५.२; ११४.७

वाचाऽस्तेनम् १०.८७.१५

वाचि १०.७१.२; ६; ११०.११

वाचि ७.५८.६

वाचौ २.४३.१

वाजः १.२७.८; १११.५; १६१.६; २.१.१२; ४.३३.३; ९; ३४.१; ३६.६; ५.१५.५; ४२.५; ६.१३.१; ५०.१२; ७.३७.४; ४८.२; ३; ८.८१.८; १०.१२.५; २३.२; ३५.१३; ६४.१०; ९३.७

वाजऽकृत्येषु १०.५०.२

वाजऽगन्ध्यम् ९.९८.१२

वाजऽजठरः ५.१९.४

वाजऽदा १.१३५.५

वाजऽदाः ३.३६.५

वाजऽदावा ८.२.३४

वाजऽदाव्नाम् १.१७.४

वाजऽद्रविणसः ८.८४.६

वाजऽपतिः ४.१५.३

वाजऽपत्नी ७.७६.६

वाजऽपस्त्यः ६.५८.२

६२.२; ६४.४; ६५.९; १०.६४.६; ६६.१०

वाजिनः ४.३७.४; ७.३८.८

वाजिनम् १.४.८; ९; ६४.६; १०६.४; ११७.९; १२९.१; २[२]; १३०.६; १३५.५[२]; १६२.१२; १७६.५; २.१३.५; ३२.३; ३४.७; ३.२.१४; ४.३८.२; ५.१.७; ६.३; ६.५५.४; ७.७.१; ९५.३; ८.२.३८; १६.३; २४.२२; ४३.२०; २५; ४६.१५; ६१.१२; ८४.८; ९३.३४; ९.६.५; १७.७; २६.१; ५३.४; ६२.१८; ६३.१७; ६५.११; ८७.१; ८९.४; १०६.११; १०.३९.१०; ८७.१; १२२.४; ८; १४१.५; १४३.२; १४७.३; १७८.१; १८८.१

वाजिना ३.२०.२

वाजिना १.१६२.३; २.२४.१२; ३.५३.२३; ६.१६.४८; ६७.४; ७.१०४.६; १०.९३.८

वाजिना ८.३५.२

वाजिनानि १०.१०३.१०

वाजिनाम् १०.१०३.१०

वाजिनाय १०.७१.१०

वाजिनि ३.६१.१; ६.६१.६

वाजिनिऽइव ९.९४.१

वाजिनी ३.६.१

वाजिनीऽवति १.४८.६; १६; ९२.१३; १५; २.४१.१८; ४.५५.९; ६.६१.३; ८.२४.२८

वाजिनीऽवती १.३.१०; ६.६१.४; ७.७५.५; ९६.३; १०.७५.८

वाजिनीऽवतोः १.१२०.१०

वाजिनीऽवसुः १०.९६.८

वाजिनीवसू इति वाजिनीऽवसू १.२.५; २.३७.५; ५.७४.६; ७; ७५.३; ७८.३; ८.५.३; १२; २०; ३०; ८.१०; ९.४; १०.५; २२.७; १४; १८; २६.३; ८५.३; १०१.८; १०.४०.१२

वाजिनीवसो इति वाजिनीऽवसो ३.४२.५

वाजिनीऽवान् १.१२२.८; ५.३६.६; ७.६९.१

वाजिनेन १०.५६.३

वाजिनेयः ६.२६.२

वाजिनेषु १०.७१.५

वाजिनौ ५.३६.६; ८.२५.२४

वाजिन्ऽतमम् ४.३७.५

वाजिन्ऽतमाय १०.११५.६

वाजिऽभिः ३.३०.१८; ६०.७; ६.१६.४; ९.६४.१५

वाजी १.६६.२; ६९.३; ७४.८; ११६.६; १३३.७; १६२.२१; २२; १६३.१२; १७५.१; २.१०.१; २४.१३; ४३.२; ३.२७.८; २९.६; ७; ३८.१; ४.३.१२; ११.४; १५.१; ३६.६; ३८.७; १०; ४०.४; ५८.७; ५.१.४; ३०.१४; ५६.७; ६.२.२; ८; ७.३; २४.२; २६.२; ७.१.१४; ४.८; ३२.१४; ३४.१; ३७.६; ४४.४; ७०.१; ९०.२; ८.३२.१८; ९३.३४; ९.७.४; १५.५; २८.१; ३६.१; ३७.३; ४५.४; ६४.२९; ७४.१; ८; ८६.११; ८७.४; ९३.१; ९६.९; १५; ९७.१०; ४५; १०७.५; १०९.६; १०; १७; १९; १०.३१.११; ३४.४; ५६.३; १०३.५

वाजीऽइव ९.१००.४

वाजे १.३०.६; ४३.८; ८५.५; ४.३७.५; ५.४.६; ७.६७.५; ८.२१.१; ८; ५२.४; ५४.६; ९.६३.१९; १०.६.६; ८१.७; १४९.५

वाजेन ३.६१.१

वाजेभिः १.३.१०; ५.३; ३०.८; २२; ५३.५; ११०.७; ९; १४७.१; ४.२२.३; २९.१; ६.३२.४; ४५.२१; २९; ६१.४; ७.५७.५; ८.२.१९; १६.१२; १९.१८. ४६.११; १०३.९; ९.१८.६

वाजेऽवाजे १.३०.७; १३८.३; ६.६१.१२; ७.३८.८

वाजेषु १.४.८; ९; ७.४; १०.१०; २७.५; ७; ३६.२; ६३.६; ८१.१; १२९.४; १३०.६; १३८.२; १७६.५; २.२३.१३; ३.११.९; १२.९; २७.८; ३७.६; ४२.६; ५.२३.१; ३५.१; ८६.१; ३; ६.१४.५;

वार्ते ८.४०.१
वार्तैः २.१.६
वार्तौ १०.१३७.२
वार्धूऽयम् १०.८५.३४
वाध्रिऽअश्व १०.६९.५; ९; १२
वाध्रिऽअश्वस्य १०.६९.५
वान्ति ५.८३.४
वापुथ १०.१६.१३
वापुषः ५.७५.४
वाम् ६.५५.१
वाम् १.२.४; १७.३; ७–९; २२.३; ४; ३०.१८; ३४.१; ५; १२; ४६.१; ३^{२}; ५; ८; ४७.१; २; ४; ८; ९३.२–४; १०^{२}; १०८.१; ५; ६; १०९.१; २; ११२.२४; ११६.६; ११; १२^{२}; १३; १७; १८; २५; ११७.१; २; ४; ६; ८; १०^{२}; १५; १६; १९; २२^{२}; २३; २५; ११८.१; ३; ४; ५^{२}; १०; ११; ११९.१; २; ४; ५; ७; ९^{२}; १२०.१^{२}; ३; ५; ६; १२२.७; ९; १५; १३५.४^{२}; ५; ६^{२}; १३७.१; २; ३^{२}; १३९.३; ४^{२}; ५; १५१.२; ३; ६–९; १५२.३; ७; १५३.१^{२}; २^{३}; ३; ४; १५४.६; १५५.२; १५७.६; १५८.१; २; ३^{२}; ४; १८०.१^{२}; २–४; ५^{३}; ७; १०; १८१.१–७; ८^{२}; ९; १८२.८^{२}; १८३.३; ४^{३}; ६; १८४.१; ३; ४^{२}; ५; ६; १८५.११; २.२४.१२; ३१.५; ३२.१; ३७.५; ३९.८; ४१.४; २१; ३.४.४; १२.५; ८; ९; ३३.२; ५४.४^{२}; ५८.२–४; ५^{२}; ६; ८^{२}; ९; ६२.१^{२}; २; ४.१४.४^{२}; १५.९; १६.१०; ३८.१; ४१.१^{२}; ८; ११; ४२.९; ४३.४^{२}; ५^{४}; ६^{२}; ७; ४४.१–३; ५^{२}; ६; ७; ४५.२; ४; ७; ४६.३; ७^{२}; ४७.४; ४९.१; २; ५०.१०; ११; ५६.५; ५.३१.८; ९; ४१.१; ३; ४९.१; ६२.१; २^{२}; ४^{२}; ६३.२; ४; ६४.२; ६५.३; ६६.३; ६; ६७.५^{२}; ६८.३; ६९.२^{२}; ४; ७०.१^{२}; २; ७३.४^{२}; ५^{२}; ६; ७^{२}; ८; ७४.१–३; ६^{२}; ७–९; १०^{२}; ७५.१; ४^{२}; ६; ९; ७६.४; ७७.३; ७८.४; ८६.४; ६.५९.१^{२}; २^{२}; ४; ५; ६०.८; १३^{२}; ६३.३^{२}. ४; ६^{२}; ७^{२}; ८^{३}; १०; ११; ६७.२^{२}; ५; ८^{२}; ९–११; ६८.१; ५; ११; ६९.१–५; ७; ७०.३; ७२.१; ३; ७४.१; ७.२.७; ३६.२^{२}; ५३.२; ३; ६०.४; ६१.१; २; ५^{२}; ६^{३}; ६२.४; ६३.५; ६४.१; ४; ६५.१–४; ६६.७; ६७.१^{२}; ३; ४^{३}; ६; ७; ८^{२}; ६८.२–४; ५^{२}; ६; ६९.१; ३–५; ६^{२}; ७०.१; २^{२}; ५; ६; ७१.१; ३; ४^{२}; ७२.१; ४; ७३.२; ३; ७४.१^{२}; ४; ८२.२^{२}; ९; ८३.९; ८४.१^{२}; ८५.१; ४^{२}; ९०.१; ५; ९१.२; ५; ६; ९२.२; ९३.१; ६; ९४.१; ६; ९; ९७.९; ९९.६; १०४.३; ६^{२}; ८.५.१६; १८; १९; २२^{२}; २४; २७; २९; ३३; ३४; ८.४; ६; ८–११; १५; १६; १८; १९; २२; ९.३; ४; ६; ८; ९; १०^{३}; १४^{२}; १०.५; २२.४^{२}; ५; ६; ८; १८; २५.१; ६; २६.३; ४; ९; १३; १४; १६; १८; ३५.२२–२४; ३८.३; ९; ४०.२; ४२.४–६; ५७.३; ४; ५८.३; ५९.१^{२}; ३^{२}; ४; ७३.१–१०; ११^{२}; १२^{२}; १३^{२}; १४–१८; ८५.३; ८६.१; २^{२}; ३; ८७.१; ३; ६; १०१.३; ८; ९.९८.९; १०.१२.४; १३.१; २; २२.६; २९.१; ३९.१^{२}; ४; ५^{२}; ६; १२; १४; ४०.१; २; ५; १२; ४२.२^{२}; ६१.४; ७०.६; ७९.४; ८५.१४; १५; १३२.२; ३; १४३.३; ४; ६. १६७.४; १७८.२
वामऽजाताः १०.१४०.३
वामऽदेवस्य ४.१६.१८
वामऽनीतिः ६.४७.७
वामऽभाजः ३.५५.२२; ६.७१.६
वामम् १.३३.३; १२४.१२; १४१.१२; १९०.५; २.६१.६; ४.५.१३; ३०.२४^{३}; ५.६०.७; ६.१९.१०; ५३.२; ६४.६; ७१.४; ६^{३}; ७.२७.४; ७१.२; ७८.१; ८.२७.२१; ८३.४^{३}; १०.७.४; ४०.१०;

वारेण ९.१.६; ९८.७
वारेभिः ९.२०.१; ३८.१; ६८.७; १०१.१६; १०८.५; १०.७४.२
वारेषु ९.६.१; ६३.१०; १९
वारैः ८.२.२
वाकायाम् १.८८.४
वात्रेऽहत्याय ३.३७.१
वार्यम् १.२६.८; ८१.९; १३९.१०; ३.८.७; २१.२; ४.५३.१; ५.६.३; ६; १६.५; १७.५; ३५.८; ४१.१३; ४८.५; ६.१५.६; ७.१५.११; १२; १६.५; ४२.४; ८.२२.१८; २५.१३; ४३.३३; ९.३५.३; १०.१७.७; २४.२; ६४.१५; १३३.२
वार्यस्य ७.२४.६; २५.६; ८.४४.१८
वार्या १.५८.३; ३.११.९; ४.५५.९; ५.२३.३; ६.१६.५; ८.१.२२; २३.२७; ६०.१४; ७५.२; ९.३.४; १८.४; २१.४; ४२.५; ६३.३०; ६६.४
वार्याणाम् १.५.२; २४.३; ६.५.३; ८.७१.११; १३; १०.९.५; २४.३
वार्याणि १.३५.८; ११३.१५; ११४.५; १४९.५; १५९.१; १६३.१३; १६४.४९; ३.५६.६; ५.४.३; ४९.३; ८०.६; ६.५०.८; ७.२.७; १७.५; ८.१९.२४; ९.९०.२; १०.४५.११
वार्येण १०.२७.१२
वाषागिराः १.१००.१७
वावक्रे ७.२१.३
वावदत् ६.५९.६
वावदतः १०.६८.१
वावदत्ऽभिः १०.६७.३
वावदीति ६.४७.३१
वावशतीः ४.५०.५
वावशन्त १.६२.३; ७.७५.७
वावशानः २.११.८. ३.२२.१; ३५.९; ५१.८; ६.३२.२; ९.९३.२; ४; ९६.१४; १०.५.५
वावशानम् ९.९५.४
वावशाना १.११३.१०; १६४.२८
वावशानाः १.७३.६; ३.२०.१; ५७.३; ४.२६.२; ७.५.५; ३६.६; ५६.१०; ९.८६.३१; ९७.२२; ३४; ३५; १०.१२३.३
वावशाने इति १०.८९.१३
वावशुः ६.५१.१४; ८.३.१८
वावशे २.१४.९
वावश्रे ९.९४.२
वावहिः ९.९.६
वाशः ८.१९.३१
वाशति ५.५४.२
वाशीऽइव ८.१२.१२
वाशीः १.८८.३
वाशीभिः १.३७.२; १०.५३.१०; १०१.१०
वाशीम् ८.१९.२३; २९.३
वाशीऽमन्तः १.८७.६; ५.५७.२
वाशीऽमन्तम् १०.२०.६
वाशीषु ५.५३.४
वाश्रः ९.३४.६
वाश्रम् १०.९९.१
वाश्रा १०.११९.४
वाश्राऽइव १.३८.८; २.३४.१५; १०.१४९.४
वाश्राः १.३७.१०; ९५.६; ८.७.७; ९.१३.७; ७७.१; १०.७५.४
वाश्राःऽइव १.३२.२
वाश्राय ८.४३.१७
वाश्रासः ८.७.३; ४४.२५
वासः १.११५.४; १६२.१६; ७.७७.२; ८.३.२४; ९.८९.२; १०.८५.६; ९७.४; १०२.२
वासःऽदाः १०.१०७.२
वासःऽवाचः १०.२६.६
वासते १०.३७.३
वासय १.१३४.३[२]; १४०.१; ९.७५.५
वासयः ६.३५.१
वासयत् ६.३९.४
वासयथः ६.७२.२
वासयन्तः ८.१.१७
वासयसिऽइव ७.३७.६
वासयामसि ९.८.५; ३५.५; ४३.१; १०४.४
वासयिष्यसे ९.२.४; ६६.१३

५४.४^{६}; ८; १२; ५५.२^{२}; ६; ९; ५९.६; ६०.१; ६१.३; ७^{३}; ९; ६२.७; ६३.२; ५; ७; ६९.२; ७५.७; ७७.२; ७८.१; ५; ६; ७९.२^{२}; ३^{२}; ९; ८०.३; ८१.१; २^{२}; ५; ८३.२; ८; ८५.१–३; ५; ८; ६.१.११^{२}; ४.३; ६; ५.३; ५; ६.३; ४; ७.७^{२}; ८.२; ३^{२}; ९.१–३; ५; ६^{४}; १०.७; १२.६; १३.१; ३; १५.१४; १६.४५; १७.१; ६; ७; १८.३; ५; २०.७; २१.७; २२.४; ६; ९; २४.३; ६; २५.४; २८.४; २९.५; ३०.२; ५; ३१.१; ३३.२; ३४.१; ३५.५; ३७.३; ४; ३९.२–४; ४०.१; ४४.६; ८; १०; १६^{२}; २४; ४५.९; ४७.२; ४८.१७; ५१.१; ५; ५३.३; ४^{२}; ६; ६२.७; ११; ६४.२; ६५.२^{२}; ५; ६६.७; ६७.७; ८; १०; ६९.८; ७२.२; ७३.२; ७४.२; ७५.११; ७.१.९; २१; २.५; ३.२; ४; ६; ४.७; ५.२; ८.२–४; ९.२; १०.२; १३.३; १७.१; २; ७; १८.८; १३^{२}; २१; १९.९; २०.३; २१.४^{२}; २३.३; ४; २५.१; २८.२; ३२.७; ३४.१३; २२; ३६.१^{२}; ५; ३७.२; ३८.१; २; ४८.३; ५६.१३; ५८.३; ५९.२; ६२.३; ६६.११; ६९.३; ७२.४; ७५.१; ३; ७७.५; ७८.१; ७९.१^{२}; २–४; ८६.१; ८८.७; ९०.४; ९१.३; ५; ९५.३; ६; ९९.३; १००.३; ४; १०४.१५; १८; २५; ८.१.१; ४; ४.१३; ५.१; ९; ६.६; १३; ७.१; ८; २३^{२}; २५; ३६; ९.१६^{२}; १२.१९–२१; १३.४; २०; १४.५; ७; १०; १५; १५.५; १७.५; २०.४; ११; २१.६; २३.४; २४.२२; २५.१६; २७.९; १६; १८; २०; २९.७; ३१.८; ३२.५; १९; ३४.३; ३९.६; ४०.६; ४१.१०; ४२.२; ४५.४; ८; १६; २२; २७; ३०; ४६.३३; ४७.२; ३; १०; ५४.६; ५५.१; ५८.२^{२}; ६०.१६; ६१.१३^{२}; ६४.५; ६७.१२; २१^{४}; ७६.२; ३; ७७.१; ७९.८; ८२.६; ८६.१–४; ५^{२}; ८९.४; ९१.५; ९३.१४; २६^{२}; ९४.११; ९७.१४; १००.१२; १०३.२; ९.३.६–८; ५.१; ३; ७.२; १०.५; १३.६; १४.४; १५.३; १६.८; २१.३; २२.३; ५; २४.३; २७.३; २८.१; ३४.१; ३६.३; ३७.३; ३९.४; ४५.३; ४९.४; ५१.३; ६१.१७; १८; ६४.३; ६६.५; २७; ६७.५^{४}; १४; २१; ६८.३; ५; ७०.२; ५; ७१.७; ७४.४; ९; ७५.३; ४; ७९.१; ८०.१; ८३.२; ८५.५; ९; १२; ८६.८; २१; ३४; ३७; ३८; ४०; ४३; ९०.२; ९१.३; ४; ९५.५; ९७.१८; ३२; ३८; ५६; ५८; ९९.७; ८; १००.४; १०१.७; ११; १५; १०२.३; १०३.६; १०६.१०; १०७.२३; १०८.९; १२; १०९.१६; ११०.६; ९; ११२.१; १०.२.७; ३.१; २; ६; ५.१; १०.७; ८; ११.२; १२.५; १३.१; १४.९^{२}; १६.१; ८; १८.३; २१.१–८; २३.१^{२}; ३; ७; २४.१–३; २५.१; २^{२}; ३; ४; ५^{२}; ६–११; २६.७; २७.७; १०; १५; १८; २०; २८.५; ९; २९.३; ८; ३०.११; ३१.९^{२}; ३२.२^{२}; ३३.३; ९; ३४.६; १३; ३५.४; ५; ३८.२; ३९.१३; ४०.९; १०; ४२.४; ४३.५; ९; ४४.८; ४५.४; ५; ८; ११; ४८.१; ४९.९; ५४.५; ५५.३; ६१.१३; २६; ६२.३; ९; ६४.१५; ६६.७; ६७.४; ६; ७^{२}; १२; ६८.४; ९; ६९.२; ७०.४; ५; ७१.३; ४; ८^{२}; ११; ७३.८; ७८.७; ७९.५; ६; ८०.१; ५; ६; ८१.२; ८३.३; ८४.२^{२}; ८५.१९; २८; २९; ३३; ४२^{२}; ८६.१; ५; २०; ८७.५; २५; ८८.१७^{२}; ८९.१; ३; ९०.४; ११^{२}; ९२.३; ५; १०^{२}; ९४.१४^{२}; ९५.३; १२; ९७.१२; ९८.१२^{२}; १०१.३; ४; १०२.२; १०६.१; १०८.८; ११०.४; ५; ११; १११.६; ११२.७; ११३.२; ४; ६; ११४.१; २; ४; १०; ११५.४; ११६.६; ११७.८; ११८.३; १२२.५; १२४.३; १२५.३; ७; १२६.८; १२७.१; १२८.६; १३०.२; १३१.५;

विऽजामातुः १.१०९.२
विऽजामीन् १०.६९.१२
विऽजायते ३.२९.११
विजाऽवा ३.१.२३; ५.११; ६.११; ७.११; १५.७; २२.५
विऽजृम्भते १०.८६.१६; १७
विऽजेन्यम् १.११९.४
विजेषऽकृत् १०.८४.५
विऽजेहमानः ६.३.४
विऽजोषसम् ८.२२.१०
विञ्चन्ति १.३९.५
विट् १.७२.८; ७.५६.५; ९.८८.७
विट्ऽभिः १०.२८.८
विऽतक्षत् १.१५८.५
विऽततः ९.७३.९; १०.१२९.५
विऽततम् १.८३.२; ११५.४; २.३८.४; ५.५४.१२; ९.६७.२३; ८३.१; २
विऽतता १.१५२.४; ६.७५.३
विऽतताः ५.५४.११
विऽततानि ९.९७.५५
विऽतते ९.७३.७
विऽतनोति ५.४८.१
वितन्तसाय्यः ६.१८.६; ४५.१३; ८.६.२२; ६८.११
वितन्तसैते इति ६.२५.६
विऽतन्वते १.११५.२; ६.४६.१२
विऽतरम् १.१२३.११; १२४.५; २.३३.२; ४.१८.११; ५.२९.४; ६.१.११; ८.१००.१२; १०.११०.४
विऽतरित्रता १.१४४.३
विऽततुरम् १.१०२.२
विऽततुराणः ६.४७.१७
वितस्तया १०.७५.५
विऽतस्थानाम् ४.३०.१२
विऽतिरे १०.१०४.५
विऽतिष्ठन् १०.३.३
विऽतिष्ठसे ८.६०.१४; १०.९१.७
विऽतूर्थे १०.६८.३
वित्तम् १.१०५.१–१८; ५.४२.९
वित्तम् ७.७२.२
वित्तऽजानिम् १.११२.१५
वित्तात् ५.६०.६
वित्ते १०.३४.१३
विऽत्वक्षणः ५.३४.६
वित्से ७.९९.१; १०.४.४; ५४.४
विथुरम् १.१८६.२
विथुरा ६.२५.३; ४६.६
विथुराऽइव १.८७.३; १६८.६
विथुरेण ८.९६.२
विथुर्यति १०.७७.४
विद १.८६.८; १५६.३; ५.४१.१३; ५५.२; ८.४७.२
विदः ५.३०.४
विदुः १.४२.७–९; १७३.१३; ४.१.३; ९.२०.३; ५९.४; १११.२
विदत् १.६१.६; ६२.३[२]; ७२.४; ८; ९६.४; २.१९.३; ३.३१.६; ४.२१.८; ५.७.६; ३२.५; ८.६९.६; ७९.६; ९३.१४; ९.९६.१०; १०.२१.५; ४३.४; ६१.१३; ६८.११; ७६.२; ९९.८; १२३.४; १३८.३
विदुत् १.८४.१४; १००.८; १८९.४; २.४२.१; २; ५.४४.८; ४५.८; ६.४७.५; ७.५०.१–३; ९.६८.९; १०.८६.१८
विदतम् १.१५१.२
विदत्ऽवसुः ३.३४.१
विदत्ऽवसुम् १.६.६; ८.६६.१
विदथम् १.११७.२५; २.१२.१५; ७.९३.३; ८.४८.१४; १०.८५.२६; २७
विदथस्य १.५६.२; ६०.१; ३.३.३; ३८.५; ५.३३.९; १०.९१.८; ९२.२
विदथा १.१६४.२१; ३.१.२; ४.३८.४; ६.८.१; ११.२; ८.३९.९
विदथानि ३.१.१८; १४.१; २७.७; ४.१६.३; ६.५१.२; ७.६६.१०
विदथानिऽइव १.१३०.१
विदथाय १०.११.३
विदथुः १.१८२.४
विदथे १.३१.६; १५१.१; १५३.३; १६२.१;

५.८१.१; ८.१.४; ३.३; ४३.१९; ६५.९; ९.२२.३; ३३.१; १०१.१२; १०.१७७.१

विपःऽचितम् १.४.४; ३.२६.९; २७.२; ८.१३.१०; ९.१६.८; ६४.२५; ८६.३६

विपःऽचिता ५.६३.७

विपःऽचिताम् ३.३.४

विपःऽचिते ८.९८.१; ९.८६.४४

विपःऽधाम् १०.४६.५

विऽपक्षसा १.६.२

विऽपत्मनः १.१८०.२

विऽपथयः ५.५२.१०

विपन्यया १.११९.७; ३.२८.५; ६.१६.३४; १०.७२.१

विपन्यवः १.२२.२१; १०२.५; १३८.३; २.२०.१; ३.१०.९; ५.४३.१४; ७.९४.६; ८.२२.११; ८७.६

विपन्यवः ५.६१.१५

विपन्या ४.१.१२

विपन्यामहे १.१८०.७

विपन्युऽभिः ८.१९.१०; ९.२.३

विपन्युवः ९.८६.१७

विपन्यू इति ८.८.१९

विपर्यन्ति ७.२१.२

विऽपर्वम् १.१८७.१

विऽपश्यति ३.६२.९; १०.१२५.४; १८७.४

विपा ५.६८.१; ९.३.२; २२.३; ६५.१२; १०.९९.६

विऽपाकः १.१६८.७

विऽपाट् ३.३३.१

विपानः ८.६.२९

विपाम् ३.३.७; १०.५; ८.६.७; ९.९९.१

विऽपाशम् ३.३३.३

विऽपाशि ४.३०.११

विऽपिपानः ४.१६.३

विऽपिपानम् १.११२.१५

विऽपिपानस्य ७.२२.४

विऽपिपाना १०.१३१.४

विऽपृक्तः १.१६१.३

विपृक्वत् ५.२.३

विऽपृचे ४.१३.३

विऽपृच्छते ९.७०.९

विऽपृच्छम् ७.८६.३

विऽपेततुः १०.९६.९

विप्र १.१४.२; १२७.२; १३०.६; १५०.३; २.३६.४; ४.१९.१०; ५.३१.७; ५१.३; ५८.२; ६.३५.५; ३८.५; ८.१९.२; १७; ७१.५; १०२.१२; १०.५०.७; ८७.२४

विप्रः १.१४.९; २.२४.१३; ३.५.१; ३; ८.५; १३.३; १४.५; २७.८; २९.७; ३३.४; १२; ४.३.१६; ८.८; २६.१; ५.२.११; ४३.१; ७४.७; ६.७.३; १०.३; ११.३; १३.३; ५१.२; ६८.३; ७.५८.४; ६१.२; ६८.४; ७२.३; ८७.४; ८८.४; ६; ९३.४; ८.२.३६; ३.१४; ६.२८; ७.१; ८.९; १२.३१; ३९.९; ४२.५; ४३.१४; ४४.२१; २९; ४६.३२; ६१.९; ७९.१; ९.१८.२; ८४.५; ८७.३; ९७.३७; १०७.६; ७; १०.२६.२; ६१.१६; २३; २४; ६४.१६; ९७.६; १४८.३; १६५.२

विप्रऽजूतः १.३.५

विप्रऽतमः ३.३१.७

विप्रऽतमम् १०.११२.९

विप्रम् १.५१.१; ८६.३; ११२.१३; ११९.७; १२७.१; १६५.१४; ३.२.१३; २६.२; ४.२९.४; ५.१.७; ४१.६; ६.१५.४; ७; ८.७.३०; ११.६; ४४.१०; ९.१३.२; ४०.१; ६५.२९; ६६.८; १०.६७.२; ८७.२२

विप्रऽमन्मनः ६.३९.१

विऽप्रयन्तः ९.२२.५

विप्रऽराज्ये ८.३.४

विप्रऽवचसः ८.६१.८

विप्रऽवाहसा ५.७४.७

विप्रऽवीरः ९.४४.५

विप्रऽवीरम् १०.४७.४; ५

विप्रऽवीरस्य १०.१८८.२

विप्रऽवीराः १०.१०४.१

विप्रस्य १.१७.२; ७६.५; ८५.११; ८६.२;

१२९.११; १४२.२; १५१.६; ५.८१.१; ६.१६.६; ७.२२.४; ५६.१५; ८.१९.१२; ४३.१; ९.१२.८; ४३.३; ६; ४४.२; १०.११.५; २५.१०; २६.५; ३९.८; ४०.१४; ४१.३

विप्रा ७.२.७; ४४.२; ६६.८; ८.२५.२४

विप्रा ६.५०.१०

विप्राः १.२२.१४; २३.३. ४५.७; ८; ८२.२; १६२.७; १६४.४६; २.११.१२; १८.३; ३.७.७; १०.९; २७.११; ३०.२०; ३१.५; ३४.७; ४७.४; ५०.४; ६२.१२; ४.२.१५; १७.१६; २९.५; ५०.१; ५.१३.५; ३०.१५; ४३.७; ८१.१; ६.७०.४; ७.२२.९; ३१.११; ४३.१; ९३.३; ८.६.२; ३३; १२.१३; १३.१७; २३.२५; ४२.४; ६६.१३; ९७.१२; ९.८.४; १२.२; १७.६; ७; ६३.२०; २१; ६४.२३; ८६.३९; ९२.२; ९७.३५; १०.४३.७; १०८.११; ११४.५; १२०.४; १२३.१; ४; १३१.३

विप्राः ३.५३.१०; ७.३८.८; १०.४२.१

विप्राणाम् ५.७६.१; ९.८५.७; ९६.६; १०.२६.४

विप्रान् ६.१७.१४

विप्राय १.११७.११; १८२.३; ३.२१.३; ५.६१.९; ६.६५.४; ८.४३.१५; ८५.५; ९८.१; ९.४७.४; १०.२५.११

विप्रासः १.८.६; २२.२१; ११८.३; ३.३.३; ११.८; ५८.३; ५.८०.१; ६.२२.२; ७.१५.९; ७८.२; ८०.१; ९४.५; ८.३.१८; ९.३; ११.५; ६; १९.१७; २१.४; ५१.१०; ६०.५; ८७.६; ९.२६.१; ८६.२४; १०७.२४; १०८.४; १०.६.५; ३०.४; ७८.१

विऽप्रुतम् १.११६.२४; ११७.४

विप्रेण ८.४३.१४; ४४.१२

विप्रेभिः १.२०.१; २७.९; ७७.५; १२७.२; ५.५१.३; ६.३३.२; ८.६०.३; ८१.८; ९.१०७.११

विप्रेभ्यः ५.३२.१२; १०.१३५.४

क.३५

विप्रैः १.६२.४; १२९.२; ९.३.६

विप्रौ ८.२६.९

विऽबभ्रते १.२८.४

विऽबबाधे १०.८९.१

विऽबभाज ७.१८.२४

विऽबाधः १०.१३३.४

विऽबाध्य २.२३.३

विऽबाल्यम् ४.३०.१२

विऽबोधनम् ८.३.२२

विऽभक्ता ३.४९.४

विऽभक्ता १.२७.६; ४.१७.११; ५.४६.६; ६.३६.१; ७.१८.२४; २६.४; १०.१४७.५

विऽभक्तारम् १.२२.७

विऽभजन् १.१०३.६

विऽभजन्तः २.१३.४

विऽभजन्तम् ५.४९.१; २

विऽभजासि १.१२३.३; १०.११.८

विऽभञ्जनुः ४.१७.१३

विऽभराः ५.३१.६

विऽभर्वः ३.६.९

विऽभागे १.१०९.५; ५.७७.४; ७.३७.३; ४०.१; ५६.२१

विऽभाति १.७१.६; २.८.४; २३.१५; ३५.८; ६.६८.९; ७.९.४; १०.६.२; १२१.६

विऽभाती १.९२.६; १२३.१०; १२४.६

विऽभातीः १.११३.१७; १२३.६; ३.६.७; ४.२.१९; ५१.१; १०; ११; ७.३५.१०; ७८.३; ५; ८८.१२

विऽभातीनाम् १.११३.१५; ४.१३.१

विऽभात्नीम् ३.६१.५; ६; ५.८०.१; ७.७८.४

विऽभानाम् १०.५५.४

विभानो इति विऽभानो ८.१०२.२

विभाऽवः १.५८.९

विभाऽवम् १.१४८.१

विभाऽवरि १.३०.२०; ४८.१; १०; ९२.१४; ४.५२.६; ५.७९.४; १०; ८.४७.१४

विभाऽवसुः ३.२.२; ८.४३.३२; ४४.२४; १०.११८.४
विभाऽवसुम् ५.२५.२; ८.४४.६; १०; १०.९२.१
विभावसो इति विभाऽवसो १.४४.१०; ५.२५.७; ८.९३.२५; १०.१४०.१
विभाऽवा १.५९.७; ६६.१; ६९.५; १४८.४; ३.३.९; ४.१.८; १२; ५.१.९; ४.२; ६.४.२; १०.१; ११.४; ४९.९; १०.६.१; २; ८.४; ६१.२०; ८८.७; ९१.१
विऽभासि १.९२.८; ६.४८.३
विऽभिः १.४६.३; ११७.१४; ११९.४; ५.५३.३; ७४.९; ७५.५; ६.६२.६; ८.५.२२; २९.८
विऽभिद्य १०.६७.५
विऽभिनत्ति ८.३३.७
विऽभिन्दुता १०.१३८.५
विऽभिन्दन् १.१०३.३
विऽभिन्दुना १.११६.२०
विभिन्दो इति विऽभिन्दो ८.२.४१
विऽभिन्नम् १०.१३८.६
विऽभीदकः ७.८६.६; १०.३४.१
विऽभीषणः ५.३४.६
विऽभु १.९.५; १६५.१०; २.२४.१०; ८.१०१.१२
विऽभुः १.३१.२; ३४.१; ६५.५; १४१.९; २.२४.११; ५.४.२; ५.९; १०.९१.१
विभुऽक्रतुम् ८.६९.१५
विभुऽभिः ७.४८.२
विऽभुम् ६.१५.८
विभुमत्ऽभ्यः ८.९६.१६
विभुऽवसुः ९.७२.७; ८६.१०
विभूतऽद्युम्नः १.१५६.१; ८.३३.६
विऽभूतम् १०.१८३.१
विऽभूतयः १.८.९; १६६.११
विभूतऽरातिम् ८.१९.२
विऽभूतिः १.३०.५; ६.२१.१
विऽभूतिम् ६.१७.४; ८.४९.६; ५०.६
विऽभूपति १.११२.४
विऽभूषन् ६.१५.९
विऽभृतः १.७१.४; १४४.२; ३.५५.४; १०.१.२
विऽभृता १०.४५.२; ८०.४
विभृते इति विऽभृते १०.७९.१
विऽभृत्रः २.१०.२
विऽभृत्रम् १.९५.२
विऽभृत्राः १.७१.३; ७.४३.३
विऽभृत्वा ९.९६.१९
विऽभ्यः २.३८.७; ४.२६.४
विऽभ्राजते ८.४३.२२
विऽभ्राजन् ८.९८.३; १०.१७०.४
विऽभ्राजन्ते ५.६१.१२
विऽभ्राजमानः ७.६३.३
विऽभ्राजमानान् ४.३३.६
विऽभ्राट् १०.१७०.१; २
विऽभ्राष्टिम् १.१२७.१
विऽभ्वः ४.३४.९; ७.४८.१; २
विऽभ्वः १.१६६.११; ३.३१.१६; ६.३४.१
विऽभ्वः ४.३६.३
विभ्वऽतष्टः ४.३६.५
विभ्वऽतष्टम् ३.४९.१; ५.५८.४
विभ्वऽतष्टाः ५.४२.१२
विऽभ्वना १०.७६.५
विऽभ्वने ६.६१.१३
विऽभ्वम् ३.३१.१३; ४.७.१; १०.११.४; ४०.१
विभ्वऽसहम् ५.१०.७; ९.९८.१
विऽभ्वा १.११३.१; १६१.६; १९०.२; ४.३३.३; ९; ३४.१; ३६.६; ५.४६.४; ७.४८.३; १०.३.६
विऽभ्वा १०.१३८.५
विऽभ्वी ५.३८.१
विऽभ्वीः १.१८८.५
विऽभ्वे ८.९६.११
विम् ३.४५.१; १०.११५.३
विऽमंहते ८.४५.१२
विऽमदः १०.२०.१०
विऽमदस्य १०.२३.७

विश्वऽदोहसम् ६.४८.१३
विश्वध १.६३.८; १७४.१०; ४.१६.१८
विश्वधा १.१४१.६; ५.८.४; ७.२२.७; ८.५.१; ९.७९.२
विश्वऽधायः १०.८३.६
विश्वऽधायसः १०.१२२.१; १७६.१
विश्वऽधायसम् २.१७.५; ५.८.१; ७.४.५; ८.५.१५; ७.१३; १०.१२२.६
विश्वऽधायाः १.७३.३; ३.५५.२१
विश्वऽधेनाः ४.१९.२
विश्वऽधेनाम् ४.१९.६
विश्वऽपिशः ७.५७.३
विश्वऽपिशा ७.७५.६
विश्वऽपुषम् १.१६२.२२
विश्वऽपुषा ८.२६.७
विश्वऽपेशसम् १.६१.१६
विश्वऽपेशसा १.४८.१६; ४.४८.३
विश्वऽप्सु ६.३५.३
विश्वऽप्सुः १०.७७.४
विश्वऽप्सुम् ८.२२.१२
विश्वऽप्स्न्यः ७.७१.४
विश्वऽप्स्न्यस्य ७.४२.६; ८.९७.१५
विश्वऽप्स्न्याय २.१३.२
विश्वऽभरसम् ४.१.१९
विश्वऽभानुषु ४.१.३; ८.२७.३
विश्वऽभुवे १०.५०.१
विश्वऽभेषजः १०.६०.१२; १३७.३
विश्वऽभेषजीः १.२३.२०
विश्वऽभोजसम् ६.४६.१३
विश्वऽभोजसा ७.१६.२
विश्वऽभोजाः ५.४१.४
विश्वऽभ्राट् १०.१७०.३
विश्वम् १.१६.८; ३१.९; ३६.४; ६; १४; २०; ३७.१५; ३८.१०; ४१.६; ४८.८; ४९.४; ५०.४; ५; ५२.१३; १४; ५७.२; ६; ७३.५; ८; ८१.५; ९; ८५.३; ८६.१०; ९२.९; ९३.३; ९८.१; १०२.८; १०८.२; ११४.१; १२९.४; १३०.८; १६४.४२; ४४; १८५.१; १८६.१; ९; २.२.५; ५.२; १५.४; २२.४; २३.१९; २४.१२; १६; ३३.१०; ३५.१५; ३८.५; ४०.५; ३.४.५; २९.१५; ३०.६; १४; ४४.४; ५४.८; ५५.८; ४.१.१; ५.११; ६.१; १७.१०; ५४.४; ५८.११; ५.६.६; २८.२; ३२.१०; ४१.७; ४८.२; ५०.३; ६३.७; ८१.५; ८३.२; ९; ६.८.३; १३.४; १६.२७; २८; २०.२; १३; २५.८; ३१.२; ५२.१५; ६०.४; ७.७.२; ६; १६.६; २०.३; ५६.२०; ५९.७; ६६.१५; ७६.१; ७७.१–३; ९०.६; ९८.६; ८.३.१६; २०.२६; २४.२१; २६.६; ३१.८; ३९.७; ४०.४; ४१.३; ४७.१३; ४९.८; ५८.२; ७८.५; ७९.२; ८९.६; ९.६१.१८; ६३.५; ६८.९; ८६.२८; १०.२.४; ११.१; १७.१; १०; २०.१०; २२.११; २७.२२; ३५.१३; ३६.४; ३७.२; ४; ५६.५; ५८.१०; ६१.१२; ६४.१५; ८३.१; ८५.४२; ८८.१५; ९२.५; ९६.५; ९९.१२; १०७.१; ८; ११४.४; १२१.७; १२६.४; १३३.२; १३६.१; १७३.४
विश्वऽमनः ८.२३.२
विश्वऽमनसः ८.२४.७
विश्वऽमनाः १०.५५.८
विश्वऽमनुषाम् ८.४६.१७
विश्वऽमहसः १०.९३.३
विश्वऽमानुषः ८.४५.४२
विश्वम्ऽइन्व ३.२०.३; ७.२८.१
विश्वम्ऽइन्वः २.४०.६
विश्वम्ऽइन्वम् १.६१.४
विश्वम्ऽइन्वा ५.८०.२
विश्वम्ऽइन्वाः १०.११०.५
विश्वमिन्वे इति विश्वम्ऽइन्वे १.७६.२; ३.३८.८; ९.८१.५; १०.६७.११
विश्वम्ऽइन्वेभिः ५.६०.८
विश्वम्ऽएजय ९.३५.२; ६२.२६
विऽश्वयत् ७.५०.१
विश्वया ८.१.१९; ६८.२
विश्वऽरूपः १.१६२.२; ३.३८.४; ५५.१९; ५६.३; ६.४१.३; १०.१०.५

१४; १२७.६; ८; १३१.१; १३६.४; १६४.२२; ३९; १८६.२^{२}; २.१.१४; ३.४; १२.७; १६.४; २४.४; २५.५; ४१.१३; १५; ३.१४.४; ३०.१३; ३२.८; ३८.४; ९; ५१.८; ५४.१७; ५७.२; ५८.४; ४.१.१०; १८; १६.१९; १७.५; ६; १८.१; १९.१; ३०.३; ३४.३; ४२.१; ५.३.१; २१.३; २३.३; २९.५; ८; ३१.१०; ३६.२; ४३.१०^{२}; ४५.८; ५१.१३; ५२.४; ५८.३; ६७.३; ६.७.४; ९.५; ७; १६.८; १७.८; ११; १८.१४; ४५.३३; ५०.१४; १५; ५१.५; ५२.७; ८; १०; १३; १४; १७; ५८.२; ६७.५; ६८.४; ७.६.६; २८.१; ३३.११; ३४.२४; ३८.३; ३९.४; ४४.५; ४८.४; ४९.४; ५०.३; ५१.३^{४}; ५२.३; ५७.७; ५९.३; ७८.४; ८२.२; ८.४.५; ६.३१; २३.१८; २७.२; ४; ५; १४; ३०.१; ४; ४१.७; ४६.१२; ४८.१; ५३.४; ५४.३; ६२.७; ६९.११; ९३.१४; ९४.२; ३; ९६.७; १००.१; ९.५.११; १४.३; १८.३; ६७.२७; ८१.५; ९२.४; ५; ९६.४; १०२.५; १०९.२; १५; १०.१२.३; १३.१; १५.६; २४.५; २७.४; ३३.१; ३५.१३^{४}; ३६.१३; ४२.१; २; ६३.६; ११; १७; ६४.६; १७; ६५.१३; १४; ६६.१३; ७०.११; ८२.५; ६; ८५.१४; ४७; ८८.७; ९३.३^{२}; ७; ९८.९; ११२.६; ११३.३; ८; १२०.१; ३; १२१.२; १२८.४; ५; १३०.३; १४२.६; १५७.१

विश्वे इति ४.५६.४

विश्वेन १.५०.१३

विश्वेभिः १.९.१; १४.१; १०; २६.१०; ९१.१७; ९५.९; १८९.३; २.३७.६; ३.२४.४; ४०.३; ४.१०.३; ११.२; ५.२६.४; ४३.१३; ५१.८; ६.१२.६; १५.१६; २१.११; ७.८.५; ११.१; ३८.३; ५७.६; ८.२१.४; ७१.३; ९२.२९; ९.६७.२८; १०.३१.१; ९८.८; ११३.१

विश्वेभ्यः २.५.८; २३.१७

विश्वेषाम् १.५८.७; ६८.१; २.२३.२; २७.१०; ३८.६; ४.१.२०^{२}; ७.३; ९.२; ६.१६.१; ६७.१; ७.५.१; ८.१.२१; ३.२१; १९.३४; ४६.१६; ५३.३; १०२.१०; १०.२.६; ९३.३; १३२.४

विश्वेषु १.१३०.८; १३१.२; १५७.५; ४.२२.५; ७.३०.२; ८.३९.८; ९.९२.३; १०.२५.२; २८.२; ५०.४; १८३.३

विश्वैः १.९१.४; ३.५४.१५; ५.५१.१; ८.३५.३; १०.१६९.४

विश्व्या २.४२.१

विषः ८.१९.११; १०.१०९.५

विषम् १.१९१.१०; ११; १४; १५; १६^{२}; ६.६१.३; ७.५०.३; १०.८७.१८; १३६.१

विषऽवत् १०.८५.३४

विषस्य १.१९१.१२; १३; १०.१३६.७

विषाणिनः ७.१८.७

विषुणः ५.३४.६; ८.२९.१

विषुणक् १.३३.४

विषुणम् ३.५४.८

विषुणस्य ४.६.६; ७.२१.५

विषुणाः ५.१२.५

विषुणे ८.९६.१४

विषुद्रुहाऽइव ८.२६.१५

विषुऽरूपः ५.१५.४

विषुऽरूपम् ७.२७.३

विषुऽरूपा ७.८४.१; १०.१०.२; १२.६

विषुऽरूपाणि ६.७०.३

विषुऽरूपे १.१८६.४

विषुरूपे इति विषुऽरूपे १.१२३.७; ६.५८.१

विषुऽरूपेषु १०.६४.५

विषुऽवतः १.८४.१०

विषुऽवता १.१६४.४३

विषुऽवृत् १०.४३.३

विषुऽवृतम् २.४०.३

विषूचः ६.५९.५; ७.८५.२; १०.७९.७

विषूची ३.५५.१५

विषूचीः १.१६४.३१; २.३३.२; ६.२५.२; ३०.५; १०.१७७.३

वृणक् ७.१८.१२; ८.९७.७^{२}
वृणक्ति ४.७.१०; ६.५१.१६
वृणक्ति १.१२४.६; ३.२९.६; ६.४७.१७
वृणक्तु ७.४६.३; ६०.९; ८.६७.८; १०.१६५.२
वृणक्षि १.५४.५
वृणक्षि १०.१४२.३
वृणजन् ८.४७.५
वृणते १.५८.७; १०.११.४
वृणते १.१४१.६; ४.१९.१; ५.११.४; ६.१७.८; १०.९१.८; ९; १४७.२; १६४.२
वृणानः १.१०८.६; ९.९४.१; १०.१२४.४
वृणाना ५.४८.१
वृणानाः ३.४.५; ५.११.४; ७.१८.१२; १०.१८.६; ८८.४; १२४.८
वृणीत ३.३९.७; ५.५०.१; ८.६.४४
वृणीते १.६७.१; ४.२५.३
वृणीध्वम् ५.२८.६
वृणीमहे ३.२.४; ४.४१.७; ५३.१; ८.३१.१०; ९.६६.१८^{२}; १०.१२६.२
वृणीमहे १.१२.१; ३६.३; ३९.७; ४२.५; ४४.३; ११४.४; ९; १३९.१^{२}; २.२६.२; ४१.१९; ५.२०.३; २६.४; ८२.१; ७; ७.९७.२; ८.४.१५; १४.६; १८.१६; २५.१३; २६.२१; २७.२२; ४४.२०; ६०.१; ६७.४; ८३.१; ९०.२; ९.६१.४; ६५.९; २८; १०.२१.१; ३५.१; २; ३६.२–१०; ११^{२}; १२; १००.१–११
वृणीष्व १०.१२७.८
वृणीष्व ४.३१.११; ७.१९.९
वृणे १.१७.१; ३.१२.३; ५; १९.१; ३३.११; ३७.९; ७.५९.११; ८.३८.१०; ९४.८
वृणोति ७.८२.६
वृण्वते १.५.४
वृण्वते ८.४५.२१
वृण्वते ७.३२.१६
वृण्वे ४.२१.८
वृत ९.१०१.१३
वृतः १.१७४.३; ४.१७.९; ७.९८.४
वृतः ७.७.५; १०.५२.१; ९८.७
वृतम् १.१०२.४; ८.४५.३
वृतम् ६.१७.१२
वृतम्ऽचयः २.२१.३
वृतया ५.४८.२
वृता ४.३१.१
वृताऽइव ६.१.३
वृताः ४.४२.५
वृतान् ४.१९.५; ४२.७
वृताभ्यः १०.३०.७
वृतासः ७.३३.५
वृतौ ५.३७.५; १०.६५.५
वृत्तम् १.१५५.६; ४.३१.४; ५.३६.३
वृत्रः १.३२.७; ८; ८०.१२
वृत्रऽखादः ३.४५.२; ५१.९
वृत्रऽखादम् १०.६५.१०
वृत्रऽघ्नः ८.६६.१०; ७८.७
वृत्रऽघ्ना १.१७५.५
वृत्रऽघ्नी ६.६१.७
वृत्रऽघ्ने ३.३१.१४; ५.८६.३; ९.९८.१०
वृत्रऽतरम् १.३२.५
वृत्रऽतुरम् ४.४२.८; ६.२०.१; १०.४८.८; ९९.१
वृत्रऽतुरा ६.६८.२
वृत्रऽतूर्ये २.२६.२; ६.१३.१; १८.६; ३४.५; ६१.५; ८.७.२४; १९.२०; ७४.९; १२; १०.६६.८; १०४.९
वृत्रऽतूर्येषु १.१०६.२; ६.३८.५; ८.३७.१
वृत्रऽपुत्रा १.३२.९
वृत्रम् १.२३.९; ३२.५; ११; ३३.१३; ३६.८; ५१.४; ५२.२; ८; ५६.५; ६१.१०; ६३.४; ८०.२–४; १०; ११; १३; ८५.९; १०३.८; १२१.११; १६५.८; १७४.२; १८७.१; २.११.९; १८; १४.२; १९.४; ३.३०.८; ३२.६; ३३.६; ३४.३; ३६.८; ४७.३; ५३.११; ४.१६.७; १७.१; ३; ८; १८.७; ११; १९.८; २१.१०; ५.३७.४; ६.१३.३; १७.१; २०.२; ३७.५; ४४.१५; ६०.१; ६८.३; ७२.३; ७.१९.५; २०.२; २१.६; ४८.२; ५८.४; ८.२.३२; ३६;

वृश्च्यन्ताम् १०.८७.१८
वृषऽकर्मन् १.६३.४; १३०.१०
वृषऽक्रतुः ६.४५.१६
वृषक्रतो इति वृषऽक्रतो ५.३६.५
वृषऽखादयः १.६४.१०
वृषऽगणाः ९.९७.८
वृषऽच्युताः ९.६९.७
वृषऽजूतिः ५.३५.३; ८.३३.१०
वृषणः १.१०९.३; १६५.१; १७७.२; १७९.१; १८१.२; १८६.५; २.१६.८; ३.२७.१५; ५४.२०; ४.२.२; ६.९; ४१.६; ५.३१.५; ४७.६; ६.२९.२; ४४.१९[२]; २०; ७.२१.२; ७१.३; ८.१.९; २०.१२; २३.११; ३३.११; १०.५.२; ६६.६[४]; ७; ९२.७; ९४.६
वृषणः १.८५.१२; २.३३.१३; ४.३५.६; ७.५६.१८; २०; २१; ५८.६; ६०.१०; ८.९६.१४
वृषणम् १.१६.१; ६४.१२; ८२.४; ८५.७; १०१.१; ११८.९; १२७.२; १२९.३; १३१.३; १५७.२; १७७.३; १७९.४; २.१६.५; ३.२७.१५; २९.३; ९; ४.१७.१६; २४.७; ८; ५.३६.५; ४०.३; ७५.१; ६.१९.८; ६७.११; ७.२०.५; २३.६; २४.४; ८८.१; ८.१.१; १३.३३; १५.४; ३३.१२; ६१.११; ९४.१२; ९.६.६; ६३.२१; ९०.२; ९७.४९; १०६.१; ३; ५; १०.२७.१०; २८.७; ४७.१–८; ६७.९; १०; १३१.३
वृषणश्वस्य १.५१.१३
वृषणश्वेन ८.२०.१०
वृषणा १.१०.३; १७७.१; २.१६.५; ६; ३.३५.३; ५; ४३.४; ५७.२; ७.१९.६; ८.४.११; १४; १३.२३; ३१; ३३.११; ६१.१८; १०.४९.२; ६६.६; ७; १०२.१२; ११४.३
वृषणा १.९३.१; ७; १०८.३; ११२.८; २४; ११७.३; ४; ८; १२; १५; १८; २५; ११८.१; ६; ११९.४; १५१.२; ३; १८१.८; १८३.१; १८४.२; २.४०.३; ४.१४.४; ६.६२.७; ६८.११; ७.७०.७; ७१.६; ७३.३; ७४.३; ८२.२; ८३.९; १०४.१; ८.२२.७; १२; १६; २६.१; २; १२; ३५.१५; १०.३९.९
वृषणौ १०.६६.७
वृषणौ १.१०८.७–१२; ११६.२१; ११७.१९; १५३.२; १५७.५; १५८.१; १६०.७; ७.६०.९; ६१.५
वृषण्यति ९.५.६
वृषण्यन्तीभ्यः ९.१९.५
वृषण्ऽवती ८.६८.१८
वृषण्ऽवन्तम् १.१००.१६
वृषण्वसू इति वृषण्ऽवसू १.१११.१
वृषण्वसू इति वृषण्ऽवसू २.४१.८; ४.५०.१०; ५.७४.१; ७५.४; ९; ८.५.२४; २७; ३६; २२.८; ९; २६.१; २; ५; १५; ७३.१०; ८५.७; १०.९३.५
वृषण्ऽवान् १.१२२.३; १७३.५; १८२.१
वृषत्ऽअञ्जयः ८.२०.९
वृषऽत्वना ८.१५.२
वृषऽत्वा १.५४.२
वृषऽत्वेभिः १.९१.२
वृषऽधूतस्य ३.३६.२; ४३.७
वृषन् १.१३९.६; ५.४०.१–३; ८.३३.१२; ९.४०.६; ५१.४; १०.८९.९
वृषन् १.७.६; १३१.५; २.१७.८; ३.२७.१५; ५.३३.२; ६.१.१; २२.८; ३३.१; ४४.२०; ७.३१.४; ८.७०.६; ९२.१५; २३; ९३.१९; ९.६४.२; १०.९६.१३; १५३.२; १९१.१
वृषऽनाभिना ८.२०.१०
वृषनाम ९.९७.५४
वृषन्ऽतमः १.१००.२; ६.५७.४
वृषन्ऽतमम् १.१०.१०
वृषन्ऽतमस्य १.१०.१०; ५.३५.३
वृषन्धिम् ४.२२.२
वृषऽपत्नीः ८.१५.६
वृषऽपर्वा ३.३६.२
वृषऽपाणयः ६.७५.७

३.५३.१४; ४.२५.७; ५.२.१२; ७.१५.३; १९.१; ८.४५.१५; ८१.७; १०.२७.१०; ८४.२; ९९.३

वेदः १.४३.९

वेदत् २.३५.२; ५.३०.३; ८.९६.१०–१२

वेदता १०.९३.११

वेदति ८.४५.४२

वेदथः ८.२६.११

वेदनम् १.१७६.४; ४.३०.१३; ७.३२.७

वेदना १.३३.१५

वेदने १०.३४.४

वेदयामसि ४.३६.२; ७; १०.१५१.१

वेदसः २.१७.६

वेदसा ३.६०.१; ८.८७.२

वेदसाम् १.८९.५

वेदि ४.१६.४

वेदिः १.१६४.३५; ७.३५.७

वेदिता ८.१०३.११

वेदिम् १.१७०.४; ५.३१.१२; ७.६०.९; ८.१९.१८; १०.६१.२

वेदिष्ठः ८.२.२४

वेदिऽसत् ४.४०.५

वेदिऽसदे १.१४०.१

वेदी ६.१.१०

वेदी इति २.३.४

वेदीयान् ७.९८.१

वेदेन ८.१९.५

वेद्यः ६.४.२; ८.१९.८

वेद्यम् २.२.३; ८.८४.१

वेद्या ६.१३.४

वेद्यानाम् १०.२२.१४

वेद्याभिः १.१७१.१; ३.५६.१; ६.९.१; ७.२१.५; १०.७१.८

वेद्याय ५.१५.१

वेधः १.७३.१०; १६९.१; ४.२.२०; ३.३; १६; ४२.७; ६.१६.३; २२.११

वेधःऽतम १.७५.२

वेधःऽतमः ६.१४.२

वेधसः १.७२.१; १३१.६; १५६.४; ४.२.१५; ६.१; ३२.११; ५.५२.१३; ६.१५.१७; २५.६; ७.२६.३; ३७.६; ८.२०.१७; ४३.१; ६०.५; ९९.२; ९.२.३; ७.५; १६.७; २६.६; २९.२; ६४.२३; ८६.४; १०.९१.९; १२२.८; १७७.१

वेधसः ५.५४.६

वेधसम् ५.४३.१२

वेधसा १.१८१.७

वेधसाम् १.१२९.१[२]

वेधसे १.६४.१; १५६.२; २.२१.२; ३.१०.५; ५.१५.१; ६.१६.२२; ७.४६.१; ८.४३.११; ९.१०३.१; १०.९१.१४; १४४.१

वेधस्या ९.८२.२

वेधाः १.६०.२; ६५.५; ६९.२; १२८.४[२]; १५६.५; ३.१४.१; ५९.४; ४.१६.२; ६.४४.८; ८.६०.३; ९.१०१.१५; १०.१०.१; ६१.१६; ८६.१०

वेधाम् ९.२६.३; १०२.४

वेनः १.८३.५; १३९.१०; ८.३.१८; ६३.१; १०.१२३.१; २; ५

वेनः १.४३.९; ५.३१.२; ३६.४; ६.४४.१०

वेनतः १.८६.८; ९.९७.२२

वेनतम् ५.७५.७; ७८.१

वेनति ८.६०.७

वेनति १०.१३५.१

वेनन् १०.६१.१८

वेनन्तः १०.१२३.६

वेनन्ता १.२५.६

वेनन्ति १०.६४.२

वेनम् ९.२१.५

वेनस्य १.६१.१४

वेनाः १.५६.२; ८.१००.५; ९.६४.२१; ७३.२; ८५.१०; १०.६४.२

वेनात् ४.५८.४

वेनानाम् ९.८५.११

वेनाम् १.३४.२

वेनीः ८.४१.३

वेने १०.९३.१४

वेन्यः ६.४४.८

वैश्वानरम् ३.३.५; २६.१; २; ६.७.१; २; ८.४; ७.५.५; ९.६१.१६; १०.८८.१२–१४
वैश्वानरस्य १.९८.१; ३.३.११; ६.७.६
वैश्वानराः ८.३०.४
वैश्वानराय १.५९.४; ३.२.१; ३.१; ४.५.१; ६.८.१; ७.१३.१
वैश्वानरे १.५९.३
वोच १.१३२.१; ६.५९.१
वोचः ६.२.११; १४.६
वोचः १.२७.४; ४.५.१२; ६.१८.३; २२.४; ७.१.२२; ६२.२; ८६.४; ८.७५.२; १०.२८.५
वोचत् २.५.३
वोचत् १.११७.२२; १६४.१८; ३.५४.५; ४.५.३; ६.१५.१०; ७.८७.४; १०.१०.६; १२.८; ८८.१७; ११४.७; १२९.६; १३९.६
वोचत २.२१.२; २७.६; ८.२०.२६; २४.२०; २७.१०; ३०.३; ३२.१; ४५.२५; ४८.१४; ५२.९; ६७.६; १०.४०.११; ६३.११; ११३.९; १२८.४
वोचतम् ७.८३.२
वोचतात् ५.६१.१८
वोचति १.१०५.४; १२३.३; १०.११.२; १६.११
वोचतु ३.५४.१९
वोचन् ४.१.१४; १०.६९.९
वोचन्त ५.५२.१६
वोचन्त ५.५२.१६²
वोचम् १.३२.१; ५९.६; १२९.३; १३६.६; १५४.१; १६४.२६; २.१५.१; २१.३; ३.१.२०; ५.३१.६; ४१.१४; ८५.५; ६.८.१; ५२.१४; ७.९८.५; ८.१०१.१५; १०.६९.५; ९३.१४; ११२.८
वोचाति १०.७५.१
वोचाम १.१६६.१; २.३०.७; ३.५५.१८; ४.३२.१०; १०.७२.१
वोचावहै १.२५.१७
वोचें ५.४९.४
वोचे १.४१.८; १५०.१; ४.५.११; ६.५१.३; ७.३३.१; ७३.२; ८.८४.५
वोचेः १.१६५.३
वोचेः १.१३२.३; ७.९३.७
वोचेतम् १.१२०.३
वोचेम १.४३.१; ७५.२; ७.२८.५; २९.५; ३०.५
वोचेम १.४०.६; ७४.१; २.३५.२
वोचेमहि १.१६७.१०
वोचेय १.१२२.५; ४.१.१९
वोचेयम् १०.९१.१३
वोचेयम् १.१२९.६
वोचेयुः १.४.६
वोळ्हम् ८.५.१०
वोळ्हम् २.४१.९; ८.३५.४–६
वोळ्हवे १.४५.६; १३४.३²; ३.२९.४; ४.९.६; ५.१४.३; ५६.६²; ६.६०.१२
वोळ्हा ६.६४.३; ८.२.३५; ९.८१.२; ९६.१५; ११२.४
वोळ्हा ७.६९.१; ७१.४
वोळ्हाम् ८.३२.२९; ९३.२४
वोळ्हुः १.१४४.३
व्यचः १.३०.३; ५२.१४; १०.९२.४
व्यचस्वतीः २.३.५; १०.११०.५
व्यचस्वन्ता ६.२५.६; १०.१०५.५
व्यचिष्ठम् २.१०.४
व्यचिष्ठे ५.६६.६
व्यत ९.६९.५; ७०.२; ८६.३२
व्यतीन् १.१५५.६; ८.६९.१३
व्यतीनाम् ४.३२.१७
व्यथते ५.३७.४; ५४.७; ६.५४.३
व्यथन्ते १०.१०७.८
व्यथमानाम् २.१२.२
व्यथय ६.२५.२
व्यथिः ४.४.३; ५.५९.२; ६.२८.३; ६२.३; ८.४५.१९; १०.३१.१०; ८६.२
व्यथेते इति ३.५४.८

व्यन्तः १.१२७.५[२]; ४.५.५; ६.१.४; ७.२७.५

व्यन्ता १.१२२.४

व्यन्ति ५.२३.३

व्यन्ति १.१०५.७

व्यन्तु २.११.१५; ५.४६.८; ७.१९.६

व्यन्तु ३.८.७; ५.४६.८; ७.१.१८; ५७.६

व्ययति ७.८१.१

व्ययस्व ३.५३.१९; १०.१६.७

व्ययेयम् २.२९.६

व्यश्वऽवत् ८.२३.२३; २४.२२; २६.९; ९.६५.७

व्योमऽसत् ४.४०.५

व्रजः ३.३०.१०

व्रजनम् ७.३.२

व्रजन्तीः ३.५६.४

व्रजम् १.१०.७; ९२.४; १३०.३; १३२.४[२]; १५६.४; २.३८.८; ४.१.१५; १६.६; २०.८; ५.३३.१०; ४५.६; ६.४५.२४; ६६.८; ८.६.२५; २४.६; ३२.५; ९.७७.४; ९४.१; १०२.८; १०८.६; १०.४.२; २५.५; २६.३; २८.७; ४०.८; ४५.११; ६२.७; ९७.१०; ९९.११; १०१.८

व्रजस्य १.१३१.३; ४.५१.२; ६.१०.३; ६२.११

व्रजा ५.६.७

व्रजाऽइव ५.६४.१

व्रजान् ४.३१.१३; ६.७३.३

व्रजिनीः ५.४५.१

व्रजे १.८६.३; ५.३४.५; ७.२७.१; ३२.१०; ८.४१.६; ४६.९; ५१.५; ७०.६

व्रतऽचारिणः ७.१०३.१

व्रततैःऽइव ८.४०.६

व्रतऽनीः १०.६५.६

व्रतऽपाः १.८३.५; ३.४.७; ७.८; ५.२.८; ६.८.२; ८.११.१; १०.३२.६

व्रतऽपाम् १.३१.१०; १०.६१.७

व्रतम् १.२५.१; ३१.२; ९३.८; १०१.३; १२८.१[२]; १३६.५[३]; १४४.१; १६६.१२; २.८.३; २४.१२; ३८.३; ६; ९; ३.४.७; ७.८; ५९.३; ६१.१; ४.१३.२; ५.६९.१; ७.५.४; ८.४०.८; ४१.३; ७; ९.७३.३; ८२.५; १०.१२.५; ३३.९; ३७.५; १२२.२; १६६.४

व्रतस्य ७.६६.६

व्रता १.३६.५; ६२.१०; ६५.२; ६९.४; ७०.१; ९०.२; २.५.४; २७.८; ३८.७; ३.६.५; ७.७; ५५.१; ५६.१; ६०.६; ५.६३.७; ६७.३; ६.१५.९; ८.२५.१७; ३२.२८; ४१.१०; ६७.१३; ९४.२; ९.३५.४; १०.६५.११; ६६.९; १११.४

व्रताऽइव ५.६६.२

व्रतानि १.२२.६; १९; २४.१०; ८४.१२; ९१.३; ९२.१२; १२४.२; १८३.३; २.२८.८; ३.३.९; ३२.८; ५४.१८; ५५.६; ४.५३.४; ५.६९.४; ६.७.५; ८.२; ७.६.२; ३१.११; ४७.३; ७५.३; ७६.५; ८३.९; ८७.७; ८.२५.१६; ४२.१; ४८.९; १०३.१; ९.५३.३; ७०.४; ८८.८; ११२.१; १०.२.४; १०.५; २५.३

व्रताय २.२३.६; ३.३०.४

व्रते १.२४.१५; ३१.१; १२; ८३.३; १०१.३; २.२८.२; ३८.२; ३.३८.६; ५.४६.७; ८३.५[३]; ६.५४.९; ९.९.५; ३५.६; ८६.३७; १०२.५; १०.३६.१३; ५७.६; ६०.४; ६४.५

व्रतेन १.१६३.३; ३.५९.२; ५.७२.२; १०.१३.३

व्रतेभिः ७.३५.९

व्रतेषु ३.५४.५; ९.६१.२४; ६९.१; १०.११४.२

व्रतैः ४.५३.५; ६.१४.३; ८.१.२७

व्रत्याः ८.४८.८

व्रन् ४.५.८

व्रन् ४.२.१६; ५५.६; ५.२९.१२

व्रन्दिनः १.५४.४; ५

व्रयः २.२३.१६

६.३१.४; ८.२.१५; ९.८७.९; १०.४९.११; १०४.४

शचीऽवतः ६.२४.४

शचीऽवते १.५४.२

शचीवसू इति शचीऽवसू १.१३९.५; ७.७४.१

शचीवसो इति शचीऽवसो ८.६०.१२

शचीऽवान् ४.२२.२; ८.२.३९

शच्या ३.६०.६; ४.२०.९; ३५.५^{३}; ५६.३; ६.१७.६; २६.६; ३१.४; ४४.२४; ८.९६.१३; १७; १०.६१.३; १०४.३

शच्याम् १०.६१.१

शण्डिकानाम् २.३०.८

शतऽअनीकाः ८.५०.२

शतऽअरित्राम् १.११६.५

शतऽअर्चसम् ७.१००.३

शतऽअवयम् ५.६१.५

शतऽअश्रिम् ६.१७.१०

शतऽअश्वम् ८.४.१९; १०.६२.८

शतऽआत्मा १.१४९.३; १०.३३.९

शतऽआत्मानम् ९.९८.४

शतऽआयुषम् ६.२.५

शतऽआयुषा १०.१६१.३; ४

शतऽऊतिः ७.६८.३

शतऽऊतिम् ६.६३.५

शतऽक्रतुः २.२२.४; ४.३०.१६; ८.१.११; ३२.११; ७७.१; ८९.३; ९३.३२

शतऽक्रतुम् १.३०.१; ५१.२; ३.५१.२; ८.५२.६; ५३.२; ६१.१०; ९२.१; ९९.८

शतक्रतू इति शतऽक्रतू १.११२.२३

शतंक्रतो इति शतंऽक्रतो ६.४१.५; ८.४६.३

शतक्रतो इति शतऽक्रतो १.४.८; ९; ५.८; १०.१; १६.९; ३०.६; १५; ५४.६; ८२.५; १०५.८; २.१६.८; ३.३७.२; ३; ६; ८; ९; ४२.५; ५.३५.५; ३८.१; ५; ६.४५.२५; ७.३१.३; ८.१३.३१; ३३.११; १४; ३६.१–६; ५२.४; ५४.८; ६१.९; १८; ७६.७; ८०.१; ९१.७; ९२.१२; १३; १६; ९३.२७–२९; ९८.१०–१२; १०.३३.३; ११२.६; १३४.४

शतऽक्त्वः १०.९७.२

शतऽग्विनः ८.४५.११

शतऽग्विनम् १.१५९.५; ४.४९.४; ९.६५.१७; ६७.६

शतऽचक्रम् १०.१४४.४

शतऽतमम् ४.२६.३

शतऽतमा ७.१९.५

शतत्ऽवसुम् १.११९.१

शतऽदातु ९.७२.९

शतऽदायम् २.३२.४

शतऽदाव्नि ५.२७.६

शतऽदुरस्य १०.९९.३

शतऽदुरेषु १.५१.३

शतऽधन्यम् ४.१८.३

शतऽधारः ९.८५.४; ८६.११; ९६.१४

शतऽधारम् ३.२६.९; १०.१०७.४

शतऽधाराः ९.८६.२७

शतऽनीथः १.१००.१२; १०.६९.७

शतऽनीथम् १.१७९.३

शतपत्ऽभिः १.११६.४

शतऽपत्रः ७.९७.७

शतऽपर्वणा १.८०.६; ८.६.६; ७६.२; ८९.३

शतऽपवित्राः ७.४७.३

शतऽब्रध्नः ८.७७.७

शतऽभुजिः ७.१५.१४

शतभुजिऽभिः १.१६६.८

शतम् १.२४.९; ३०.२; ४८.७; ५२.१; ६४.१४; ८९.९; ११६.७; १६; ११७.६; १७; १८; १२६.२^{३}; १२८.३; २.१३.९; १४.६^{२}; ७; २७.१०; ३३.२; ३.३६.१०; ६०.७; ४.२७.१; ३०.२०; ३१.३; ९; १०; ३२.१७; ४८.५; ५.२७.५; ४८.३; ५४.१५; ६१.१०; ६.१७.११; ३४.३; ४७.२४; ४८.८^{२}; ६३.९; ७.३.७; १६.१०; २५.३; ६६.१६^{२}; ९१.६; ९९.५; ८.१.२४; ५.३७; ६.४२; ४६; २१.१०; ४६.३१; ३२; ५५.२; ३^{४}; ५६.३^{३}; ७०.५^{२}; ७७.१०; ९.४८.२; ५२.५; ५६.२; ६१.२७; ९७.२९; १०.१८.४; २९.२;

८.३५.१२; ९.८५.२; ९०.३; ९४.५; ९६.२३; ११०.१२; १०.४२.५; ६९.११; ८३.३; ८४.२; ३; १०७.११; ११२.१; ५; ११६.३; ५; १२०.१; १३८.४; १८०.१; २

शत्रोः १.५१.७; १६५.६; ६.७५.२; ७.४८.३; ९.१९.७

शत्रोःऽशत्रोः ६.१९.३

शनैःऽइव ८.९१.३

शनैः ८.४५.११

शनैःऽइव ८.९१.३

शपथाः १०.८७.१५

शपथ्यात् १०.९७.१६

शपन्तम् १.४१.८

शपातः १०.८७.१३

शफऽआरुजः १०.४४.९

शफऽआरुजम् १०.८७.१२

शफऽच्युतः १.३३.१४

शफम् ८.४७.१७

शफऽवत् ३.३९.६; ५.८३.५

शफात् १.११६.७; ११७.६

शफानाम् १.१६३.५; ५.६.७

शफौऽइव २.३९.३

शबलौ १०.१४.१०

शम् १.५.७; ४३.६; ९०.९[५]; ९३.७; १०६.५; ११४.१; २; १५७.३; १६५.४; १७३.८; १८९.२; २.३३.१३; ३८.११; ३.१३.६; १७.३; १८.४; ४.१.३[२]; १२.५; ५.७.९; ११.५; ४७.७; ५०.५[३]; ५३.१४; ६९.३; ७४.९; ६.२१.४; ३४.३; ४५.२२; ५०.७; ७४.१[२]; ७.६.२; ८.६; ३५.१[५]; २[६]; ३[६]; ४[५]; ५[४]; ६[४]; ७[७]; ८[५]; ९[६]; १०[४]; ११[६]; १२[५]; १३[५]; ३८.७; ५४.१[२]; ६९.५; ८६.८[२]; ८.५.२०; १३.११; १७.६; १८.८; ९[३]; ३९.४; ४८.४; ७१.१५; ७९.७; ८२.३; ९.११.३[४]; ७; ६०.४; ६१.१५; ६९.७; ९१.६; १०९.५; १०.९.४[२]; १५.४; ३७.१०[७]; ११; ५९.८; ८५.४३[२]; ४४[२]; ८६.१५; ९७.१८; १६५.१[२]; ३; १८२.१; २[२]; ३

शमम् १.३३.१५

शमस्य १.३२.१५

शम्ऽआयते ८.८६.५

शम्ऽआये ३.१.१

शमि १.८७.५; २.३१.६; ३.५५.३; ८.४५.२७; १०.४०.१

शमिता २.३.१०; ३.४.१०; ७.२.१०; १०.११०.१०

शमिताऽइव ५.८५.१

शमितारः १.१६२.१०

शमितारा ५.४३.४

शमितुः १.१६२.९

शमी १.११०.४; ४.२२.८; ९.७४.७

शमीनहुषी इति १०.९२.१२

शमीभिः १.२०.२; ३.६०.३; ४.१७.१८; ३३.४; ५.७७.४; ६.३.२; ५२.१; १०.२८.१२

शमीम् ५.४२.१०; ८.७५.१४

शम्ऽगयः २.१.६

शम्ऽगयीम् ९.९७.१७

शम्ऽतनत्रे १०.९८.१; ३; ७

शम्ऽतम ८.५३.५

शम्ऽतमः १.१६.७; ७७.२; १२८.७; १३६.४; ८.१३.२२; ९.१०४.३

शम्ऽतमम् १.४३.१

शम्ऽतमा १.७६.१; २.३३.१३; ३.१३.४; ५.४२.१; ४३.८; ७३.१०; ८.३३.१५; ७४.८; १०.५३.९

शम्ऽतमानि ६.२३.६; ३२.१

शम्ऽतमाभिः ८.५३.५

शम्ऽतमेन ५.७६.३; ७८.४; ७.५१.१; १०.१५.४

शम्ऽतमेभिः २.३३.२

शम्ऽताति ८.१८.७

शंतातिऽभिः १०.१३७.४

शंताती इति शम्ऽताती १.११२.२०

शम्बः १०.४२.७

शम्बरम् १.५१.६; ५४.४; ५९.६; १०१.२;

शर्यीम् १.१४८.४; १०.१७८.३

शर्यैः १.११९.१०

शर्वरीः ५.५२.३

शर्वी १.१००.१८; २.१२.१०; ४.२८.३; ७.८५.२; १०.८७.६

शल्मलिम् १०.८५.२०

शल्मलौ ७.५०.३

शल्यान् १०.८७.४

शर्वः १.८.५; ३७.९; ३९.१०; ५१.१०; ५२.६; ५६.३; ८०.३; १३; ८१.४; ८४.९; १८६.२; २.११.१८; ३.३६.४; ५.३५.४; ५८.७; ८६.३; ८७.२; ६; ६.१९.६; ४३.४; ४८.२१[३]; ७.१०४.३; ८.३.४; ६; ८; १०; २४.९; ५१.१०; ५६.१; ६२.८; १०; ७५.१३; ९.६४.२; १०.२३.२; ५; १४८.४

शर्वःऽभिः १.१३०.४; ६.१७.१

शर्वसः १.५४.१; १००.८; १५; १४५.१; १६७.९; ३.४१.५; ४.२४.१; ५.१५.५; २०.२; ५२.२; ६.१४.४; २९.५; ४४.४; ७.२७.१; ८.२५.५; ६८.४; ९०.२; १०.२२.३; ९९.१

शवसः १.११.२; १३१.४; १६१.१४; ४.३४.६; ३५.१; ८; ३७.४; ४७.३; ५.६.९; ३५.५; ८.६.२१; ४५.२०; ९०.५; ९२.१४; ९७.६; ९.३६.६

शर्वसा १.२७.२; ३९.८; ५१.४; ५२.१०; ११; ५४.२; ५६.४; ६१.१०; ६२.९; ६४.८; ९; १३; ९४.१५; १००.३; १२; १४; १०२.१; ११०.७; १२७.११; १४१.३; १६७.९; १७१.५; २.२२.४; २३.१५; २४.११; १४; ३.३.९; ४.८.८; १६.७; १७.१; ३; १९.४; २२.१; ५; ३८.१०; ५.७.३; ११.५; ३०.४; ४६.६; ६.४.७; १३.३; ५; १५.११; १८.७; १९.२; २०.१; ७; २९.३; ३२.५; ३६.५; ४४.३; ६६.६; ६८.३; ७.२१.६; २३.१; ३०.१; ४८.२; ५७.१; ७४.६; ८५.४; ९३.२; ८.१.२१; १२.२६; १९.१६; २४.२; १७; ७०.६; ८८.४; ९७.९; १०.३१.५; ४३.४; ४९.८; ७३.८; १००.५; १०५.६; १२०.२; ६; ९; १४०.१; १७८.३

शवसान् १.६२.१३; ८.६८.८

शवसानम् ६.३७.३; ८.४६.६

शवसाना ७.९३.२

शवसानात् ८.२.२२

शवसानाय १.६२.१; २

शवसानेभिः १०.९९.९

शवसाऽवन् १.६२.११

शवसिन् ७.२८.२

शवसी ८.४५.५; ७७.२

शर्वसे १.५७.१; ८१.१; ८; १३०.६; ३.३७.१; ५.८७.१; ६.३४.२; ७.२८.३; ६६.८; ८.९.२०; २४.१२; १०.४८.११; ४९.२; ११६.१

शर्वांसि ६.२५.३; ७.२१.९; ४८.२; ५६.७; ८.२.३०; ६८.८; ९७.१३

शर्विष्ठ १.८०.१; ८४.१; ८.६६.१२; ६८.१

शविष्ठ १.८४.१९; १२७.११; १६५.७; ५.२९.१३; १५; ३५.८; ३८.२; ६.२६.७; ३५.३; ७.२१.५; ८.६.३१; १२.१; १३.१२; ३३.१३; ४६.९; १९; ६२.४; ७०.६; १२; ९०.४; ९७.१४; १०.११६.१

शर्विष्ठः ८.६१.१

शर्विष्ठम् ५.४४.१०; ६.१९.६; २२.२; ७; ८.४०.२

शर्विष्ठस्य ८.७४.१४

शर्विष्ठा ६.६८.२

शर्विष्ठाः १.७७.४

शर्विष्ठात् ८.७४.१५

शर्वीरया १.३.२; ३०.१७

शशः १०.२८.९

शशमते ६.२.४

शशमानः १.२४.४; १५१.७; ४.२.९; २३.४; ५१.७; १०.११.५

शशमानम् २.१२.१४; २०.३

शुक्रे २.३४.२; ५.४३.१४
शुक्रेण १.१२.१२; ४५.४; ४८.१४; ४.५२.७; ६.४८.७; ८.४४.१४; ५६.५; ९.८५.१२; १०.२१.८; ४५.७; १२३.८; १८७.३
शुक्रेभिः २.३३.९; ३५.४; ३.१.५; ९.१०२.८
शुक्रैः १.९५.१०; ३.४४.५; ५.७९.८
शुक्रौ १०.८५.१०
शुचतः ६.३.३
शुचता २.३४.१२
शुचते ४.२३.१
शुचत्ऽभिः १०.६७.७
शुचत्ऽरथाः ४.३७.४
शुचध्यै ४.२.१
शुचन्तः ४.२.१५; १७
शुचन्तम् १०.७९.३
शुचन्तिम् १.११२.७
शुचमानः ४.२३.८
शुचयः १.५.५; ६४.२; ७२.३; १३४.४; ५; १८१.२; २.१.१३; २७.२; ९; ३५.३; ४.५१.२; ९; ६.६.३; ४; ६६.४; ११; ७.२.२; ४९.२; ३; ५६.१२; ५७.५; ९०.१; ८.३.३; ४४.१७; ५२.१०; १०.१२४.७
शुचयत्ऽभिः ४.५६.१; २; १०.४.६
शुचयन्तः १.१४७.१
शुचयन्तम् १०.४६.८
शुचये ३.१.१०; ७.४१.६
शुचस्य १०.२६.६
शुचायाः १०.२६.६
शुचाऽशुचा ३.४.१
शुचि १.७१.८; १२१.५; १४०.११; ४.१.६; १९; २.१६; १०.६; ६.१०.२; ५१.१; ९.६७.१२
शुचिः १.६६.१; ९१.३; १२७.७; १४१.४; ५; १४२.३; ९; १६०.१; १८०.३; २.१.१; १४; ५.४; ७.४; २७.१३; ३.५.७; ४.१.७; ५.१.३; ७.८; ११.१; ३; ६.८.१; १५.१; ७.३.९; १०.१; १५.१०; ९५.२; ९७.७; १०४.१६; ८.२.९; १३.१९; २९.५; ४४.२१[३]; ९.१.३; २४.६; ७; ७०.८; ७२.४; ७५.४; ८५.१२; ८६.१३; ८८.८; १०.१७.१०; २९.१; ४३.९
शुचिऽक्रन्दम् ७.९७.५
शुचिऽजन्मनः १.१४१.७; ६.३९.३
शुचिऽजन्मानः ७.५६.१२
शुचिऽजिह्वः २.९.१
शुचिऽदन् ५.७.७; ७.४.२
शुचिना २.५.४; ३५.८
शुचिऽपा ७.९१.४
शुचिऽपाः ७.९०.२; ९२.१
शुचिऽपे १०.१००.२
शुचिऽपेशसम् १.१४४.१
शुचिऽप्रतीकम् १.१४३.६
शुचिऽबन्धुः ९.९७.७
शुचिऽभिः ५.१.३; ६.६२.२
शुचिऽभ्यः ७.५६.१२
शुचिऽभ्राजाः १.७९.१
शुचिम् १.७२.३; १४०.१; २.३५.३; ३.२.१४; १५; ६२.५; ५.४.३; ६.१५.७; ७.४७.१; ५६.१२; ९०.२; ९१.४; ९३.१; ८.१०१.१०; १०२.४; ९.१०५.४
शुचिऽवर्णम् ५.२.३
शुचिऽव्रत ८.४३.१६
शुचिऽव्रत १०.११८.१
शुचिव्रतऽतमः ८.४४.२१
शुचिऽव्रता १.१८२.१; ६.१६.२४
शुचिऽव्रता १.१५.११; ३.६२.१७
शुचिव्रते इति शुचिऽव्रते ६.७०.२
शुचिष्मः ६.६.४
शुचिऽसत् ४.४०.५
शुची ७.५६.१२
शुची इति ४.५६.५; १०.८५.१२
शुचीनाम् १.३०.२; ७.५६.१२; ९.५२.५
शुचीनि २.३३.१३
शुचे १.३१.१७; ६.६.३; ४८.३; ७.८९.३; ८.४३.१३
शुतुद्रि १०.७५.५
शुतुद्री ३.३३.१

अद्धे १०.१५१.२[२]
अमत् २.३०.७
अमऽयुवः १.७२.२
अमस्य १०.११४.१०
अमिष्म २.२९.४; ८.४.७
अयध्वम् ५.५.५; १०.७०.५
अयन्ताम् १०.१८.१२
अयन्ताम् १.१३.६; १४२.६; २.३.५; ७.१७.२; १०.११०.५
अयन्ते ७.७८.१
अयमाणः ३.८.२
अयस्व ३.८.२; ३
अयेताम् ७.२.६
अयेथे इति १०.१०६.२
अवः १.९.७; ८; ४०.४; ४३.७; ४४.२; ५१.१०; ६१.१०; ७३.७; १०; ७९.४; १०२.२; ७; ११०.५; ११७.८; १२६.१; २; ५; १६०.५; १६५.१२; १७१.५; ३.३७.१०. ५३.१५; १६; ४.१७.२०; २६.५; ३१.१५; ३६.९; ३८.५; ५.७.९; १६.४; १८.५; ३५.८; ५२.१; ८६.६; ६.१.४; २.१; ३७.३; ४६.५; ४८.१२; ५८.३; ६५.३; ६; ७०.५; ७.५.८; १८.२४; ३४.१८; ८१.६; ८.९.१७; १३.१२; १५.८; ३१.७; ४६.२४; ५५.५; ६५.९; १२; ७४.९; ८०.५; ८९.४; १०३.५; ९.१.४; ४.१; ६.३; ७.९; ९.९; २०.३; ३२.६; ४४.६; ५१.५; ६१.१०; ६३.१२; ६६.७; ८०.२; ८३.५; ८६.४०; ९८.८; १००.८; १०.२७.११; २८.१२; ५०.१; ६२.७; ६९.३; ९२.१०; ९३.१०; १०२.४; १३१.३; १४०.१; १५५.५
अवःऽएषे ५.६६.५
अवःऽकामम् ८.२.३८
अवःऽजितम् ८.३२.३४
अवःऽभिः १.१४९.२; १५६.२; ३.३०.५; ५९.७; ६.१.११; ८.५.३२
अवःऽसु ३.३७.७

अवत् १.३०.८; १२१.१; ६.४५.२३; ५०.६; ७.३२.५; ८.१.१५; ८१.५
अवत् ४.४३.१; ७.९५.४; ८.४३.२४; ४४.६
अवतः ८.२६.१०
अवथः ५.७४.१
अवर्थ ४.२९.३; ८.९६.१२
अवय ६.३१.५
अवयतम् ७.६२.५
अवयत्ऽपतिम् ५.२५.५
अवयत्ऽसखा ८.४६.१२
अवयन् २.१३.१२
अवयन्तः १.११०.३
अवसः ४.४१.९; ७.१६.१०; ९०.७; ९१.७; १०.६१.२४
अवसा १.९२.८; ३.१.१६; ६.५.५; १०.३; ५; ८.६.४८; १०१.१२; ९.७०.२; ११०.५
अवसि ८.७४.९
अवसे १.३१.७; ५७.३; ७३.५; ९५.११; ९६.९; १०३.४; ११३.६; १२१.१४; १३४.३; ६.१७.१४; ७.१८.२३; ८.७०.९; ९.३२.१; ६२.२२; ८०.३; ९७.२५; ११०.७; १०.३५.५
अवस्यः २.१०.१; ६.१.१०
अवस्यतः ६.४६.१३
अवस्यता १०.७४.२; १४७.२
अवस्यताम् १.१३८.४
अवस्यते १.१२८.१; ८.४७.१२; ६२.४
अवस्यन् १.१७७.१
अवस्यन्तः १.१३१.५
अवस्यम् १.११७.९
अवस्यया १.१२८.६
अवस्यवः १.४८.३; ८५.८; १२५.४; १३२.५[२]; २.३१.१; ७; ४.१६.१५; ५.९.२; ६.१.४; ४५.१०; ८.२४.१८; ५२.४; ९.१०.१; ६६.१०; ८७.५
अवस्यस्य ८.९६.२०
अवस्या १.६१.५; १४६.५; २.१९.७; ६.२७.६; ७.१८.११; २३.१; ९.९६.१६

श्रुत १.२३.८; २.४१;१५; ६.३१;५; १०.६३.२; १२५.४
श्रुतऽऋषिम् १०.४७.३
श्रुतः १.५३.९; ५५.८; २.२०.६; ४.३०.२; ३२.२१; ६.५६.५; ७.३२.१७; ८.२२.५; २४.२; २६.४; ३३.१०; ६२.९; ६७.८; १०.२२.१; २
श्रुतऽकक्षः ८.९२.२५
श्रुतम् १.६.६; १०१.७; ११६.१३; १२०.६; १२२.६; १८४.२; २.३३.११; ५.३९.३; ५२.१७; ७४.६; ७८.५; ६.४९.३; ६२.७; ७.१८.१२; ६२.५; ६८.२; ८.२.२७; १३.१०; २६.१७; ५०.१; ५९.६; ७१.१४; ९३.१६; १०.३८.४; १००.१
श्रुतम् १.१२२.६; १५१.२; २.४१.४; ५.७५.१–९; ७.६८.८; ८.२६.११; १०.९२.१३
श्रुतऽमघम् ८.९३.१
श्रुतऽरथाय ५.३६.६
श्रुतऽरथे १.१२२.७
श्रुतर्यम् १.११२.९
श्रुतर्वणि ८.७४.१३
श्रुतर्वणे १०.४९.५
श्रुतर्वा ८.७४.४
श्रुतऽवित् ५.४४.१२
श्रुतस्य ३.४६.१; ५.८५.५; ६.४९.१२; ८.२.१३; ९६.११
श्रुता ५.७४.२
श्रुताम् ५.६२.५
श्रुताय २.१४.८; ५.८५.१; ६.३८.५; ८.३२.४
श्रुतासु ५.६०.२
श्रुते ८.६६.७; ९.९७.५३
श्रुत्ऽकर्णं १.४४.१३
श्रुत्ऽकर्णः ७.३२.५
श्रुत्ऽकर्णम् १.४५.७; ८.४५.१७; १०.१४०.६
श्रुत्यम् १.११७.२३; १६५.११; २.३०.११; ५.३०.५; ६.७२.५; ७.५.९; ८.४६.१४; १०.८०.१
श्रुत्यस्य १.३६.१२
श्रुत्या ६.२१.६; ३६.५
श्रुत्यानि १०.१३८.६
श्रुत्यै २.२.७; ८.९६.३; १०.११.३
श्रुत्वा ६.५०.५
श्रुधि १.२.१; १०.९; ४४.१३; ४८.१०; १३३.६; १४२.१३; २.११.१; ५.२४.२; ६.१७.३; २१.१०; २६.१; ७.२२.४; ३८.२; ८.२५.१२; ६६.१२; ८२.६; ९५.४; १०.११.९; १२.९; ६१.१४; २१; १२५.४; १४८.५
श्रुधि १.२५.१९; २०; २६.५; ४५.३; ५; १२९.२; १३१.६; २.६.१; ६.२१.८; ३६.५; ४५.११; ७.३२.१; ८.६.१८; २४.१४; ७४.११; ९९.१
श्रुधिऽयुतः ६.६७.३
श्रुयाः २.१०.२
श्रुवत् १.१२७.३
श्रुवन्तु ६.४९.१; १०.१५.५
श्रुष्टये २.३८.२
श्रुष्टिः १.१७८.१; ७.४०.१; १०.१०१.३
श्रुष्टिऽगौ ८.५१.१
श्रुष्टिम् १.६७.१; ६९.४; १६६.१३; २.१४.९; ३२.३; ३.५०.२; ७.१८.६; १०
श्रुष्टिऽमन्तम् १.९३.१२; ५.५४.१४
श्रुष्टी २.३.९; ९.४; १४.८; ३.९.८; ४.३६.४; ६.१३.१; ६८.१; ७.३९.४; ८.२३.१४; १८; ८७.६; ९.१०६.१; १०.२०.६
श्रुष्टीऽवरीः १०.३०.११
श्रुष्टीवाऽइव ७.७३.३
श्रुष्टीऽवानः १.४५.२; १२७.९
श्रुष्टीऽवानम् १.११९.१; ३.२७.२
श्रुष्टीवानाऽइव १०.१०६.४
श्रुष्टौ २.१३.९
श्रूयते १०.२२.१
श्रेणयः १०.१४२.५
श्रेणिः १०.६१.२०; ९५.६
श्रेणिऽदन् १०.२०.३
श्रेणिऽभिः ४.३८.६

ष

स

संविदाने इतिं समऽविदाने ३.५४.६; ६.७५.४

संवृक्तऽधृष्णुम् ९.४८.२

संशिश्वरीःऽइव ८.६९.११; ९.६१.१४

संसत्ऽसु ८.४५.२५

संसृष्टऽजित् १०.१०३.३

संस्कृतः ८.३३.९

संस्कृतऽत्रम् ६.२८.४

संस्कृतम् ५.७६.२

सः १.१.२; ४; ९; ५.३^{४}; ७.६; १०.६; १२.१०; ११; १४.११; १६.५; ९; १८.२; ४; ७; २२.५; २३.१५; २४.२; १२; २५.१२; २०; २६.१; २७.२; ३; ७; ९; ११; १२; ३०.१६^{२}; ३१.१५; ३२.१५; ३६.२; ४; ६; १२; १६; ४०.४; ४१.१; ५; ६; ४४.७; ५२.२; ३^{२}; ५४.३; ७; ११; ५५.२^{२}; ४–६; ५६.३; ६२.४^{२}; ६४.१३; ६८.४; ७०.३; ७७.२; ३^{३}; ४; ५^{३}; ७९.५; ६; ११; ८०.२; ८१.१; ८२.४; ८४.१६; ८६.१; ३; ७; ८७.४; ८९.१०^{२}; ९३.३; ९४.२^{२}; १६; ९५.६; ९६.१; २; ४; ९७.८; ९८.२^{२}; ९९.१; १००.१; ४–८; ९^{३}; १०^{३}; ११; १२; १४; १५; १०२.९; १०३.२; ३; ५^{५}; १०४.६^{२}; १०५.४; ७; ९; १३; १६; १०९.१; ११७.२२; १२१.२; १२२.९; १०; १२३.५; १२५.५; १२७.३; ६; ११; १२८.२; ४; ५^{२}; ७^{३}; १२९.१; २; ६; १३०.१०; १३२.३; १४०.७; १४१.१२; १४३.२; ५; १४४.५; १४५.१^{५}; ५; १४७.४; १४९.१; २; ५; १५०.३; १५३.३; १५४.५; १५६.२; १६०.३; १६४.१६^{२}; २१; २९; ३१^{२}; ३२^{२}; ४६; १६९.१; १७१.५; १७४.१०; १९०.२; ७; ८; १९१.१०; २.२.५; ६; ८; ११; ३.३; ४.३; ५; ७; ६.४; ५^{३}; ८; ९.६; १०.१; १२.१–४; ५^{३}; ६–१५; १३.२–५; ६^{२}; ७–१२; १५.२; ४; ५^{२}; ६; ७; १७.२; ५; ६; १८.१; २^{४}; १९.३–६; २०.३–७; २२.१^{२}; २; ३; २३.१७; २४.१^{२}; ७; ९^{४}; ११; १३; १४; २५.१; ४; ५; २६.३^{४}; २७.१२; ३५.१; ४; ५; ७; १०^{२}; १३^{३}; ३७.१; २; ४१.१०; ३.२.२^{२}; ७; १०^{२}; ११; १२; ४.२; ३; १०; ६.१०; ८.४; १०.३^{३}; ४; ८; ११.१–३; १३.१; ३^{३}; ४; १४.१; १६.३; १८.५; १९.१; ३–५; २०.४; २२.१; २; २५.२; २६.३; ३०.७; ३१.११^{२}; ३२.५; ४०.१; ४१.६; ४५.५; ४६.२; ५१.८; ११; ५३.२१; ५५.१७^{४}; ५६.३; ५९.२; ८; ६२.९; ४.१.२; ५; ८; ९^{२}; १०; ११; २.९; ४.६; ७; ८.२^{२}; ३; ४^{२}; ८; ९.२; ३; १२.१; २; १६.८; १८.४; २४.१; २^{४}; ९; २६.४; २७.२; ३०.२२; ३२.५; ७; ३६.५; ६^{५}; ३७.६^{३}; ३९.३; ४१.२^{२}; ५०.५^{२}; ७; ८; ५१.४; ५३.६; ७; ५६.३; ५७.१; ५.२.४; ७; ३.५; ४.३; ६; ११; ६.२; ३; ७.४; ७; ८.४; ७; ९.१; ७^{२}; ११.२; ६; १२.६; १३.३; ५; १५.३; १६.२; १८.२; २३.४; २४.२; २५.१–३; ९; २८.२; ३३.२; ६; ३६.१; ५; ३७.४; ४१.१२; ४२.३; ४४.३; ८; १०; १२; १३; ४८.५; ५३.१५; ५४.७; ६१.८; १३; ६५.१^{२}; ७७.४; ८१.३; ८२.३; ८३.५; ८६.१; ८७.४; ६.१.६; ९^{२}; २.४; ५; ३.१; ५; ६; ४.२; ४; ५.५; ६; ६.२; ६; ७; ८.२; ९.३^{३}; ४; १०.१; ३; १२.१; ४; ६; १३.३; ४; १४.१; १५.२; ३; १०; १३^{२}; १६.२; १२; २०; २१; २३; १७.२^{२}; १४; १८.२; ६^{२}; ७^{४}; ८; १९.५; २०.५; ८; ९; २१.३; ४^{२}; ८; १२; २२.७; ११; २३.७; ८; २५.६; २७.७; २८.५; २९.४; ३१.५; ३२.२–५; ३३.४; ३५.४; ३६.४; ५; ४३.१–४; ४४.१–३; १३; ४५.१; ४; ११; १५; १७; २०; २१; २७; ४६.२; ४७.४^{२}; १३; २८; २९; ४८.२; ४९.५; ८; १२; ५१.१४; ५६.२; ६६.८; ६८.५^{२}; ६; ७०.३;

७५.१; ७.१.१४–१६; २३^{२}; २.१०; ४.२; ४; ८; ५.२; ७; ६.५; ९.२; १०.५; १२.२^{२}; १५.३; ६; ११; १६.२^{२}; ९; २०.५; ६^{२}; १०; २१.५; १०; २२.२; २३.६; ३२.६; १०; ३३.१२; ३८.३; ४०.३^{२}; ४१.५; ४२.४; ४५.२; ३; ४६.२; ५६.१८; ५९.२; ८; ६०.९; ६१.१; २; ६२.२; ६६.५; ६९.२; ८५.४^{२}; ८६.६; ९३.७; ९५.३^{२}; ९७.४; ७^{३}; १०१.१; २; ६; १०२.१; १०४.१०; ११; १५; ८.१.२२; २७^{२}; २.३५; ३.४; १०; १८; ४.१२; १५; ११.३; १३.१; २; १९; १५.३; १६.८^{२}; ११; १२; १८.१३; १९.४^{२}; ९^{३}; १०^{४}; १४; ३०; २०.१५; १६; २१.२; १०.^{२}; २३.१२; २१; २४.३; २६; २६.२५; २७.१६; १७; ३१.३; ३२.५; १२; ३३.१६; ३९.३; ५^{२}; ६; ७^{२}; ९; ४०.२; ४१.२; ३^{२}; ४^{२}; ५; ८^{२}; ९; १०; ४२.२; ४३.९; १५; २४; २७; ३२; ४४.६; १४; ४६.४; ९; १२; १३; २१; ४८.९; ५१.४; ६; ९; ५२.५; ६; ५६.५; ६०.१२; १४; ६१.९; १५^{३}; ६३.१; ३; ४; ७; ६६.३; ८; ६९.१५; ७१.३; ५; ९; ७४.११; १२; ७८.६; ८०.२; ८७.१; ९०.४; ९२.१५; ९३.३; ७; ८^{३}; २९; ९६.१९^{२}; २०^{३}; २१; ९७.३; ६; ९८.१२; ९९.१; ४; १०१.१; १०२.२; १०३.४; ५^{२}; ९.७.७; ९.३; ४; ११.३; १८.७; २०.२; ३; ६; ३६.२; ३; ५; ३७.१–६; ३९.४; ४०.५; ४१.५; ४४.४–६; ४५.१; २; ४६.५; ४९.४; ५०.५; ५५.४; ५७.३; ४; ५८.१^{२}; २–४; ६१.६; ९; १२; २२; ६२.८; १०; ६४.१२; ६५.१५; २७; ६६.२३; ६७.२२^{२}; ३१; ६८.२; ४; ७०.२; ४–६; ७१.३; ८; ७२.८; ७३.१; ८^{२}; ७४.२; ७; ९; ७६.५; ७७.२^{२}; ७९.३^{२}; ८०.३; ८६.१५; ३२; ३८; ४१; ४२; ८७.३; ८८.२; ९१.५; ९३.४; ९६.३; ८; १०; ९७.९; २५; ३२; ३८^{३}; ३९; ९८.४; ९; ९९.६; ७; १०१.१५; १०४.५; १०५.५; १०७.११; २४; १०८.२; १२; १३; १०९.३; १७; ११०.७; १२; १०.१.२; ६; २.३^{४}; ६; ३.७; ६.१; ४; ७.४; ८.२; ८; १०.१४; ११.१^{२}; ७^{२}; १४.१४; १६.१०; १७.३; ५; २०.६; २५.१०; २६.३; ५; २७.१; २४; २८.२; २९.७^{२}; ३०.३; ३१.४; ७; ८; ३२.७; ९; ३४.११; ३५.७; ३८.२; ४३.३; ६; ८; ४४.५; ४६.१; ३; १०; ४८.१०; ४९.६; ५०.२; ५१.२; ५२.३; ५३.१^{२}; ३; ११; ५५.५; ६१.२; ८; ९; १६^{२}; १७; २३; २६; ६३.१३; ६७.७; ६८.९^{४}; १२^{४}; ६९.३^{४}; ४^{२}; १२; ७०.९; ७७.७^{२}; ७९.४; ८१.१; ४; ७; ८५.२१; ३४; ८६.१६^{२}; १७.^{२}; ८७.१^{२}; ८; ८८.४; ५; ८–१०; १६; ८९.२; ९०.१; ५; ९१.२; ९३.२; ६; ९; ९६.३; ७; ९७.६; १७; २३; ९८.१; ५; ९९.२^{२}; ३–६; ७^{२}; ८; ९; १२; १००.९; १०१.८; १०३.३^{३}; १०७.६; १०८.४; १०९.५; ११०.३; १११.१; ३; ११२.५^{२}; ११४.४^{३}; ११५.५; ११७.२–४; ६; ११८.३; ८; १२१.१; १२२.१; ५; १२३.५; १२५.४; १२८.८; १२९.७; १३१.७; १३९.२; १४०.४; १४७.४^{२}; १४९.३; १५३.५; १६४.५; १७७.३^{२}; १८६.२; १८७.१–५; १९१.१

सका १.१९१.११

सकृत् १.१०५.१८; २.१६.८; ६.४८.२२^{३}; ६६.१; ८.१.१४; १०.३३.३; ९५.१६

सकृत्ऽस्वम् १०.७४.४

सऽकेताः ६.९.५

सक्तुम्ऽइव १०.७१.२

सक्थानि ५.६१.३

सक्थि १०.८६.६; ७

सक्थ्या १०.८६.१६; १७

सकर्मन् १.३१.६

सक्म्यम् ३.३८.७
सऽक्रतवः २.२७.२
सऽक्रतुः १०.१४८.४
सक्रतू इति सऽक्रतू १.९३.५
सक्षणः ५.४१.४
सक्षणि १०.३२.१
सक्षणिः २.३१.४; ८.२४.२६; ९.११०.१
सक्षणिम् १.१११.३; ८.७०.८; ९.७१.४; ७८.३
सक्षणी इति ८.२२.१५
सक्षत् १.१२९.१०; ५.३०.६
सक्षत ८.१३.२८
सक्षन्तः १.१३१.३
सक्षि ५.३३.२
सऽक्षितः ६.४४.६
सऽक्षितौ १.१४०.३
सक्षीमहि ७.३९.६; ५१.१; ५४.३
सक्ष्व १.४२.१
सखा १.४.१०; २२.१९; २६.३; ३१.१; ५३.२; ६३.४; ७२.५; ७५.४; ९१.८; १५; १७; १००.४; १७०.३; १८७.३; २.१.९; २०.३; २४.१; २८.१०; ३.४.१; ३१.८; ३९.५; ४३.४; ५४.१७; ४.४.१०; १६.१८; १७.१७; १८; २५.६; ३१.१; ५२.२; ३; ५.२९.७; ६.३३.४; ४५.१; १७; ५५.३; ५; ७.१८.६; १९.१०; २०.८; ५५.१; ८८.६; ८.२.३९; ४.९; १३.३; १७.१४; ३२.१३; ४३.१४; ४५.१–३; ३७; ७०.११; ९३.३; १००.२; ९.६६.१; ४; ८६.१६; ९६.२; १०१.६; १०.१०.२; २५.९; २६.७; ८; ४२.११; ४३.११; ४४.११; ११७.४; १३६.४–६; १५२.१; १६८.३; १८६.२
सखाऽइव ३.१८.१; ८.४८.४; ९.१०४.५; १०५.५
सखायः १.५.१; २२.८; ३०.७; ५३.११; १६५.११; ३.९.१; ३०.१; ३१.१७; ५५.२२; ४.१२.५; ३२.६; ५.७.१; १२.५; ३१.१०; ३२.१२; ५२.२; ६.२१.५; २६.८; ४५.४; ७.१९.८; २१.९; ३१.१; ६८.७; ८.१.१; २.१६; २१.२; ९; २४.१; १९; ४५.१६; ७०.१३; ९२.३३; ९६.७; १००.५; ९.४५.५; ९६.४; ९७.८; ४३; १०१.१; १०४.१; १०.७१.२; ७; ८; १०; ८५.२३; ८८.१७; १७९.२
सखायः १.४१.७; १६५.१३; ३.२९.९; ५.४५.६; ६.१६.२२; २३.९; ४८.११; ७.९७.२; ८; ८.२०.२३; ९.९८.१२; १०५.१; १०.३०.१४; ५३.८; १०१.१; २; १०३.६
सखायम् १.१२९.४; १८५.८; ४.१.३; २४.६; ५.३१.१२; ८५.७; ६.४५.७; १९; ५५.२; ७५.३; ७.१८.६; ३४.१५; ८६.४; ८.२.२७; ४५.३७; ६१.११; ६२.६; ९.८.७; १०.७.३; ८.७; १०.१; २७.६; ४२.२; ७१.६; ८७.२१; ८९.३; ११७.३; ६
सखाया १.१६४.२०; ३.३५.४; ४३.१; ४; ४.४१.३; ६.४०.१
सखायौ ६.६०.१४
सखिऽत्वनाय ६.५१.१४; ८.१२.६
सखिऽत्वम् ३.१.१५; ४.२५.२; ८.२१.८; ९.३१.६; ६१.४; ६५.९; ६६.१४; १०.१३३.६
सखिऽत्वे १.१०.६; ८.७.३१
सखिऽभिः १.१००.२; ४; १८; ३.१.९; ३९.५; ४७.३; ५१.८; ४.१६.६; ३२.३; ६.३२.३; १०.६७.३; ७; ७३.५; ६; ११२.३
सखिऽभ्यः १.४.४; ५३.२; ७५.४; ८०.६; ३.३०.१५; ३१.१५; ३२.१६; ६२.१; ४.२३.५; ६; ५.२४.२; ६.४४.७; ७.२७.२; ४; ९५.४; ९७.७; ८.९६.२१; ९.४५.२; ६६.१; ४; ९६.१; १०.६.२; ३४.२; ५; ४२.११; ४३.११; ४४.११; ८१.५
सखिऽयतः १.१३१.५
सखिऽयताम् ४.१७.१८
सखिऽयते १.१२८.१; ८.४०.३; १०.९१.१

सखिऽयन् ३.३१.७; ५.४९.१; ६.३२.३

सखिंऽवान् १.१५६.४

सखीन् १.१६५.१३; ३.४.१; ३१.८; ४.३५.७; ५.५३.१६

सखीनाम् १.३०.११; ४.३१.३; ५.६४.५; ७.३२.२५; १०.११२.१०

सखे १.३०.१०–१२; ३.५१.६; ४.१.३; १८.११; ३५.३; ८.७१.९; १००.१२; १०.८७.२१; ११२.१०

सख्यम् १.१५.५; ६२.९; ८९.२; १३८.४; १६३.८; २.१८.८; ३.३१.१४; ४३.२; ५८.६; ६०.३; ४.२३.५^{२}; ६; २५.१; ७; ३३.२; ५.५०.१; ६.१८.५; ४५.२६; ४८.१८; ७.७.२; १८.१२; २१; ३६.५; ८२.८; ८.१०.३; १३.२१; १९.३०; ४४.२०; ४८.२; ६८.८; ११; ७२.२; ९६.७; ९.५६.२; ८६.९; ९७.५; ११; १०.१०.२; ४०.७; ४२.४; ६१.१०; ११; ६२.१

सख्यस्य १.२६.५; ५.५५.९; ८.४४.२२; १०.७८.८

सख्या १.५३.७; ६.२१.७; ५६.२; ८.४३.१४; ४८.१०; १०.५०.२; ७१.१०

सख्या १.७१.१०; १०८.५; १७८.२; २.३२.२; ३.५८.६; ४.३.४; १०.८; १६.२०; ६.४७.१७; ६१.१४; ७.२२.९; ७२.२; ८८.५; ८.८६.१–५; १०.६.२; १०.१; २३.७^{२}; ४८.९

सख्यात् १०.१२४.२

सख्यानि १०.७१.२; ९५.१५; ११३.९

सख्याय १.१०१.१–७; ११९.५; १३८.२; १६७.४; ४.१७.१६; २२.२; ३१.११; ३३.११; ४१.२; ३; ७; ५५.३; ५.२९.११; ६.२९.१; ५७.१; ६०.१४; ७.१८.१२; ८.२१.१४; ८९.२; ९८.३; ९.६६.१८; ८६.२०; १०७.२०; १०.२९.८; ३६.७; ६१.२५; ६४.७; ७३.४; १३१.३

सख्युः १.७२.५; ३.४३.४; ४.३.१३; ८.१.१६; ४५.३६; ६९.७; ९.८६.१६; ९६.२२; १०.३.४; ८६.१२

सख्यै १.२६.३; १६५.११; २.३५.१२; ३.१८.१; ५.२९.७; ७.६७.७; ८.४८.४; ९.१०४.५; १०५.५; १०.११७.४

सख्ये १.११.२; ९१.१४; ९४.१–१४; १३८.३; ३.९.३; ५४.२१; ४.१६.१०; १७.९; २८.१; ५.१६.३; ४४.१४; १५; ६.२७.१; २; ४४.११; ७.५४.२; ८.४.७; २१.१५; ७१.१३; ९.६१.२९; ६६.१४; १०७.१९; १०.२५.१; ४८.५; ७१.५; ८८.२; १२४.९

सख्येभिः ३.१.१९; ३१.१८; १०.११३.९

सख्येषु १.१०.५; १०.१३८.१

सख्यैः ६.१९.१३; १०.१३२.२

सऽगणः १.१०१.९; ३.३२.३; ४७.२; ४; ५२.७; १०.१५७.३

सगरस्य १०.८९.४

सघत् १.५७.४

संकाः ६.७५.५

संगच्छमाने इति सम्ऽगच्छमाने १.१८५.५

सचत ४.५.९

सचत १०.७५.५

सचताम् १.१८३.२

सचते १.९१.१४; १२५.१; १४०.९; १४५.२; १८०.५; २.१८.२; ४.७.११; १२.२; ५.३४.५; ४४.३; ६.२८.३; ८.४.६; ९; ६०.१८; ९.७४.१; ७; ८६.८; ९३.३

सचथाय १.१५६.५

सचथ्यम् ८.१०१.५

सचथ्यैः ५.५०.२

सचध्यै १.१६७.५

सचनः १.११६.१८

सचनःऽतमा ८.२६.८

सचनस्य ६.३९.१

सचनस्यमाना १०.४.३

सऽचनाः १.१२७.११

सचनाऽवन्तम् ८.२२.२

सचन्त १.७३.४; १०.१११.७

सचन्त १.१५६.४; १६४.५०; २.५.५; ३.१.१४; ५.१७.५; ४३.१५; ७.५.४; ७४.५; १०.९०.१६; १७२.१

सचन्ताम् १.२२.११; ९८.३; ४.५.१४; ४१.१०; ७.१०४.१४; १०.८९.१५; १०३.१२

सचन्ते १.५९.६; १३४.२; ३.१३.२; ७.९१.६; १०.५.४; ६४.७

सचन्ते १.६०.२; ७१.७; १००.१३; १२३.८; १९०.२; ३.४०.७; ४.४२.१; २; ४४.२; ७.५.५; ३३.७; ६१.५; ७२.१; ९०.५; ९.८२.५; ८९.५; ९५.४; १०.१२४.८

सचमानः ९.७४.५; ९६.१९; १०.३.३

सचमानाः ५.४२.८

सचमानाय १०.११७.४

सचमानौ ५.३६.६

सचसे ४.११.६; १०.८.६

सचसे २.१.३; ५.२८.२

सचस्यमानः १०.८.७

सचस्व १.१.९; १२९.९[२]; ६.२४.१०

सचस्व ३.५३.१७; ५.३१.२

सचा १.५.२; ७.२; ९.३; १०.४; ४०.१; ५१.११; ६३.३; ७१.४; ८१.८; ८३.५; ९३.११; १२२.८; १३०.१; १३५.३; १३९.७[२]; १४०.७; १६१.५; १६७.७; १७४.६; २.१७.७; ३.१२.२; ५३.१०; ५४.२; ६०.४; ४.१.३; ३.९; ५.१०; ३१.५; ३२.३; ४; ३७.३; ५०.११; ५.१६.५; १९.४; ४४.१२; ४८.४; ५६.८; ९; ६५.३; ७४.२; ६.२४.१; २६.४; ६; ४५.२२; ५७.४; ५९.३; ७.१.२१; २२; २२.४; ३२.२; ५९.३; ८१.२; ९३.८; ८.१.१; ४.२; ३; २१.१५; २५.२४; ३२.२०; ३३.४; ७; ४५.२९; ४६.७; ५१.१; ५२.१; ६१.११; ६६.६; ६८.१७; ७८.२; ९२.२९; ९३.२०; ९७.८[२]; ९.१०.८; ७०.४; १०.२३.४; ५०.७; ६२.६; ९३.५; ९५.८; १०५.४; ९; १३१.४; १३४.४

सचानः ६.२०.२

सचाऽभुवः ८.३१.१०

सचाऽभुवम् १.१११.१; १३१.३[२]

सचाऽभुवा १.३४.११; १५७.४; २.३१.१; ८.३५.१–३; १०.७६.१

सचाऽभुवे १०.११७.४

सचाऽभूः १०.७०.९

सचावहे इति ७.८८.५

सचावहै ६.५५.१

सऽचितः १०.६४.७

सचिऽविदम् १०.७१.६

सचेत ५.५२.१५; ८.१०२.२२

सऽचेतसः ८.५८.१; १०.१.३; ४.५; ६४.७

सऽचेतसम् १०.४४.४

सऽचेतसा १०.११३.१

सऽचेताः १.६१.१०; ४.१६.७

सचेताम् १.१८५.९

सचेते इति २.४१.६

सचेते इति १.१३६.३; ३.३९.३

सचेथे इति ८.५.२

सचेथे इति १.११६.१७; १५२.१; १८०.१; १८३.२; २.३९.२; १०.१०६.१०

सचेमहि ५.५०.२; १०.७.१

सचेमहि १.१३६.६[२]; २.८.६; ८.२५.११; १०.५७.५; ६; ६४.११

सचेय ८.१९.२८; ४८.१०

सचेवहि ८.६९.७; १६

सऽजन्या ४.५०.९

सऽजाताः १०.१०३.६

सऽजातान् १.१०९.१

सऽजात्यम् २.१.५; ३.५४.१६; ८.२७.१०; ७३.१२

सऽजात्यस्य १०.६४.१३

सऽजात्यानाम् ८.८३.७

सऽजात्यै ८.१८.१९

सऽजात्येन ८.२०.२१

सजामि १.१९१.१०

सऽजित्वरीः १०.९७.३

सऽजित्वानम् १.८.१

सुऽजित्वाना ३.१२.४
सुऽजूः १.२३.७; ४४.२; १४; ५.५१.८^{२}; ९^{२}; १०^{२}; ६०.८; ६.४७.२९; ७.३४.१५; ८.९७.१०; १०.७५.६; १०५.९
सुऽजोषः ६.२.३
सुऽजोषसः १.४३.३; १३१.१; १३६.४; १७३.७; २.११.१४; ३.८.८; २०.१; २२.४; ४.३४.६; ८^{४}; ५.२१.३; २३.३; ५७.१; ८.२३.१८; २५.१४; २७.५; १७; ५४.३; ९.५.११; १८.३; ८१.४; १०२.५; १०.६५.१; १२६.१; १७५.३
सुऽजोषसः २.३१.२; ५.५४.६; १०.३५.११
सुऽजोषसम् १०.१५३.४
सुऽजोषसा ३.५८.७; ४.४६.६; ७.७२.२; ८.९.१२; २६.११; १०१.७
सुऽजोषसौ ८.३५.१–२१
सुऽजोषाः १.६५.१; ७२.६; ९०.१; ११८.११; १५३.१; १८६.२; ३; ६; २.३१.४; ३.४.८; ३२.२; ३५.९; ४३.३; ४७.२; ४.५.१; ३४.७^{४}; ३९.३; ५६.४; ५.४.४; ३१.५; ४१.२; ४; ८; ४३.६; ६.३.१; १३.३; १७.११; ४०.५; ४९.७; ५०.१२; १३; ५१.५; ६७.५; ६८.१; ७.२.८; ३.१; ५.९; १०.४; २४.४; ३४.२३; ३८.४; ४८.४; ६०.४; ८.४८.१५; ६३.१२; १०.१८.६; २०.१०; ६१.२७; ८३.२; ११०.३
सुऽजोषौ ३.६२.२
संचरन्ती इति सुम्ऽचरन्ती १.१४६.३; ३.३३.३
संज्ञातऽरूपः १.६९.५
सत् १.१६४.४६; २.४१.१०; ४.५.१०; ५.४४.३; ६.१८.४^{२}; २४.५; २७.२^{५}; ७.१०४.१२; ८.७३.१–१८; ९.६१.१०; १०.५.७; ७२.२; ३; १२९.१
सुतः १.३६.३; ९६.७; ४.६.६; ७.३२.२४; ८७.६; १०४.२१; ८.२३.२६; १०१.११; ९.१९.७; २१.७; ३१.६; ८६.५; ६; १०.२७.४; ५३.१०; १२९.४
सुतःऽमहान्तः ८.३०.१

सुतःऽवीराः ६.७५.९
सुतःऽसंतः ३.३१.८
सत्ऽअश्वः ५.५८.४
सुता ८.४३.१४
सुताम् १.१७३.७; २.१.३; १६.१; ६.६७.१
सुती २.१७.७; ४.३.९; ६.४७.२०; ८.५.१
सुतीः १.१६४.१६; ३.३१.५; ५.२९.५; ८.६.८; १४.८; ९.८७.८; १०.१६९.४
सुतीनऽकङ्कतः १.१९१.१
सुतीनऽमन्युः १०.११२.८
सुतीनऽसत्वा १.१००.१
सुते १.१२४.१२; ५.७.४; ६.४७.२०; ६४.६; १०.११५.६
सुत्तः १.१०५.१३; १४; २.३६.६; ३.४१.२; ७.४२.२; ५६.१८
सत्ता ३.१७.५; ९.८६.६; ९६.२३
सत्ऽपतिः १.५४.७; ९१.५; १००.६; १३०.१^{२}; १७४.१; २.१.४; ३.३४.७; ५.२७.१; ४४.१३; ६.१३.३; १६.१९; ५६.२; ८.१९.३६; १०.८.९; ४३.९
सत्ऽपतिम् १.११.१; २.३३.१२; ५.२५.६; ३२.११; ८२.७; ६.१४.४; २६.२; ४६.१; ८.२.३८; २१.१०; ५३.६; ६९.४; ७४.१०; १०.६०.२
सत्पती इति सत्ऽपती ५.६५.२; ६.६०.६; १०.६५.२
सत्ऽपतीन् ६.५१.४
सत्ऽपते ६.४६.३; ८.६८.१
सत्ऽपुते १.५३.६; १६५.३; ३.४०.४; ६.५१.१३; ८.१२.८; १८; १३.१२; ३६.१–६; ६१.१७; ९३.५; १०.५०.२
सत्यु १.२९.१; ६.४५.१०; ८.९२.१८; ९८.५
सुत्यऽउक्तिः १०.३७.२
सुत्यः १.१.५; ६३.३; ७३.२; ८७.४; १४५.५; १५२.२; १६७.७; १७४.१; २.१२.१५; २२.१–३; २३.११; २४.१४; ३.१४.१; ४.१६.१; २१.१०; ३१.२; ४०.२; ५.२३.२; २५.२; ६.२२.१;

६७.८; ८.२.३६; ३.४; १६.८; ९०.२; ४; ९.७.३; ९२.६; १०.२९.४

सत्यऽकर्मन् ९.११३.४

सत्यऽगिर्वाहसम् १.१२७.८

सत्यऽतर १.७६.५

सत्यऽतरः ३.४.१०; ७.२.१०

सत्यऽताता १०.१११.४

सत्यऽताते ४.४.१४

सत्यऽधर्मा १०.३४.८; १२१.९; १३९.३

सत्यऽधर्माणः ५.५१.२

सत्यऽधर्माणम् १.१२.७

सत्यऽधर्माणा ५.६३.१

सत्यऽध्वृतम् १०.२७.१

सत्यम् १.१.६; ३८.७; ५२.१३; ९८.३; १०५.१२; १५९.३; १८५.११; २.२२.१–३; २४.१२; ३.१४.६; ३०.६; ३२.९; ३९.५; ५४.३; ४.१.१०; १८; १७.५; १०; २८.५; ३३.६; ५४.४; ५.७३.९; ८५.८; ६.३०.४; ७.५६.१२; ६०.१; १०४.१२; ८.३३.१०; ४०.११; ४५.२७; ४६.२; ५९.३; ५; ६२.१२; ७४.१५; ९३.५; १००.३[२]; ९.६४.२; ९२.५; ११३.४; १०.२७.१०; ४७.४; ५५.६; ८७.१२; १०९.६; ११७.६; १३९.५; १७०.२; १९०.१

सत्यऽमद्वा ८.२.३७

सत्यऽमन्त्राः १.२०.४; ७.७६.४

सत्यऽमन्मा १.७३.२; ९.९७.४८

सत्यम्ऽउग्रस्य ९.११३.५

सत्यऽयजम् ४.३.१; ६.१६.४६

सत्यथा १०.६३.११

सत्यऽयोनिः ४.१९.२

सत्यऽराधः ७.४१.३

सत्यऽराधः १.१०१.८

सत्यऽराधसे ७.३१.२

सत्यऽराधाः ४.२४.२; २९.१; ५.४०.७; १०.२९.७; ४९.११

सत्यऽवाचः ३.५४.४

सत्यऽवाचम् ३.२६.९; ७.२.३

सत्यऽवाचा १०.१२.१

सत्यऽशवसः १.८६.८; ९

सत्यऽशवसम् ५.५२.८

सत्यऽशुष्म १०.११२.१०

सत्यऽशुष्मः ३.३०.२१; ४.११.४; ९.९७.४६

सत्यऽशुष्मम् १०.४४.३

सत्यऽशुष्माय १.५१.१५; ५७.१; ५९.४; १०३.६

सत्यऽश्रवसि ५.७९.१–३

सत्यऽश्रुतः ५.५७.८; ५८.८; ६.४९.६

सत्यऽसत्वन् ६.३१.५

सत्यऽसवम् ५.८२.७

सत्यऽसवस्य १०.३६.१३

सत्यस्य २.१५.१; ७.३५.२; १२; ८.५७.२; ६९.४; ९.७३.१

सत्या १.७०.४; २.१५.१; ४.१.७; १७.२०; २२.६; ५.४५.७; ६.६५.५; ७.७५.७; ८३.४; ७; ९.९४.४; १०.२२.१३; ५६.३; १२८.४

सत्याः १.७९.१; १७९.६; १८०.७; ५.६७.४; ६.५०.२; ७.१७.५; ८.४४.२३; ५७.२; १०.११६.८

सत्यानि ६.६७.१०; ९.७८.५

सत्यानृते इति ७.४९.३

सत्याभिः १.१२९.७

सत्याम् १.१०८.६; ९.७०.१; १०.६७.११; १०४.३

सत्यासः १०.१५.१०

सत्ये ९.१०९.६

सत्ये इति ३.६.१०

सत्येन १.२१.६; ७.९०.५; ९.११३.२; १०.६७.८; ८५.१

सत्येभिः ७.७५.७; १०.६७.७

सत्यैः १.६७.३; १०.१५.९; १११.१

सत्रा १.५७.६; ७१.९; ७२.१; २.२०.७; ८; ३.५१.६; ४.१७.६[३]; २१.७; २२.९; ३०.२[२]; ५.६०.४; ६५.५; ६.२०.२; २५.८; ३६.१[३]; २; ४६.२; ७; ७.२५.५; ३१.१२; ३२.१६; ९३.५; ८.२.३०;

१५.१०; ११; ४६.११; ९७.१३; १०१.१२; १०.९६.१३; ११३.५; ११६.४
सत्राः ६.३४.४
सत्राऽकरः १.१७८.४
सत्राचः १०.७७.४
सत्राचा ७.१००.१; ८.२.३७; ९.७७.४
सत्राचीम् ७.५६.१८
सत्राच्या ८.६१.१
सत्राऽजित् ८.९८.४; ९.२७.४
सत्राऽजितः ८.३.१५
सत्राऽजिते २.२१.१
सत्राऽदावन् १.७.६
सत्राषाट् ७.२०.३
सत्राऽसहः २.२१.३
सत्राऽसहम् १.७९.८; ३.३४.८; ५१.३; ८.९२.७
सत्राऽसहे २.२१.२
सत्राऽहनम् ४.१७.८
सत्राऽहम् ५.३५.४
सत्राऽहा ६.४६.३
सत्रे ७.३३.१३
सत्वनम् १०.११५.४
सत्वनाम् ८.९६.४; १०.१०३.१०
सत्वने ६.४५.२२; ८.४५.२१
सत्वनैः ५.३७.४
सत्वऽभिः १.१३३.६[२]; १४०.९; २.२५.४; ३०.१०; ३.३९.५; ४९.२; ५.३४.८; ८.४५.३; ९.३.४; ७६.१; १०.१५५.१
सत्वा १.१७३.५; ४.१३.२; ४०.२; ५.३३.५; ६.१८.२; २२.१; २९.६; ३७.५; ७.२०.५; ८.१६.८; ९.८७.७
सत्वानः १.६४.२
सत्वानम् ८.४०.१०; ११
सत्सत् १०.५३.१
सत्सि ८.११.१०
सत्सि १.१२.४; ७६.४; २.६.८; ३.१४.२; ५.२६.५; ६.१६.१०; ८.२३.२६; ४४.१४; १०.१.७; ४४.५
सद २.३६.४; ७.११.१; ८.९७.८; १०.७०.३
सदः १.८५.२; ६; ७; १२८.३; ५.६१.२; ६.१६.१७; ८.२९.९; ४१.९; ९.७०.२; ९२.३; १०७.१०; १०.९६.२; १३०.२
सदः ३.२४.३; ८.१७.१; ७५.१; ९.२.२; ५५.२; १०६.७; १०.४३.२
सदःऽसदः १०.१५.११; ७६.१
सदःऽसु ७.८५.३
सदत् १.१२८.१; ३.१३.१; ८.१३.२४; १०.९९.३
सदत ७.५९.६
सदत ७.५७.२; १०.१५.११
सदतन २.३६.३
सदतम् ७.९१.४
सदतम् ४.१६.१०; ५.७२.१; २
सदताम् ५.७२.३; ७.४२.५; १०.७०.६; ११०.६
सदतु ७.९७.४
सदथः ५.६७.२
सदन् ४.३.११; ८.६३.२
सदनम् १.९६.७; १०४.५; ११७.१०; १३६.२; २.२३.१; ४०.४; ३.३१.९; १२; ५४.६; २१; ६.७.२; ९.७१.६; १०.१३५.७
सदनऽसदं ९.९८.१०
सदनऽस्पृशः ९.७२.८
सदना १०.१८.१३
सदनात् १.१६४.४७; ४.२१.३; ७.३६.१
सदनानि १.५५.६; ११३.२; १८१.५; ९.९१.१
सदनाय ५.४७.७; १०.९३.५
सदनी १.१८६.११
सदने १.३१.१७; ५३.१; ८४.४; ९५.८; १२२.६; १४४.२; १४८.३; १६९.६; १८९.४; ३.३०.९; ३४.७; ५१.३; ४.१०.८; ४२.४; ५.४३.१२; ४७.१; ६.११.५; ४०.५; ७.३४.१; ३६.३; ८.१३.२; १९.१५; २७.५; ५९.४; ९७.५; ९.१२.१; ३; ७२.६; ७७.४; ९२.२;

१०.११.९; १२.७; ९; ३८.२; ४३.७; ६८.७; ७५.१; १००.१०; १४३.४

सदने इति ७.५३.२

सदनेषु १.५६.६; २.३४.१३; ४.२१.५; ५.३०.११; ८.९.१०; ९.८६.११

सदन्तः ४.२१.६; १०.६१.१३

सदन्ता ७.७०.३

सदन्तु १.१८६.८; ३.४.८; ७.२.८; ४३.३; ८.२७.६; १०.११०.८; १४२.६

सदन्यम् १.९१.२०

सदम् १.२७.३; ३६.२०; ८९.१; १०६.५; ११४.८; ११६.६; १२२.१०; १२९.११; १८५.८; २.१४.१; ३४.४; ३.२.१५; ४.१.१; २.५; ३.१२; १३; ७.७; १२.५; ५.७७.४; ८५.७; ६.१.५; १२; ५०.९; ६७.८; ७.२.३; ११.२; ४१.७; ८०.३; १०.४.७; ७.३; ९३.१; ९४.१०

सदसः १.१८.६; १८२.८; २.१७.७; ३.३६.६; ४.१७.४; ५१.८; ५.८७.४; ६.१७.५; १०.९४.१२; १११.२

सदसि १.४७.१०; १८१.८; २.४१.५; ३.१.१४; ७.२; ५५.१२; ५.४१.१; ९.४०.२

सदस्पती इति १.२१.५

सदा १.१२.२; २२.२०; २४.३; २६.२; ११७.२३; १२५.५; १२९.९; १४०.९; ३.३.८; ११.५; ५४.२१; ४.१.८; ५.४१.९; ७३.५; ६.४५.३३; ७.१.२०; २५; ३.१०; ४.४; १०; ७.७; ८.७; ९.६; ११.५; १२.३; १३.३; १४.३; १९.११; २०.१०; २१.१०; २२.५; ९; २३.६; २४.६; २५.६; २६.५; २७.५; २८.५; २९.५; ३०.५; ३४.२५; ३५.१५; ३६.९; ३७.८[2]; ३९.७; ४०.७; ४१.७; ४२.६; ४३.५; ४५.४; ४६.४; ४७.४; ४८.४; ५१.३; ५३.३; ५४.३; ५६.२५; ५७.७; ५८.६; ६०.१२; ६१.७; ६२.६; ६३.६; ६४.५; ६५.५; ६७.१०; ६८.९; ६९.८; ७०.७; ७१.६; ७२.५; ७३.५; ७५.८; ७६.७; ७७.६; ७८.५; ७९.५; ८०.३; ८३.९; ८४.५; ८५.५; ८६.८; ८७.७; ८८.७; ९०.७; ९१.७; ९२.५; ९३.८; ९५.६; ९७.१०; ९८.७; ९९.७; १००.७; १०१.६; ८.१.२०; ४.९; १९.२८; २०.२२; २३.२८; २५.२१; ४४.२०; २९; ४६.५; ५०.६; ५३.८; ८३.२; ९४.३; १०३.५; ९.९०.६; ९७.३; ६; ११०.४; १०.१.७; ११.५; ६४.११; ६५.१५; ६६.१५; ९३.११; १२२.८

सदांसि ३.३८.६; ५४.५; ९.९१.४

सऽदानः ७.३३.१२

सदान्वे १०.१५५.१

सदाऽपृणः ५.४४.१२

सदाम ७.१.११; ४.६; ८.२१.१५

सदाऽवृध ५.३६.३

सदाऽवृधः ४.३१.१; ८.२४.१६; ९.४४.५

सदाऽवृधम् ८.१३.१८; ६८.५; ७०.३

सदाऽवृधा ८.१८.६

सदाऽसहम् १.८.१

सदाऽसाः ४.१६.२१; १७.२१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११; ५६.४

सदाऽसातमम् ४.३७.५

सदाऽसाम् ७.३९.६

सऽदिवः २.१९.६

सऽदृङ् १.९४.७; ८.११.८; ४३.२१

सऽदृशीः १.१२३.८[2]; ३.३५.३; ५२.८; ४.५१.६; ६.४७.२१

सदेम ६.१.६; ७५.८; १०.१६९.४

सद्म १.३८.१०; ७३.१; १७३.३; ३.५५.१४; ४.१.८; ९.३; ५.८७.७; ६.११.५; ६७.७; ७.१८.२२; ९.७.३; ८३.५; ९७.१; १०.२०.५; ६७.१०; ९६.१०

सद्मऽइव १.६७.५; २.१५.३; ९.९२.६

सद्मन् १.१५१.५; ७.१८.११; ४२.२; १०.१०५.९

सद्मनः ६.४७.२१

सद्मनी इति १.१८५.६

सद्मनोः ३.५५.२
सद्मऽबर्हिषः १.५२.४
सद्मऽमखसम् १.१८.९
सद्मऽसु १.१३९.२; ५.२३.३
सुद्मानम् १.१७३.१; ६.५१.१२
सद्मानि १.१३९.१०; ६.३०.२; १०.१.१
सुद्यः १.५.६; ८.९; २७.६; ६१.७; १४; ७१.९; ९६.१; १०४.२; ११५.३; ११६.१५; १२२.७; १४; १२३.८; १२६.२; १२८.३; १२९.१; १४५.४; २.११.१२; १९.४; ३.५.८; २९.३; ३१.७; ३२.९; १०; ४८.१; ५५.५; ५७.१; ५८.८; ४.७.९; १०; १५.८; १६.१२; २८.२; ३०.१८; ३१.८; ३३.१; ४५.७; ५१.५; ७; ५.१.९; ४७.४; ५४.१०; ६.१२.५; १९.२; ४५.३२; ४८.२१; ६२.१; ६८.७; ७.४.२; ५.७; ७.४; १८.१३; १९.५; ९; ३२.५; ७५.४; ९३.१; १०१.१; ८.३.१०; १२.४; ४६.२५; ७७.८; ९६.२१; ९.१८.६; ६१.२; १०.६.७; २७.१९; ३१.१०; ३९.८; ४५.४; ६२.८; ९३.१५[२]; ११०.११; ११५.१; १२०.१; १७३.८
सुद्यःऽअर्थम् १.६०.१
सुद्यःऽऊतयः १०.७८.२
सुद्यःऽऊतयः ५.५४.१५
सुद्यःऽजुवः ८.८१.९
सुद्यःऽवृधम् ३.३१.१३
सुधनिऽत्वम् ४.१.९
सुऽधन्यः ४.४.१४; ६.५१.३
सुऽधन्यम् १०.५०.३
सुऽधन्या १०.९३.५
सुधऽमाः ७.१८.७
सुधऽमात् ४.२१.१
सुधऽमादः १.१२१.१५; ३.४३.६; ५.२०.४[२]; ६.३७.१; ६९.४; ७.४३.५; ७६.४; १०.४४.३
सुधऽमादम् १.१८७.११[२]; ४.२३.२; ७.३२.१; ८.२.२८; १०.१४.१०; ८८.१७
सुधऽमादे १.३०.१३; ३.३५.४; ४३.३; ७.२२.३; ८.२.३; ९.६२.६; १०.३५.१०; ९६.१२
सुधऽमादेषु १.५१.८
सुधऽमाद्यः ८.३.१; ५४.५; ९७.७; ९.२३.६
सुधऽमाद्या ८.१३.२७; ३२.२९; ९३.२४
सुधऽमाद्यानि ४.३.४
सुधऽमाद्यासः १०.१०४.४
सुधऽवीर् ६.२६.७
सुधऽस्तुति ५.१८.५
सुधऽस्तुतिम् १.१७.९; ४.४४.६; ८.१.१६
सुधस्तुती इति सधऽस्तुती ८.३८.४
सुधऽस्तुत्याय ८.२६.१
सुधऽस्थम् १.१५४.१; ३; १६३.१३; ३.६२.१५; ७.३९.४; ९७.६; ९.१.२; १६.४; १७.८; २१.३; ६५.६; १०७.५; १०.३२.४; ६१.१९
सुधऽस्था ३.२०.२; ५६.५; ९.१०३.२
सुधऽस्थात् १.११५.४; ५.३१.९; ७.६०.३; ८.११.७
सुधऽस्थानि ३.१२.८; २५.५
सुधऽस्थे १.१०१.८; १४९.४; २.४.२; ९.३; ३.६.४; ७.४; २३.१; ५१.९; ५.२९.६; ४५.८; ५२.७; ६४.५; ८७.३; ६.५२.१५; ८.४५.२०; ७९.९; १०.११.९; १२.९; १६.१०; ४०.२; ४६.२; ६४.८; ६७.९
सुधस्थे इति सुधऽस्थे १०.१७.६
सुधऽस्थेषु ९.४८.१
सधिः ८.४३.९
सुध्री २.१३.२
सुध्रीचीः १.१६४.३१; ३.३१.१६; ६.३६.३; १०.४३.१; १११.१०; १७७.३
सुध्रीचीनः १०.११२.३
सुध्रीचीना १.१०८.३; ३.५५.१५; १०.१०६.१
सुध्रीचीनाः १.१०५.१०; १३४.२
सुध्रीचीनेन १.३३.११; ४.२४.६
सध्रैः ५.४४.१०
सुध्र्यक् १.५१.७; १०८.३; १३२.२;

२३.५; ५.२७.४; ६.६१.६; ७०.६; ९.३२.६

सनिषत् १०.७५.९

सनिंषन्त ९.७९.१

सनिषन्त ५.१२.४; १०.१४२.२

सनिषामहे ३.११.९

सनिंष्ठया ८.९२.१५

सनिष्णत १.१३१.५[२]

सनिष्यति ५.३१.११

सनिष्यन् ३.२.३; ७.१००.१; ९.९०.१; १०.९९.३

सनिष्यन्तः ३.२.४; १३.२

सनिष्यन्तीनाम् १०.९७.८

सनिष्यवः १.५६.२; १३१.२; ४.५५.६; ७.९४.६

सनिष्यसि ४.२०.३

सनिष्युः ८.६.४४

सनिष्युऽभिः ८.२७.८

सनिंस्यदत् ९.११०.४

सनिस्वनत् ८.६९.९

सऽनीळाः १.३४.९; ६२.१०; ६९.३; ७१.१; १६५.१; ७.५६.१; १०.३१.६; १०१.१; १२३.३

सऽनीळाभिः ९.७२.२

सनीळे इति सऽनीळे १.६२.७

सऽनीळेभिः १.१००.५; १०.९९.२

सनीनाम् ८.५.३७

सनुतः १.९२.११; २.२९.२; ५.४५.५; ६.४७.१३; ५१.२; ८.९७.३; ९.९८.११; १०.७७.६; १००.९; १०२.३; १३१.७

सनुऽतरः ४.३८.४

सनुतरिति ५.२.४; ८७.८

सनुत्यः २.३०.९; ६.५.४

सनुत्येन ६.६२.१०

सनुत्री १.१२३.२

सनुत्रीः १०.७.४

सनुयाम् १०.११९.१

सनुयाम १०.१०६.११

सनुयाम १.१००.१९; १०१.११; १०२.११; ७.२५.५; १०.१४८.१

सनुहि ८.८१.८

सनेत् १.५.९

सनैन २.२९.३

सनैम २.११.१९; ७.५२.१

सनेम १.१७.६; ७३.५; ५.६२.७; ६.२०.१०; ८.६१.४; ९.९८.१२; १०.३६.९

सनेम १.१२२.८; १२४.१३; १८९.८; ६.१७.१५

सनैमि १.६२.९; १७९.३; ४.१०.७; ७.३८.७; ५६.९; ९.१०४.६; १०५.६

सऽनैमि १.१६४.१४

सनेयम् १०.९७.४

सनेयम् ८.१९.२९

सनेरू इति १०.१०६.८

सनोति ३.२५.२; ४.१७.९; १०.८०.४

सनोति ३.२५.२; ६.६०.१

सनोतु ६.५४.५

सन्तः १.११०.४; १३८.३; ३.३२.१६; ४.५.५; १६.१९; ५.१२.५; ६.६६.४; १०.३४.९; ६७.१०

सन्तम् १.७२.२; ८४.१७; ११०.३; १२९.१; ७; १४१.३; १४८.५; २.१३.१२; ३.५.१०; ४.१.१५; ७.६; ५.८.३; ४०.७; ६.१७.५; ८.११.४; ४५.१७; ७१.१३; ८०.४; ८६.४; ९२.८; ९.९.५; १०.२७.४; ५५.५; ९३.११; ११४.५; १२४.२; ६; १७१.४

सन्ता १.२१.४; ४.३६.३; ९.६८.५

सन्ति १.८.९; ११.८; ३७.१४; ८५.१२; ९१.९; १६४.५०; १८६.१०; २.२३.९; २८.१; ३.६.८; १६.२; ४.२३.८; ३८.१; ४७.४; ५.३३.४; ३५.२; ४२.८; ५२.२; १३; ६.१.१३; १०.५; २९.४; ६०.८; ६६.३; ६७.५; ७.३.८; ३९.४; ४८.३; ५३.३; ५८.२; ६०.५; ८.१.९; ८.२३; १०.४; १८.२; २०.२०; २१.६[२]; ३१.१३; ४६.७; ५४.७; ९.६१.१०; ७८.२;

सुप्रथःऽतमम् १.१८.९; ४५.७; ७५.१; १०.१४०.६
सुप्रथःऽतमे १.९४.१३; ५.६५.५
सुऽप्रथाः १.१५६.१; ३.५९.७; ५.१३.४; ७.७७.२; ८.६०.५
सप्सरासः १.१६८.९
सबःऽदुघः ९.१२.७
सबःऽदुघा १.१३४.४
सबःऽदुघाः ३.५५.१६
सबःऽदुघाम् १.२०.३; ६.४८.११; ८.१.१०
सबःऽदुघायाः १.१२१.५; १०.६१.११
सबःऽधुक् १०.६९.८
सबःऽधुम् १०.६१.१७
सऽबन्धवः ५.५९.५; ८.२०.२१; ९.१४.२
सबन्धू इति सऽबन्धू ३.१.१०; ५.४७.५; १०.१०.९
सबर्दुघे इति सबःऽदुघे ३.६.४; ५५.१२
सऽबलः ८.९३.९
सुऽबाधः १.६४.८; ३.२७.६; ५१.४; ४.१७.१८; २३.४; ७.८.१; २६.२; ५३.१; ६१.६; ९४.५; ८.६६.१; ७४.६; १२; १०.१०१.१२
सुऽबाधसः ५.१०.६
सुऽभरसः ५.५४.१०
सऽभराः १०.१०१.३
सभाम् ८.४.९; १०.३४.६
सभाऽवती १.१६७.३
सभाऽवान् ४.२.५
सभाऽसहेन १०.७१.१०
सभासु ६.२८.६
सऽभृतयः ६.६७.७
सभेयः २.२४.१३
सभेयम् १.९१.२०
सम् १.६.३; ७; ९; ८.३; ९.५; ७; १०.८; १२.६; २०.५; २२.२१; २३.२३^{२}; २४^{३}; २५.१७; २९.५; ३०.३; ४; ६; ३१.१०^{२}; १८; ३२.६; ३३.३; १३; ३६.४; ७; ९; १४; २०; ३७.१३; ४२.१; ४४.७; ४८.१६^{४}; ५३.४; ५^{४}; ७; ५४.१; ५७.३; ६१.४; ५; ६२.३; ६४.१; ८; ६८.४; ७३.७; ८०.१५; १६; ८१.७; ८२.६; ८३.४; ८७.६; ९१.१६; १८^{३}; ९३.९; ९४.१; १०२.१०; १०३.१; १०५.८; १०८.१३; ११०.१; ४; ८; १११.३; ५; ११५.४; ५; ११६.१७; ११७.४; ११; १९; ११९.२; ३; ७; १२१.१५; १२३.७; १२५.७; १३०.४^{२}; १३२.५; १३३.१; ५; १३६.२; १४०.७; ८; १४४.३^{२}; १४५.३; १६०.४; ५; १६२.१८; १६३.१०; १६४.३; ८; ३९; १६५.१; ३; १६७.३; १६८.३; १७०.४; ५; १७३.६; १७९.२; १८१.४; १८८.२; ११; १९०.२; ७; २.१.१५; ३.२; ७^{२}; ११.८; १३.९; १३; १४.१२; १५.४; ६; १६.८; १७.४; ३१.७; ३५.३; ११; १२; ३८.४; ३९.७^{२}; ३.१.११; १३; १५; २.१; १०; ३.७; ५.२; ७.१; १०; ८.१०; १०.१; ९; ११.२; १६.६; १७.१; १९.२; २१.३; २४.२; २५.५; २६.३; २७.११; १३–१५; २९.१३; १५; ३०.८; १२; १६; १८; २१; ३१.१; १२; १५; ३२.१५; ३३.१२; ३४.६; ३५.८; ३६.८; ३८.३^{२}; ५०.३; ५१.४; ५४.५; ८; २१; २२^{२}; ५५.२०; ६०.२; ३; ६२.९; ४.३.११; १५; ४.८; ८.७; १७.११^{३}; १८.२; ९; १९.९; २०.४; २३.२; २४.४; २५.७; २९.२; ३०.९; ३१.६^{२}; ३४.१; २^{२}; ११^{३}; ३५.७; ९; ३७.८; ३८.१०; ४२.३; ४४.५; ५०.९; ५३.७; ५६.३; ५८.१; ५.१.४; २.१२; ४.२^{२}; ७; ६.२^{३}; ७.१; ३^{२}; ८.१; ७; ९.२^{२}; ११.२; १३.१; १६.३; १९.५; २१.१; २६.३; २८.३; ४; ३०.१०^{२}; ३१.८; ११; ३२.१०; ३४.७; ८; ३६.६; ३७.१; ५; ४२.४^{५}; १८; ४३.१७; ४४.६; ११; ४५.८; ५१.१५; ५४.२; १२; ५८.५; ५९.८; ६०.५; ६५.६; ७३.४; ७६.५; ७७.५; ७८.६; ८१.४; ८५.४; ६.५.२;

७.२; ४; १५.९; १२^{२}; १९; १६.१५; १७.१०; १९.३; ५; ९; २०.६^{२}; २३.९; २५.९; २६.१; ३४.१; ४; ३८.३; ४०.२^{२}; ४१.२; ३; ४६.२; ८; ४७.१४; ३१; ४८.१५^{२}; ५४.१; २; ७; ५५.१; ६३.१०; ६७.१; ३; ६९.१^{२}; ३^{२}; ७०.६; ७२.५; ७३.३; ७५.११; ७.१.१६; २.१; ३; ५; ३.३; ४.२^{२}; ९^{२}; ८.१; १६.३; २०.४; २८.३; ३१.९; १२; ३३.९; ३७.२; ४०.१; ४१.६; ४२.३; ४८.४; ५५.६; ५६.२२; ६०.३; ६१.६; ७३.४; ७६.५; ७९.२; ८१.२; ८२.२^{२}; ८३.३; ८६.२; ९३.५; १०३.२; १०४.२; ४; १८; १९; ८.१.२८; ३.७; ४.१६; ६.४; ७.२२^{४}; ९.१८; १२.१६–१८; २२–२४; १३.२; २९; १८.१४; २१.१४; २३.१६; २५.६; ३१.९; ३२.९; ३६.१–६; ४०.३; ४२.३; ४३.५; ४७.१७; ४८.५; ६; ५१.२; ५२.१०^{५}; ५३.८; ६०.१५; ६२.११; ६६.५; ७०.४; १२^{२}; ७२.१४; ७५.१२; ७७.३; ७९.८; ८१.१; ९२.१५; ९५.१; ९७.११^{२}; १२; ९.२.६; ५.१०; ६.६; ७.९; ८.५; १४.४; ७; १८.५; २५.३; ३१.४; ३४.४; ६; ४५.५; ६१.७; ८^{२}; ६३.२१; ६४.३^{२}; २३; ६६.८; ९; ६७.९; ६८.४; ५; ७१.५; ८^{२}; ७२.१; ३; ५; ६; ७३.१^{२}; ४; ७४.२; ७९.३; ८२.३; ८३.१; ८५.५; ८६.१५; १६; ३१; ४३; ९०.४; ९३.२^{२}; ९५.३; ९६.२; १२; १४^{२}; ९७.१; ३; ३५; ४५^{२}; ५५; ५७; १०१.८; ११; १०४.२; १०५.२; १०६.३; ११; ११०.८; १११.२; ३; ११३.५^{२}; १०.५.२; ३; ६.६; ९.९^{२}; १०.११; १२; १३.३; १४.८^{३}; १६.५; ७; १२; १४; १७.१; १३; १८.७; ८; १९.७; २५.४; २७.५; ८; ९; १५; ३०.६^{२}; ३१.२; ३३.२; ४२.९; ४४.४; ४६.१०; ४८.१; ४९.६; ५३.८; १०; ५४.६; ५५.२; ५; ५६.१; ४; ५९.१०; ६१.१७; ६८.२; ६९.६; ७१.३; ७२.२; ७९.१; २; ७; ८०.३; ८१.३^{२}; ८२.२; ४; ८४.४; ८५.२२; २३^{३}; २७^{२}; ४३; ४७^{५}; ८७.३; २४; ८८.१५; ९०.१४; ९१.१; १२; ९२.४; १०; ९५.७; ९; ९७.१९; २१; २२; ९८.११; १०१.१; ५; १०३.६; १०७.१०; १११.२^{२}; ११५.२; ११८.४; ५; ९; १२०.२; ३; ५; १२१.१; ७; १२५.८; १२९.४; १३०.४; १३२.३; १३४.७; १३५.४; १४०.३; १४३.६; १५०.१; ४; १५१.१; १५८.४; १५९.६; १६८.२; १६९.४; १७२.४; १८७.४; १९१.१; २^{३}

सुमः ५.६१.८; ६.४८.१९; ७.६२.१

सम्ऽअकृण्वन् १०.८२.४

सम्ऽअक्तम् २.३.१०

सम्ऽअक्ताः १०.६२.१

सम्ऽअक्षम् १०.८७.११

सम्ऽअक्षरन् १०.४३.७

सम्ऽअगच्छन्त १०.८२.६

सम्ऽअग्मत १०.९७.६

सम्ऽअङ्क्ते १०.८७.१६

सम्ऽअजग्रभीत् ८.६.१७

सम्ऽअजाति १.१००.११

सम्ऽअजासि ७.३२.७

सम्ऽअज्यसे ९.८६.४७

सम्ऽअञ्जन् १०.४५.४; ८०.१; ११०.२; १०

सम्ऽअञ्जन्ति १०.५२.३

समत्ऽवा ६.१८.२; ७.२०.३

समत्ऽसु १.५.४; ६६.३; ७०.६; १३०.८; १७३.७; २.१२.३; ३.३०.२२; ३२.१७; ३४.११; ३५.११; ३६.११; ३८.१०; ३९.९; ४३.८; ४८.५; ४९.५; ५०.५; ४.२०.१; २४.६; ३८.४; ५.३३.४; ६.१८.६; २५.९; ३३.१; ४६.३; ७५.१३; ७.३०.३; ३४.६; ८.११.८; ९; १६.१०; १९.२०; २३.१२; ४०.१; ४३.२१; ९०.१; ९.४.८; ९०.३; १११.३; १०.८०.२; ८९.१८; १०४.११; १३३.१

४.३०.२२; ६.५९.२; ७.२६.३; ७२.२; ८.७३.१२; १०.१९१.३

समऽआनजे १.१८८.९

समानतः ४.५१.८

समानऽदक्षाः ७.२६.२

समानबन्धू इति समानऽबन्धू १.११३.२

समानम् १.२५.६; ९२.१०; १२७.८; १३०.५; १३१.२; १४४.३; १४६.३; १६४.२०; ५१; २.१२.८; ३५.३; ३.२.१२; ३३.३; ६१.३; ४.५.७; ६.६६.१; ७.३३.१३; ५७.३; ६३.२; ३; ८६.३; १०३.६; ८.२०.११; ४५.२८; ७३.१२; ९९.८; १०.५.२; १७.११; २७.१६; ४१.१; ८९.३; ९१.६; ८; १२३.२; ३; १९१.३[2]; ४

समानऽयोजनः १.३०.१८

समानऽवर्चसा १.६.७

समानस्मात् ५.८७.४

समाना १०.१९१.४

समानाः ३.५८.६

समानात् २.१७.७

समानान् ६.४.१

समानानाम् १०.१६६.१

समानाम् १०.८५.५

समानी १०.१९१.३; ४

समानीः ४.५१.९

समाने १.३४.३; १४४.४; १८६.४; ६.५९.५; ७.६७.८; ७६.५; ८.२.८; ९.८९.५; १०.१०.७; ३१.६

समानेन १.९२.३; ३.५४.६; १०.१९१.३

समानेभिः १.१६५.७

समानैः १.६९.४

समान्या १.१३२.४; १६५.१; ३.५४.७; ५.४८.२; ८.८३.८

समाम् ४.५७.७

समऽआयन् १०.३१.५

समऽआयमुः १०.९४.६

समऽआरत १.१४५.४

समाराणे इति समऽआराणे ३.३३.२

समऽआवर्तम् १.११२.१८

समऽआववर्ति २.३८.६

समऽआशिराम् १.३०.२

समऽआसते ३.९.७; ७.१.४

समऽइङ्गयति ५.७८.७

समऽइत् ५.६.४; १०.५२.२; ८०.२

समऽइताः ७.८३.७

समऽइतिः १.९५.८; १०.११.८; १९१.३

समऽइतिम् १०.१६६.४

समऽइतीः ९.९२.६

समितौऽइव १०.९७.६

समित्ऽभिः ३.१.२; ६.१६.११; ८.४३.१२

समित्ऽसमित् ३.४.१

समऽइथा ९.९४.४

समऽइथानि १.५५.५

समऽइथे २.२४.१३; ३.१.१२; ५४.४; ४.३८.९; ५८.११; ६.२५.६; ७.१००.६; ९.७६.५; १०.२५.९

समऽइथेषु १.७३.५; ४.२०.८; ४१.२; ७.८३.९; १०.४८.९; ६४.६

समिद्धऽअग्निः ५.३७.२; १०.६३.७

समऽइद्धः १.९४.१४; १४२.१; १८८.१; २.३.१; १०.१; ३.५.१; ४; १८.५; ५.३.१; २१.४; २८.१; ५; ५८.३; ६.१६.३४; ७.१२.१; १७.१; ७८.२; ९३.७; ८.५८.२; १०३.९; ९.५.१; १०.३.१; ७०.७; ८७.१; २; ८८.७; ११०.१; १५०.१

समऽइद्धम् ३.९.७; ६.१५.७; ७.२.३; ४४.१

समऽइद्धस्य ३.८.२; ५.१.२; २८.४

समऽइद्धाः १०.३५.१३

समऽइद्धे २.९.३; ३.५५.३; ४.२५.१; ३९.३; ६.४०.३

समऽइद्धेषु १.१०८.४

समऽइधः १.१६४.२५; ३.२.९; ४.५८.८; १०.५१.२; ९०.१५

समऽइधम् १.९४.३; २.६.१; ३७.६; ५.४.४; ७.२.१; १०.६९.१०; ७०.१

समृऽइधा १.९५.११; ९६.९. ३.५.९; १०; १०.३; ४.४.१५; ५.१.१; ६.१.९; १०; २.५; ५.५; १५.६; ७; १९; ७.१४.१; २; ७२.४; ८.१९.५; १४; ४४.१; १०.१२.२; ८७.८; ९१.११; १२२.३

समृऽइधान् ४.४.४; ६.११; ८.६०.५; १०.१५०.२

समृऽइधानः १.१४३.७; २.२.६; ३.४.११; ५.८.४; १४.१; २६.६; ६.४८.७; ७.२.११; ९.६; ६७.२; ८.२५.१९; ४४.९; १०.२.७

समृऽइधानम् २.२.१; ५.८.६; ७.९.४; १०.३५.३–१२

समृऽइधानस्य १.१४३.२; ४.५.१५; ८.४४.४; १०.३६.१२

समृऽइधाने १.१२४.१; २.१६.१; ३.३०.२; ४.६.४; ६.५२.१७

समृऽइधे १.११३.९; ७.७७.१

समृऽइध्यते ४.१५.४

समृऽइध्यमानः ३.१७.१; २७.४; ५.२८.२

समृऽइध्यसे ८.४३.१४

समृऽइनक्षन्तः ९.७३.९

समृऽइषः ८.५०.२

समृऽईके ३.३०.११; ४.२४.३; ७.२१.९; ८.३.५; १०.४२.४

समीची इति समृऽईची १.६९.१; ९६.५; २.३.६; २७.१५; ३.१.७; ३०.११; ५५.१२; २०; ८.६.१७; १०.२४.४; ८८.१६

समृऽईचीः ३.२९.१३; ३१.१३; ४.१७.९; १०.६१.२५

समृऽईचीनाः ९.३९.६; ७४.४

समृऽईचीनासः ८.३.७; १२.३२; ९.१०.७

समीचीने इति समृऽईचीने ९.७४.२; ९०.४; १०२.७; १०.४४.८

समृऽईच्योः १०.२४.५

समृऽईजमानः ६.२९.५

समृऽईधे ३.५.१०; १०.६९.३; ४; ९८.८

समृऽईयतुः १०.११३.७

समृऽउक्षितम् ३.६०.५; ८.४.१२

समृऽउक्षितानाम् ५.५६.५

समुद्रऽअर्थाः ७.४९.२

समुद्रः १.३०.३; ११०.१; ५.४७.३; ७८.८; ६.५०.१४; ६९.६; ७.३५.१३; ८.४१.८; ९.२.५; ६४.८; ८६.२९; ९७.४०; १०१.६; १०९.४; १०.५.१; ६६.११; १४९.२; १९०.१

समुद्रःऽइव १.८.७; ८.३.४; १२.५

समुद्रऽज्येष्ठाः ७.४९.१

समुद्रतः ५.५५.५

समुद्रम् १.१९.७; ८; ३२.२; ५२.४; ५६.२; ७१.७; ११७.१५; १३०.५; १७४.९; १९०.७; २.१९.३; ३.३३.२; ३६.६; ४६.४; ४.५५.६; ५.४४.९; ८५.६; ६.१७.१२; २०.१२; ३०.४; ३६.३; ७.८८.३; ८.३.१०; ६.१३; २९; १२.२; ९.२९.३; ६१.१५; ६३.२३; ६४.१६; १७; २७; ६६.१२; ७३.३; ८४.४; ८६.८; ८८.६; ९६.१९; १०७.९; १५; २३; १०.३०.३; ५८.५; ९८.५; ११४.४; १२१.४; १२३.८; १४९.१

समुद्रम्ऽइव ८.६.३५; ९२.२२; ९.१०८.१६

समुद्रम्ऽईङ्खय ९.३५.२

समुद्रऽवाससम् ८.१०२.४–६

समुद्रऽव्यचसम् १.११.१

समुद्रस्य १.११६.४; १६७.२; ८.३४.१३; ९७.५; ९.१२.६; १०७.१४; १०.८९.११; १४२.७; ८

समुद्रस्यऽइव ७.३३.८

समुद्रा ५.७३.८

समुद्राः १.१६४.४२

समुद्राणि ६.७२.३

समुद्रात् १.४७.६; ११७.१४; ११८.६; १६३.१; ४.२१.३; ४३.५; ५८.१; ५; ६.६२.६; ७.६.७; ५५.७; ९५.२; ९.९७.४४; १०.९८.१२; १२३.२; १९०.२

समुद्रान् ७.७०.२; ९.३३.६

सहस्रऽपोषम् २.३२.५
सहस्रऽपोषिणम् ८.१०३.४
सहस्रऽपोष्यम् ६.३५.१
सहस्रऽप्रधनेषु १.७.४
सहस्रऽबाह्वे ८.४५.२६
सहस्रऽभरम् ६.२०.१
सहस्रऽभर्णसम् ९.६०.२; ६४.२५; २६; ९८.१
सहस्रऽभृष्टिः १.८०.१२; ९.८३.५; ८६.४०
सहस्रऽभृष्टिम् १.८५.९; ५.३४.२; ६.१७.१०
सहस्रम् १.११.८; २४.९; ३०.२; ८०.९; ११६.२; १२६.१; ३; १६७.१²; १८९.८; २.१४.६; ७; ४.१८.४; २६.७; ३१.१०; ३२.१७; ३८.८; ४६.३; ६.१८.११; ३४.३; ६९.८; ७.२५.३; ४६.३; ६२.३; ९१.६; ९२.१; ९९.५; ८.१.२४; ३.४; ६.४६; १२.८; २१.१८; ३४.१६; ५७.३; ७०.५; ७८.१; ९.५२.५; ७८.२; ९१.३; ९७.२९; १०६.६; १०.१५.१०; १८.१२; ६२.७; ८; ७३.३; ७९.५; ९७.२; ९८.४; १०२.२; ५; ९; ११४.८
सहस्रऽमघम् ७.८८.१
सहस्रऽमीळ्हे १.११२.१०
सहस्रम्ऽऊतिः १.५२.२
सहस्रऽमुष्क ६.४६.३
सहस्रऽमुष्कम् ८.१९.३२
सहस्रम्ऽभरः २.९.१
सहस्रऽयामा ९.१०६.५
सहस्रऽरेताः ४.५.३; ९.९६.८; १०९.१७
सहस्रऽवत् ३.१३.७; ८.२४.२९; १०.९४.२
सहस्रऽवर्चसम् ९.१२.९; ४३.४
सहस्रऽवल्शम् ७.३३.९; ९.५.१०
सहस्रऽवल्शाः ३.८.११
सहस्रऽवाजम् १०.१०४.७
सहस्रऽवाजया ८.९२.१०
सहस्रऽवीरम् १.१८८.४
सहस्रऽशाः ८.३४.१५
सहस्रऽशीर्षा १०.९०.१
सहस्रऽशृङ्गः ५.१.८; ७.५५.७
सहस्रऽशोकाः १०.६९.४
सहस्रऽसाः १.१८८.३; ४.३८.१०; ९.४७.३; ८२.५; ८७.४; ९६.१४; १०.६४.६; १७८.३
सहस्रऽसातमः १.१७५.१; ३.१३.६
सहस्रऽसातमम् १.९.८; ६.४५.३३
सहस्रऽसातमाम् १.१०.१०
सहस्रऽसाम् १.१०.११; ११७.९; ११८.९; ५.३४.९; ८.१०३.३; ९.५४.१
सहस्रऽसावे ३.५३.७; ७.१०३.१०
सहस्रऽस्तरीः १०.६९.७
सहस्रऽस्थूणम् ५.६२.६
सहस्रऽस्थूणे २.४१.५
सहस्रस्य १.१२६.४
सहस्रा १.५३.९; ६२.१०; ११६.२१; १३३.७; ४.१६.१२; १३; २८.३; ३०.२१; ३२.१८; ५.३०.१२; १४; ३३.९; ३७.३; ६.१८.१३; २६.५; ६; ४८.१५; ६३.१०; ७.१८.१४; ८.२.४१; ४.२०; ५.३७; ६.४७; ३२.१८; ३३.५; ३४.१४; ४५.१२; ४६.२२²; २९; ५६.२; ९.८७.५; ९७.२५; ५३; १०.२३.५; २८.६; ४८.४; ७३.४; ८०.४; ५; ९८.१०; ११
सहस्राणि १.५३.६; २.१.८; ३.९.९; ४.२९.४; ३०.१५; ७.३२.५; ८.५१.२; ६१.८; ९.५८.३; ४; १०.५२.६; ९८.९
सहस्रात् १.१०२.७; ५.२.७
सहस्राय १.११६.९; ८.१.५
सहस्रिणः १.३१.१०; १६७.१; २.२.७; ४१.१; ४.४८.५; ७.२६.५; ८.१.९; ७५.४; ९.३३.६
सहस्रिणम् १.५.९; ६४.१५; १२४.१३; ३.१४.६; २२.१; ४.४९.४; ५.५४.१३; ६.८.६; ८.५.१५; ३३.३; ४३.१५; ६४.५; ८८.२; ९३.२१; ९.१३.५; २०.२; ३६.१; ४०.३; ५७.१; ६२.१२; ६३.१; १२; ६५.२१; ६७.६; ९८.४; १०.२४.१; ४७.५
सहस्रिणी ६.४५.३२; ७.१५.९

सामऽभिः १.१०७.२; ८.१६.९; १०.३६.५; ७८.५
सामऽभृतम् ७.३३.१४
सामऽविप्रम् ५.५४.१४
सामानि ५.४४.१४; १५; १०.९०.९; १३०.२
साम्ऽतपनाः ७.५९.९
साम्नः २.२३.१६
साम्नःऽसाम्नः २.२३.१७
साम्ना ८.९५.७
साम्ने ८.४.१७; ६.४७
साम्ऽराज्यस्य ८.२५.१७
साम्ऽराज्याय १.२५.१०; १४१.१३; ८.२५.८
साम्ऽराज्येन ७.४६.२
साम्ऽवरणौ ८.५१.१
सायक १०.८३.१; ८४.६
सायकम् १.३२.३; ८४.११
सायकस्य ३.५३.२३
सायकानि २.३३.१०
सायकेन १०.४८.४
सायम् ५.७७.२; ८.२.२०; १०.१४६.३; ४
सारघाऽइव १०.१०६.१०
सारघेण ८.४.८
सारथयः १.५५.७
सारथये २.१९.६; ६.२०.५
सारथिः १.१४४.३; १५८.६; ६.५७.६; १०.१०२.६
सारम् ३.५३.१९
सारमेय ७.५५.२; ३
सारमेयौ १०.१४.१०
सारस्वतेभिः ३.४.८; ७.२.८
सार्ञ्जयः ६.४७.२५
सालावृकाणाम् १०.९५.१५
सालावृकान् १०.७३.३
सावः १०.४९.७
सावर्णेः १०.६२.११
सावर्ण्यस्य १०.६२.९
साविषत् १.१६४.२६; ७.४५.३; १०.९९.७; १००.३; ८

सावीः २.२८.९; ५.८२.४; ६.७१.६
साशनानशने इति १०.९०.४
साहऽदेव्यः ४.१५.७; ९
साहऽदेव्यम् ४.१५.१०
साहऽदेव्यात् ४.१५.८
साहि ४.११.२
सिंहः १.१७४.३; ३.२.११; ४.१६.१४; ९.९७.२८; १०.२८.१०
सिंहम् १.९५.५; ५.१५.३; ९.८९.३; १०.२८.४
सिंहम्ऽइव ३.९.४; ५.७४.४; १०.६७.९
सिंहस्य ५.८३.३
सिंहाः ३.२६.५
सिंहाःऽइव १.६४.८
सिंह्यम् ७.१८.१७
सिक्तः ९.९७.१५
सिक्तम् १.१३०.२
सिक्तये १०.१००.११
सिक्ता ६.७०.३
सिचः ९.८१.३
सिचम् ३.५३.२
सिचा १०.१८.११
सिचामहे २.१६.७
सिचौ १.९५.७; १०.७५.४
सिच्यते ९.६९.२
सिच्यते ४.४९.२; ५.५१.४; ८.९.४; ९.१७.४; २७.२; ३९.५; ४२.४; ६२.१३; ८६.३३; १०.१६७.१
सिच्यसे ९.११.८; ७८.२; ९८.१०
सिञ्च ८.२४.१६; ३२.२४
सिञ्च ५.८३.८; ८.२.२२; १०.१०१.१०
सिञ्चत् ४.४३.६; १०.६१.२; ७
सिञ्चत २.१४.१; ८.२४.१३; ७२.१३; ९.६३.१०; ११; १०७.१; १०८.७; १०.३२.५; १०१.७
सिञ्चतः १०.६४.१४
सिञ्चतम् ४.५७.५; ६.७०.२
सिञ्चतीःऽइव १०.२१.३
सिञ्चतु १०.१७.१३; १८४.१

सीद १.७६.२; १०४.१; २.२३.१; ३.२९.१०; ४१.३; ५३.३; ४.३.२; ६.१५.१६; २३.७; ९.५९.३; ८७.१; ९६.१३; १०.९८.४; ११२.९

सीदः ६.५.३

सीदत् ५.११.२; ६.१६.२३; ८.७२.२; १०.१२.१; ६१.४; ९९.८; १२३.५

सीदत् ७.३०.३; १०.४६.१; ६; ६१.९

सीदत १.८५.६

सीदत १.५.१; २२.८; २.३.४; ४१.१३; ६.५२.७; ९.११.६; १३.९; ३९.६; १०४.१; १०.७०.८

सीदतम् १.४७.८; ३.६२.१८; ८.८७.२; ४; १०.१३.२

सीदताम् १.१४२.७

सीदताम् १.१८८.६

सीदति ९.६४.२०

सीदति ४.९.३; ४; ९.७.५; ६; २०.६; ३८.४; ४०.२; ५७.३; ६८.९; ७०.७; ८४.४; ८६.६; ९; ११; ९९.६

सीदतु १०.३६.५

सीदतु ६.१६.४१

सीदन् १.६५.५; ६.१६.३५; ७.३४.१६; ९.३२.४; ६१.२१; ६२.८; ६४.११; ६५.१९; ८६.२२; ९२.२; ६; ९५.१; ९६.२३; १०७.१८

सीदन् १.६५.१; ७२.५; ८५.७

सीदन्तः ८.२१.५; ९.६४.२९

सीदन्तु १.२६.४; ६.२८.१; १०.७०.११

सीदन्तु १.१३.९; ४४.१३; १४२.९; २.४१.२१; ५.५.८; २६.९; १०.७०.६

सीदसि १.१४.११; ८.६१.२; ९.६३.२; ८६.३५; ४७; ९९.८; १०७.४

सीदस्व १.३६.९

सीदाति ९.९७.४

सीम् १.३३.९; ३६.१; ३७.६; ९; ६१.११; ९५.२; १००.१४; ११६.२०; ११७.१६; १९; १२२.६; १४०.५; १४१.९; १६०.२; १७९.५; २.२८.४; ३६.१; ३.१.६; २.१०; ७.३; १४.३; २३.३; ३०.१४; ३८.३; ५४.६; ५६.४; ४.२.६; १३.३; २२.७; २८.४; ३०.१०; ११; ३८.३; ८; ४३.५; ५६.१; ५.३१.९; ४७.२; ८५.७; ६.१.१; २०.८; ४५.२३; ४८.४; ६४.३; ७.७८.२; ९३.७; ८.४०.८; ६९.६; ७०.७; ८०.८; १००.७; १०.२५.९

सीमहि १.२५.३

सीरा १०.१०१.३; ४

सीराः १.१७४.९; ४.१९.८; ६.२०.१२; १०.४९.९; ९७.९

सील्माऽवती १०.७५.८

सीव्यतु २.३२.४

सीव्यध्वम् १०.१०१.८

सीव्यन् २.१७.४

सीषपन्त ७.४३.४

सीसधः २.२४.१

सीसधः ६.५६.५

सीसधाति ६.४९.८

सीसधाम १०.१५७.१

सु १.९.६; १०.११; १७.७; २६.५; २७.४; ३३.१; ३६.१३; ३७.१४; ३८.६; ४५.५; ४७.२; ५; ५२.१; ५३.१; ७६.२; ३; ८२.१; ८४.३; ९३.१; ९४.१२; १०५.३; १११.२; ११२.१–२३; ११८.१०; १२९.५; १३३.४[२]; १३५.९; १३६.१; १३८.४[२]; १३९.१; ७; ८; १४८.३; १६४.२६; १६५.१४; १६९.५; १७३.१२; १७९.५; १८२.१; १८४.२; १९१.६; २.६.१; ११.१५; १४.५; १६.८; १८.३; २०.१; २८.६; ७; ३४.१५; ३५.२; ४१.७; ३.१८.२; २४.२; ३०.६; २१; ३१.१४; ३३.९[२]; ३६.१; २; ३७.२; ५३.२; ५४.३; ५५.२; ५७.२; ४.६.१; १२.१; ४; ६; २०.४; २२.१०[२]; २६.४; ३१.३; ३२.६; १४; ४३.६; ५५.४; १०; ५.३०.७; ३५.२; ४२.१३; ५४.१५; ६२.२; ६३.६[२]; ६५.३; ६७.५; ७३.४; ८; ७४.९; १०[२]; ८३.७; १०; ८५.५;

६.११.४; १२.२; १५.१; १६.१६; २१.७; २४.९; २५.१; २७.७; ३३.१; ४५.३३; ४६.६; ४८.३; ५६.४; ७४.४; ७.२०.१०; २१.१०; २२.३; २६.३; २९.२; ३२.१; ४२.३; ५५.२–४; ५९.५[2]; ८६.८; ८९.१; ९०.७; ९१.७; ९३.६; ७; ८.१.१४; १९; २.१९; २०; ४२; ४.३; ५.१३[2]; ६.३२; ३९; ४३; ७.१८; ३२; ३३; ८.२१; १३.२५; १७.४; १८.३; १२; १८; २२; २०.१९; २२.३; २४.१; ७; २६.१; १०; १५; २३; २७.३; ३२.१९; ३४.१२; ४०.१; ४१.१; २; ४५.८; ९; ४६.१०; १७; ५०.१; ५३.६; ५९.५; ६१.५; ६७.१५; १८; २१; ७०.९[2]; ७३.१७; ७५.११; ८०.३; ६; ८१.८; ८२.६; ९२.१४; ३०; ९३.२१; ९४.३; १००.३; १०३.१; ९.२९.५; ४९.१; ६१.१३; ६५.५; ८१.३; ८२.४; ११०.१; १०.१०.१४; १६.१४[2]; १८.१२; २७.१; २०; २८.४; ३२.१[2]; २; ३३.३; ४०.११; ४२.१; ४३.२; ४४.९; ५४.१; ५९.१; २[2]; ३[2]; ४[3]; ५; ८–१०; ६१.२७; ७५.१; ७७.४; ९४.१४; १००.२; १०१.११; ११२.९; ११३.१०; १२०.३; १२६.६; ८; १३२.५; १३३.१; ३; ७; १७८.१; १७९.२

सुऽअग्नयः १.२६.७; ८[2]; ७.१५.८; ८.१९.७; ६०.६

सुऽअङ्गः १०.१.१

सुऽअङ्गा ३.४३.४

सुऽअङ्गुरिः २.३२.७; ४.५४.४

सुऽअङ्गुरे १०.८६.८

सुऽअञ्चः ४.६.९; ७.५६.१६; ९.७३.७

सुऽअञ्चम् ६.१५.१०; ५८.४; ७.१०.३

सुऽअञ्चाः ५.३७.१

सुऽअध्वर १.४४.८; ५.२८.५; ८.२३.५

सुऽअध्वरः १.१२७.१; २.२.८; ८.१९.५; २४; १०३.१२; १३; ९.३.८; ८६.७; १०.११.५; ११५.२

सुऽअध्वरम् १.४५.१; ३.२.८; ९.८; ४.४६.४; ५.९.३; ६.१५.४; १६.४०; ७.१६.१; ८.५.३३; ४०.११

सुऽअध्वरा ३.६.६; २९.१२; ६.१०.१; ७.१७.३; ४

सुऽअध्वरासः ४.४५.५

सुऽअध्वरे १.१४२.५; ५.१७.१; ८.४४.१३; ५०.५

सुऽअनीक २.१.८; ४.६.६; ६.१५.१६; ७.१.२३; ३.६;

सुऽअपत्यम् १.११६.१९; २.४.८; ७.१.५; १२

सुऽअपत्यस्य २.२.१२; ९.५; ३.१६.१; १९.३; १०.३०.१२

सुऽअपत्यानि १.७२.९; ४.३४.९; ७.९१.३; ८.१५.१०

सुऽअपत्याय १.८३.६; ४.२.११

सुऽअपत्ये ३.३.७

सुऽअपत्यै १.५४.११

सुऽअपसः १.१५९.३; १६१.६; ४.२.१९; ३३.८; १०.७६.८; ११०.८

सुऽअपस्यते १०.११.६

सुऽअपस्यमानः १.६२.९

सुऽअपस्यया १.५२.३; ११०.८; १६१.११; ३.३.११; ४.३५.२; १०.११३.४

सुऽअपस्या ४.३५.९

सुऽअपाः १.८५.९; १३०.६; ४.५६.३; ५.२.११; २९.१५; ६०.५; ७.८८.४; ९.६६.२१

सुऽअपाक ४.३.२

सुऽअपिवात ७.४६.३

सुऽअप्रसः १०.६३.३; ७८.१

सुऽअभिष्टयः १.१७३.९

सुऽअभिष्टि ७.१०१.२

सुऽअभिष्टिः ६.३३.१

सुऽअभिष्टिम् १.५१.२; ८.१९.३२

सुऽअभीशुः ८.६८.१८

सुऽअभीशून् ८.६८.१६

सुऽअरंकृतेन १.१६२.५

सुऽअरिः १.६१.९

सुऽखम् १.२०.३; ४९.२; ३.३५.४; ५.६३.५; ८.५८.३; ९.११२.४; १०.७५.९
सुखऽरथम् ५.३०.१
सुऽखादयः १.८७.६
सुऽखादये ५.८७.१
सुऽखे ३.४१.९
सुऽखेषु ५.६०.२
सुऽखैः ५.५.३
सुऽगः १.४१.४; २.२७.६; ३.५४.२१; ७.४२.२
सुऽगन्धिना ८.१९.२४
सुगन्धिम् ७.५९.१२
सुऽगभस्तयः ९.७२.२
सुऽगभस्तिः ५.४३.४
सुऽगभस्तिम् ६.४९.९
सुऽगम् १.४३.६; ९४.९; ११; १०२.४; १०६.५; २.२३.७; ५.५४.६; ६.४४.१८; ५१.१३; १५; ७.१०४.७; ८.४७.११; ९३.१०; १०.८६.५
सुऽगवः १.११६.२५
सुऽगव्यम् १.१६२.२२; ८.१२.३३
सुऽगा १.४२.७; ६.६४.४; ७.६२.६; ६३.६; ९.६२.२; १०.६३.७
सुऽगाः १.१६५.८; ८.३१.१३
सुगातुऽया १.९७.२
सुऽगाधा ७.९७.८
सुऽगान् ३.३०.१०; ५.८०.२; १०.५१.५
सुऽगानि ६.६४.१; ९.९७.१६
सुऽगार्हपत्याः ५.४.२
सुऽगुः १.१२५.२
सुऽगोभिः १.३५.११; ११६.२०; १६२.२१; १६३.६; २.२७.७; ८.२७.१७; १०.८५.३२; ११३.१०
सुगेऽवृधः ८.१८.२
सुऽगेषु ६.२१.१२
सुऽगोपा १.१२०.७
सुऽगोपाः २.२३.५; ३.४५.३; ५.३८.५[२]; ४४.२; ६.५१.११; १०.१०८.७
सुऽगोपातमः १.८६.१
सुग्म्यः १.१७३.४
सुग्म्यम् १.४८.१३; ८.२२.१५
सुग्म्याय ८.२२.१५
सुऽग्रथितम् १.१२१.१०
सुऽघ्नाय ८.७०.११
सुऽचक्रम् १०.८५.२०
सुऽचक्रे ६.३७.३
सुऽचक्षसः १०.३७.७
सुऽचन्द्र ५.६.५
सुऽचन्द्र १.७४.६; ५.६.९
सुऽचन्द्रम् २.३४.१३; ४.२.१९
सुऽचेतसः ४.३६.२
सुऽचेतसम् ७.३.१०; ४.१०; ६०.६
सुऽचेतुनम् ९.६५.३०
सुऽचेतुना १.७९.९; १२७.११[२]; १५९.५; १६६.६; ५.५१.११; ६४.२; ६५.३
सुच्छर्दिःऽतमे ७.६६.१३
सुऽजनिमा ७.१००.४; १०.२.७; १८.६
सुऽजनिमानः ७.६२.४
सुजन्मनी इति सुऽजन्मनी १.१६०.१
सुऽजम्भः ८.६०.१३
सुऽजात ५.२१.२; ८.७४.७
सुऽजात २.१.१५; ६.२; ३.१५.२; ७.८.५; १०.७.२; ६; ५१.७
सुऽजातः ७.६४.१; १०.७९.७; ९५.१०; ९९.७
सुऽजातता १०.१७२.४
सुऽजातम् १.६५.२; ३.२३.३; १०.५.४
सुऽजातम् ७.५६.२१
सुऽजाता ५.५६.९
सुऽजाता १.११८.१०; ८.२५.२
सुऽजाताः १.७२.३
सुऽजाताः २.२.११; ७.१.४
सुऽजाताः १.८८.३; १६६.१२
सुऽजातान् ६.५१.३
सुऽजाताय ५.५३.१२
सुऽजातासः ५.६.२; ५७.५; ५९.६; ७.१.१५; ८.२०.८
सुऽजाते ५.७९.१-१०

सुऽजा॒ते १.१२३.३; ७.७६.६; ७७.६
सुऽजि॒ह्व १.१४.७; १४२.४; १०.११०.२
सुऽजि॒ह्वः ३.५४.११
सुऽजि॒ह्वम् ७.४५.४
सुऽजि॒ह्वाः १.१६६.११
सुऽजि॒ह्वौ १.१३.८
सुऽजु॑ष्टा ६.६१.१०
सुऽजू॒र्णिः ४.६.३; १०.९५.६
सुऽज्योतिषः ३.२०.१; ६.५०.२
सुऽज्यो॒तिषः १०.८९.१५
सुतः १.४७.१; ८०.२; ८६.४; १०४.९; १३७.२; ३[2]; १७७.३; २.११.११; १८.४; ३६.५; ४१.४; ३.३५.७; ४४.१; ४.४६.६; ५.४०.२; ५१.४; ६.२९.४; ४०.१; ४१.४; ४३.१–४; ४४.१–३; ७.२४.२; ८.२.२; १३.३२; १७.१२; २२.८; ६६.१५; ८२.५; ७; ९४.४; १००.२; ९.१.१; ३.९; १०; ६.७; ८; २४.५; २७.३; २८.२; ३४.२; ३६.१; ३७.१; ५; ३८.६; ३९.३; ५; ४०.२; ४१.४; ४२.२; ६; ४४.३; ५१.४; ५; ६१.८; २८; ६२.५; १६; १९; ६३.३; १३; ६६.७; ६७.२; १२; १५; ६८.९; ७१.३; ७२.५; ७५.४; ८०.४; ८४.३; ८६.२३; ३४; ३५; ९७.१; ३५; ४५; ९९.७; ८; १००.५; ६; १०१.२; १०३.६; १०५.३; ४; १०६.२; १०७.१७; १०८.५; १०; १०९.१८; ११३.२; १०.११२.५; ११६.७; १४४.६
सु॒तऽक्रे॒ ६.३१.४
सु॒तऽपाः १.१५५.२; ४.२५.७; ६.२४.१; ८.२.४; १०.१००.१
सु॒तऽपाः ६.२३.६
सु॒तऽपा॒व॒न् ६.२४.९
सु॒तऽपा॑व्नः ८.२.७
सु॒तऽपा॑व्ने १.५.५
सु॒तऽपे॑याय ४.४४.१
सु॒तऽपौ ६.६८.१०
सुतम् १.३.७; ८; १०.११; १६.४; ५; ७; ८; २१.४; ८४.४; १२५.३; २.२२.१; ३.१२.१; २; २२.१; ४०.२; ५; ६; ४२.१; २; ७; ४४.५; ४७.३; ५१.८–१०; ६०.५; ४.३५.७; ४६.१; ५.२९.७; ४०.१; ६४.७; ७१.३; ६.२३.३; ४२.४; ४४.१५; ५७.२; ६०.७; ९; ६८.१०; ८.२.१; २६; ४.४; ६.३६; ८.३; ३२.२१; ३३.२; ३५.७–९; ३८.४; ४५.२२; २६; ४६.७; ५१.१; ५२.१; ६५.५; ६६.७; ७६.९; १०; ९२.१९; ९३.३१[2]; ३२; ३३; ९५.३; ९.६.६; ११.५; ५१.१; ६३.१०; ६८.७; १०७.१; ११०.२; १०.२४.१; २७.२; १०५.१
सु॒त॒म् १.२८.८
सु॒त॒म्ऽभ॒रः ५.४४.१३
सुऽत॒र॒णान् ४.११.६
सुऽत॑रा ७.९७.८; १०.१२७.६
सुऽत॑राः ६.६०.११
सुऽत॑र्माणम् ८.४२.३
सुतऽव॑तः १.३.५; ३.२५.४; ५८.९; ८.१७.४; १०.१७१.१
सुतऽव॑ताम् १०.१००.११
सुतऽव॑न्तः ८.१७.३; २६.२२; ३३.१; ५१.६; ६१.१४; ६५.६; ९३.३०
सुतऽवा॑न् १.८४.९; ८.९७.४
सुऽत॑ष्टः ७.३४.१
सुऽत॑ष्टम् २.३५.२
सुतऽसो॑मः १.१६७.६; ३.३२.१२; ४.२५.१; ५.३७.२; ५; १०.२८.२
सुतऽसो॑मम् ५.३०.१; ३१.१२; ७.९८.१
सुतसो॑मवत्ऽभिः १०.६९.११
सुतऽसो॑मस्य २.१२.६
सुतऽसो॑माः १.२.२; ४५.८; ४७.४
सुतऽसो॑माय १.१४२.१; ४.२.१३
सुतऽसो॑मासः १.४४.८; ५.२९.१२; ८.२७.७
सुतऽसो॑मे ५.६१.१८; ८.६६.१
सुतऽसो॑मेषु १.५१.१२
सुतस्य॑ १.५.६; ३२.३; ५२.१०; ५६.६; १०८.१; ५–१३; १०९.५; २.११.१०;

सुऽदक्षा ३.५८.७
सुऽदक्षिणः ८.३३.५
सुऽदक्षिणम् ७.३२.३
सुऽदत्र ७.८.३
सुऽदत्रः १.१६४.४९; ७.३४.२२
सुदर्शऽतरः १.१२७.५
सुऽदर्शः ४.२३.६; ५.३.४
सुऽदाः ८.७८.४
सुदाःऽतराय १.१८४.१; १८५.९
सुऽदातु ८.७८.८
सुऽदानवः १०.६६.१२
सुऽदानवः १.४०.१; ४४.१४; ६४.६; ८५.१०; १४१.९; २.३४.८; ३.२६.५; ५.५२.५; ५३.६; ५७.५; ६७.४; ६.१६.८; ७.९६.४; ८.२०.१८; १०३.७; ९.७४.४; १०.६५.११; ७८.५; १७२.३
सुऽदानवः १.१५.२; २३.९; ३९.१०; ४५.१०; १०६.१–६; १७२.१–३; ६.५१.१५; ७.५९.१०; ६६.५; ८.७.१२; १९; २०; १८.१२; १९.३४; २०.२३; २५.११; ६७.१६; ८३.६; ८; ९
सुऽदानवे १.४७.८; ९२.३; ६.२.४; ७.३१.२; ८.२५.१२; १०.२३.६
सुऽदानुः ३.२९.७; ४.४.७; ५.४१.१८; ६.३८.१; ६६.५; ६८.५
सुऽदानुऽभिः १०.१७२.२
सुऽदानुम् ३.२६.१; ८.८८.२
सुदानू इति सुऽदानू १.११२.११; ११७.१०; २४; १८०.६; १८४.४; ३.५८.७; ४.४१.८; ५.६२.९; ६.६७.२; ७.६१.३
सुऽदानून् ५.४१.१६
सुऽदामन् ६.२०.७
सुऽदामन् ६.२४.४
सुऽदाम्ने १.७६.३
सुऽदासः ३.५३.११; ७.१८.२२; २३; २५; ३२.१०
सुऽदासम् ३.५३.९; ७.१९.३; ३३.३; ८३.१; ४; ६; ७
सुऽदासे १.४७.६; ६३.७; ११२.१९; ५.५३.२; ७.१८.५; ९; १५; १७; १९.६; २०.२; २५.३; ५३.३; ६०.८; ९; ६४.३; ८३.८
सुदिनऽत्वम् २.२१.६
सुदिनऽत्वे ३.८.५; २३.४; ७.८८.४; १०.७०.१
सुऽदिना ४.४.७; ५.६०.५; ७.११.२; १८.२१; ३०.३
सुदिनाऽइव १०.१०६.१
सुऽदिनाः १.१२४.९; ७.९०.४
सुऽदिनानि ४.४.६
सुऽदिने १.१८६.९
सुदिने इति सुऽदिने १०.३९.१२
सुःदिनेषु ४.३७.१
सुऽदिवः १०.३.५
सुऽदीतयः १.१५९.४; ५.४६.६; ८.९७.१२
सुऽदीतये ८.७१.१४
सुदीतिऽभिः ५.८.४; २५.२; ६४.५; ६.४८.३; ८.२०.२
सुऽदीतिम् ३.२.१३; १७.४; २७.१०
सुऽदीती ७.१.२१
सुऽदीदितिम् ३.९.१; ८.१९.४
सुऽदुघा २.३५.७; ५.६०.५; १०.४३.९; ६९.८
सुदुघाऽइव १.१८६.४; ७.२.६
सुऽदुघाः ४.१.१३; ५.३१.३; ८; ७.१८.१; ३६.६; ४३.४; ८.६९.१०; ९.७७.१; ९६.२४; ९७.५०
सुऽदुघाम् १.१६४.२६; ६.३५.४; ८.१.१०; १०.१२२.६
सुदुघामऽइव १.४.१; ८.५२.४
सुदुघे इति सुऽदुघे २.३.६
सुऽदृशः ४.२३.६; ५.३.४; ९.७३.७
सुऽदृशम् ३.१७.४; ६.१५.१०
सुऽदृशी १.१२२.२
सुदृशीऽइव ४.१६.१५
सुऽदृशीः ५.४४.२
सुऽदृशीकः ५.४.२; ९.८६.४५
सुऽदृशीकम् ४.१६.४; ७.७७.३

३५.१६–२१; ३६.१; ७; ३७.१; ३८.८; ६२.१२; ९८.५
सुन्वताम् ८.३२.१६
सुन्वति ८.९७.२
सुन्वते १.२०.७; ५१.१३; ८१.२; ८३.३; ९२.३; १३२.१; १४१.१०; २.१२.१५; १९.५; ४.३१.८; ५.२६.५; ६०.७; ६.१६.५; ३१.४. ८.१.२२; ४.४; १२.१२; १४.३; १७.१०; ५०.१; ५९.१; ६६.२; ६; ६७.६; १००.६; १०.२७.१; ४२.८; ४३.८; ७६.८; १००.३; १२५.२; १३४.४; १७५.४
सुन्वत्ऽसख्यः १.१३२.४
सुन्वन् १.१३३.७; ६.२०.१३
सुन्वन्तः ८.४.१३; १३.५; १०.४८.५
सुन्वन्तम् २.१२.१४; ३०.७; ८.२.१८; ९.११२.१
सुन्वन्ति ३.३०.१; ५.३०.६; ९.३४.३; १०.२८.३; ७६.७
सुन्वन्तु ८.५३.४
सुन्वान ८.३१.१६
सुन्वानः १.१३३.७[२]
सुन्वानस्य ८.८०.३; ९.१०१.१३
सुन्वानाय १.१३३.७
सुन्विरे ८.५३.३; ९३.६; ९.६५.२२
सुन्विरे ७.३२.४
सुन्वे ७.९७.१
सुन्वे ७.२९.१; ९.८८.१; १०८.१३
सुपत्नी इति सुऽपत्नी ६.३.७
सुऽपत्नीः ६.४४.२३; १०.१८.७
सुऽपथा १.२५.१२; ४२.७; १८९.१; ६.६४.१; ४; ७.६०.६; ८.९७.१३; ९.९७.१६; १०.४४.२; ६३.७
सुऽपथानि ७.६२.६; ६३.६; ९.८६.२६
सुऽपदी ३.३१.६
सुऽपप्तनि १.१८२.५
सुऽपर्णः १.३५.७; १०५.१; १६४.४६; २.४२.२; ४.२६.४; ५.४७.३; ८.१००.८; ९.४८.३; ७१.९; ८६.२४; ९७.३३; १०.२८.१०; ३०.२; ५५.६; ११४.४; १४४.४; १४९.३
सुऽपर्णम् १.१६४.५२; ६.७५.११; ९.८५.११; १०.११४.५; १२३.६
सुपर्णऽयातुम् ७.१०४.२२
सुऽपर्णा १.१६४.२०; ४.४३.३; १०.११४.३
सुऽपर्णाः १.७९.२; १०५.११; १६४.२१; २२; ४७; ९.८६.१; १०.७३.११; ९४.५
सुऽपर्ण्यः ९.८६.३७; १०.८८.१९
सुऽपलाशम् १०.४३.४
सुऽपलाशे १०.१३५.१
सुऽपाणिः ३.३३.६; ५४.१२; ७.३४.२०
सुऽपाणिम् ६.४९.९; ७.४५.४
सुपाणी इति सुऽपाणी १.७१.९; ३.५६.७
सुपाणी इति सुऽपाणी १.१०९.४
सुऽपारः १.४.१०; ६.४७.७; ८.१३.२; ३२.१३
सुपारऽक्षत्रः ७.८७.६
सुऽपारम् ३.५०.३
सुऽपारा १.१५२.७; ७.१८.५
सुऽपाराः ३.३३.९; ८.९६.१
सुऽपारासः ३.३९.८
सुऽपित्र्य १०.११५.६
सुऽपिप्पलाः ७.१०१.५
सुऽपिशः १.६४.८
सुऽपीवसः १०.९४.११
सुऽपुत्रा ३.४.११; ७.२.११; १०.८५.२५
सुऽपुत्राम् १०.८५.४५
सुऽपुत्रे १०.८६.१३
सुऽपूतम् ४.५७.२; ५.१२.१; ७.४.१; १०.३०.३
सुऽपूर्णम् ८.२.१
सुऽपूर्णस्य ६.४८.१८
सुऽपूर्णाः ८.२.८
सुऽपृक्षः ७.३७.७
सुऽपेशसः २.३२.५; ३५.१; ५.५७.४; ८.६८.१६; ९.५.८; ८१.१
सुऽपेशसम् १.४८.१३; ४९.२; ६३.९;

सुऽभगाः ५.४२.८
सुऽभगान् १.४.६
सुऽभगाम् ३.३३.३; ६.६४.३; १०.८५.४५; ८६.११; १४०.५
सुऽभगाय ७.३०.३
सुऽभगासः २.२८.२
सुऽभगासः ५.६०.६
सुऽभगे १०.१४५.२
सुऽभगे १.३६.६
सुऽभगे १.९२.८; ११३.७; २.३२.५; ४.५७.६; ७.७६.६; ९५.६; ८.२४.२८; १०.१०.१०; १२; १०८.५; ९
सुभगे इति सुऽभगे १.१८५.७; २.३१.५
सुभगे इति सुऽभगे १०.७०.६
सुऽभद्रम् ८.१.३४
सुऽभद्राम् १०.१०.१४
सुऽभरः २.३.९
सुऽभरम् २.३.४; १०.३५.१२
सुऽभराः १.११२.२; ९.८६.४१
सुऽभराम् १.११२.२०
सुभसत्ऽतरा १०.८६.६
सुऽभागाः १.१६७.७
सुऽभागान् १०.७८.८
सुऽभासम् ८.२३.२०
सुऽभु २.३५.७
सुऽभृतः २.१.१२; ८.१९.२७
सुऽभृतम् ४.५०.७; ९.९७.२४; १०.१७०.२
सुऽभृतस्य १०.१४७.४
सुऽभोजसम् ७.९२.३
सुऽभ्वः १.५२.१; ४; ४.१७.२; ५.४१.१३; ५५.३; ५९.३; ८७.३; ६.५२.१; ७.६७.८
सुऽभ्वम् ९.७९.५
सुऽभ्वे ६.६६.३
सुऽमख २.१८.४; ४.३.१४
सुऽमखम् १०.५०.१
सुऽमखस्य १.१८१.४
सुऽमखाः ५.८७.७
सुऽमखाय १.६४.१; १६५.११; ४.३.७; ५.४१.१४
सुऽमखासः १.८५.४
सुऽमङ्गलः २.४२.१–३; ९.८०.३
सुऽमङ्गलम् १०.१०२.११
सुऽमङ्गलीः १.११३.१२; १०.८५.३३
सुऽमत् १.१४२.७; १६२.७; ५.२.४; ८.८७.४; १०.३२.३
सुमत्ऽअंशुः १.१००.१६
सुऽमतयः २.३२.५; ७.१८.२०
सुऽमतये १.१५८.२; ६.२९.१
सुऽमतिः १.२४.९; ८९.२; १०७.१; ११४.९; १२९.१५; २.३४.१५; ३.१.२३; ५.११; ६.११; ७.११; १५.७; २२.५; २३.५; ३०.७; ४.४३.७; ४४.७; ५०.११; ५.६५.४; ७.५७.४; ५९.४; ७०.२; ५; ८.२२.४; ८६.४; १०३.९; ९.८८.७; १०.३१.६; ४०.१२; १४३.४
सुमतिऽभिः २.१६.८; ४.२३.२; ७.५७.५; ८.२२.२; ६; २६.९
सुऽमतिम् १.७३.६; ७; ११४.३; ४; ११७.२३; १५१.७; १५६.३; १६६.६; १७१.१; २.४३.३; ३.१.१५; ४.१; ३३.११; १२; ५७.६; ४.४.६; ८; ५.१.१०; २७.३; ३३.१; ४१.१८; ७०.१; ६.२.११; १४.६; १५.९; ५१.१२; ५७.५; ६२.७; ७.६.६; १८.४; २४.६; २५.६; ३१.१०; ३९.१; ६०.११; १००.२; ८.२.२१; ३१.७; ५१.५; ९.९६.२; ९७.२६; १०.११.७; १४८.३
सुऽमती ४.१.२; ९.७४.१
सुऽमतीः १०.२०.१०; ४७.७
सुऽमतीनाम् १.३.११; ४.३; १७.४; १०.८९.१७
सुऽमतौ १.९८.१; ३.१.२१; ५९.३; ४; ६.१.१०; ४७.१३; ७.१८.३; २०.८; ४१.४; ८.३.२; ४४.२४; ४८.१२; १०.१४.६; १३१.७; १६०.५
सुमत्ऽगणः २.३६.३
सुमत्ऽजानये १.१५६.२

सुरामम् १०.१३१.४; ५
सुरायाः १.११६.७; १०.१०७.९
सुरायाम् ८.२.१२
सुराऽवतः १.१९१.१०
सुराश्वः ८.२१.१४
सुरुक्मे इति सुऽरुक्मे १.१८८.६; १०.११०.६
सुऽरुचः १.११०.१; ३.७.५; ४.२.१७; ५.३३.१०; ६.३५.४
सुऽरुचम् १.११२.१; २.२.४; ३.२.५
सुऽरुचा ३.१५.६
सुऽरूपः ८.४.९
सुरूपऽकृत्नुम् १.४.१
सुऽरेक्णाः ६.१६.२६
सुऽरेतः १.१२१.५
सुऽरेतसम् १.१६०.३
सुऽरेतसा १.१५९.२; ३.१.१६
सुऽरेताः १०.४५.८
सुलाभिके १०.८६.७
सुव ३.५४.११; ५६.६[२]; ५.८२.४; ५[२]; ९.६६.१९; १०.३५.७; ३७.४
सुऽवचस्याम् १०.११६.९
सुऽवज्र ७.३०.१
सुऽवज्रः १.१००.१८
सुऽवज्रम् ४.१७.४; ८; ६.१७.१३
सुऽवज्रा ७.९३.४
सुवतात् ४.५४.३
सुवति ४.५४.४
सुवति ६.७१.४
सुवतु १०.३६.१४; १७५.१; ४
सुवते १.१३५.८; १६४.२२; १०.९१.६
सुवते ३.५५.५
सुवन्तु ७.५०.३
सुऽवरत्रम् १०.१०१.६
सुऽवर्चाः १.९५.१; १०.१४.८; ८५.४४
सुऽवर्णाः १०.६८.३
सुऽवसनस्य ६.५१.४
सुऽवसनानि ९.९७.५०
सुवसि ४.५४.२
सुवसि ४.५४.५
सुऽवह्वा ६.२२.७
सुऽवाचः ३.७.१०; ७.१०३.५; ८.९६.१
सुऽवाचम् ३.१.१९
सुऽवाचसा १.१८८.७
सुऽवाचा १०.११०.७
सुवाति ५.८२.३; ९; ७.४०.१; ६६.४
सुवाति ५.४२.३
सुवाते इति ५.१.४
सुवानः ७.३८.२; ९.६.३; ९.१; १८.१; ३४.१; ५२.१; ६६.२८; ८६.४७; ८७.७; ९१.२; ९२.१; ९७.४०; ९८.२; ३; १०७.३; ८; १०; १०९.१६; १०.३५.२
सुवानम् १.१३०.२
सुवानस्य २.११.२०; १९.१
सुवानाः ९.१३.५; ६५.२४; १०१.१०
सुवानासः ८.३.६; ६.३८; ५१.१०; ९.१०.४; १७.२; ७९.१
सुवाने ८.५२.२
सुवानैः ८.७.१४
सुवामि १०.१३७.४
सुऽवासाः १.१२४.७; ३.८.४; ४.३.२; १०.७१.४; ७५.८; ९१.१३; १०७.९
सुऽवास्त्वाः ८.१९.३७
सुऽविज्ञानम् ७.१०४.१२
सुवितः १०.५६.३[५]
सुवितम् १.१४१.१२; ४.५५.४; ७.९१.२; १०.१४८.१
सुवितस्य ७.१.२४; १००.२; ९.४१.२; १०.३१.३; १००.४
सुविता १.३८.३; १०.८६.२१
सुवितानि ८.९३.२९
सुविताय १.९०.४; १०४.२; ११८.१०; १६८.१; १७३.१३; १८०.१०; १८१.३; १८९.३; २.२.६; ३.२.१३; ५४.३; ४.१४.३; ५.११.१; ४१.१८; ५७.१; ५९.१; ४; ८०.३; ६.३२.४; ४०.३; ७१.३; ७.२.६; ३५.१; ६६.१५; ७५.२; ७९.३; ८५.४; ८.७.३३; २७.१०; ९.८२.५; १०.३५.३; ४०.१; ६६.३; ७४.२

सुऽहोता ८.१०३.१२
सूः १.३२.९; १४६.५
सूकरः ७.५५.४
सूकरस्य ७.५५.४
सूक्तऽवाकम् १०.८८.८
सूक्तऽवाकेन १०.८८.७
सूक्तऽवाचः ५.४९.५
सूचीकाः १.१९१.७
सूच्या २.३२.४
सूत १०.३१.१०
सून १०.६१.२०
सूतवे १०.१८४.३
सूते ७.१०१.३
सूते १.१६४.१७
सूदऽदोहसः ८.६९.३
सूदनम् ४.३९.५
सूदम् ९.९७.४४
सूदय ४.४.१४; ७.१६.९
सूदयन् १.७१.८
सूदयन्तु ४.३९.१; ४०.१
सूदयन्ते ८.२३.८
सूदयाति २.३.१०; ३.४.१०; ७.२.१०
सूदयामि १.१६२.१७
सूदयित्न्वः १०.६४.९
सूदाः ७.३६.३
सूदैः १०.६१.२
सूनया १.१६१.१०
सूनरः ८.२९.१; १०.११५.७
सूनरम् १.४०.४; ५.३४.७
सूनरि १.४८.१०
सूनरी १.४८.५; ८; ४.५२.१; ७.८१.१
सूनवः १.३७.१०; ४५.५; ८५.१; १५९.३;
६.५०.४; ५२.९; ७.८१.४; ८.२०.१७;
१०.५६.६. ६२.५; १७६.१
सूनवः २.३६.२
सूनवि ८.६८.१५
सूनवे १.१.९; २६.३; ३४.६; ५९.४;
१२७.५; १४३.१; २.३८.५; ३.१.१२;
८.४८.४; १०.२५.३
सूनाः १.१६२.१३
सूनाम् १०.८६.१८
सूनुः १.२७.२; ६२.९; ६६.१; १०३.४;
१८९.८; ३.१.२३; ५.११; ६.११; ७.११;
१५.७; २२.५; २३.५; २५.१; २८.३;
३३.५; ६.२.७; १२.१; ७.६७.१; ९.९.३;
१०७.१३; १०.४५.५; ६१.२४; ६३.१७;
६४.१७; ९५.१२
सूनुऽभिः १.१००.५
सूनुम् १.६४.१२; १२७.१; १६६.२; १८५.२;
३.११.४; ४.२४.१; ५.४२.२; ६.५.१;
६.१; ४९.२; ६२ ६; ६६.११; ८.२३.२५;
६९.४; ७१.११; १०.२०.७; ३९.१४
सूनुऽमतः ३.२४.५
सूनू इति ८.२५.५
सूनून् ५.४२.१५
सूनृत ८.४६.२०
सूनृता १.८.८; ३०.५; ४०.३; ५१.२;
१३४.१; १३५.७; ६.४८.२०; ७.३७.३;
५७.६; ८.१४.३; ४५.१२; १०.१४१.२
सूनृताः १.४८.२; ११३.१२; १२३.६;
३.३१.२१; ६१.२; ७.७९.५; ८.१३.८;
१०.३९.२; १११.१०
सूनृतानाम् १.३.११; ९२.७; ११३.४; १८;
३.३१.१८; ७.७६.७; ८.३२.१५
सूनृताभिः १.१२५.३; ७.६७.९; ८.१९.२२;
१०.६१.२१; १०४.५
सूनृतायै १.१२१.१४; १०.६१.२५
सूनृताऽवतः १.८२.१
सूनृताऽवता ८.९७.६
सूनृताऽवति १.९२.१४
सूनृताऽवती १.२२.३; ७.८१.६
सूनृताऽवते ७.७४.२
सूनृताऽवरि ४.५२.४
सूनृताऽवान् १.५९.७
सूनृते ४.५५.९
सूनृते १.१२३.५; १२४.१०; ८.९.१७
सूनो इति ८.४०.९
सूनो इति १.५८.८; ३.१.८; २४.३; २५.५;

२८.५; ४.२.२; ११.६; ३७.४; ५.३.९; ४.८; ६.१.१०; ४.१; ४; ५.५; ११.६; १३.४–६; १५.३; १८.११; २०.१; २१.११; ५०.९; ७.१.२१; २२; ३.८; ७.७; ८.७; १६.४; ८.१९.७; २५; ६०.२; ७५.३; १०.११.७; ५०.६; १४२.१

सूनोः १.११७.११; ९.१९.४

सूर्भर्वम् १०.१०२.५

सूर्भर्वाः १०.९४.३

सूयत १०.१३२.४

सूयते ४.५८.९; १०.११६.३

सूयते ८.६४.१०

सूरः १.५०.९; ६६.१; ७१.९; १२१.६; ७; १०; १३; १२२.१५; १३०.९; १४१.१३; १४९.३; १७४.५; ४.५.१३; १६.१२; १४; ४१.६; ४५.६; ५.३१.११; ७९.९; ६.२.६; ३.३; ४८.१७; ४९.३; ५१.९; ५६.३; ७.३.६; ४५.२; ६९.४; ८.१.११; ६.२५; ७.३६; ५६.५; ९२.३१; ९.१०.९; ६३.८; ९; ६६.१८; २२; ८६.३४; ९१.३; १११.१; १०.८.३; २७.२०; २९.५; ९२.७; ८; १२१.६; १३२.६; १७९.२

सूरऽचक्षसः १.१६.१; ८९.७; ११०.४; ७.६६.१०

सूरम् १.८६.५; ९.६५.१; ६७.९

सूरयः १.२२.२०; ४८.४; ७३.५; ९; ९७.३; ४; १२५.७; १४१.३; ८; २.१.१६; २.११–१३; ४.२९.५; ५.६.२; १०.३; ६; १६.५; १७.५; ५२.१६; ६६.६; ७९.७; ६.२५.७; ७.१६.७; ६६.१३; ७४.५; ९०.६; ८.१०.४; ६०.६; ९४.७; ९.९८.१२; ९९.३; १०.६५.४; ६६.२; ११; ७८.६

सूरयः ४.३४.६; ३७.७

सूरये १.३१.७; ५.२७.४

सूराः ९.१०.५

सूरात् १.१६३.२

सूराय १.५०.२

सूरिः १.१२२.८; १५३.२; १७६.४; १८०.६; १८१.४; १८६.३; २.६.४; ६.२३.१०; २९.५; ३७.५; ७.१.२३; ८.५.३९; ४६.२४; ७०.१३; १५; ९.६७.२; १०.६१.१८; ८१.६; १६७.४

सूरिऽभिः १.५१.१५; १८६.६; ५.४१.१५; ४२.४; ५२.१५; ६.२६.७; ६३.११; ७.३२.१५; ६६.९; ९२.४; ८.१८.४; २६.१२; १०.२३.३; ११५.७

सूरिऽभ्यः १.१८०.९; २.४.९; ६.४.८; ६८.७; ७.१.२४; १८.२१; ३०.४; ८१.६; ८.१३.१२

सूरिम् १.६१.३; ११९.३; १७३.७; ६.४५.३३

सूरिषु ५.७९.६; ८६.६; ६.४७.१९; ७.१९.७; ८४.३; ८.२६.१; ९.९८.८; १०.१४७.३

सूरीन् १.५४.११; १७३.८; २.३५.६; ६.८.७; १७.१४; ३७.४; ४४.१८; ७.३.८; ३८.३; ५७.७; ६७.१०; ६९.८; १०.६१.२२; ११५.५; ९

सूरे १.३४.५; ३.१५.२; ६.३१.१; ७.६३.५; ६५.१; ६६.४; ७; १२; ८.१.२९; १३.१३; २७.२१; ७२.१७; ९.९७.३८

सूरे ४.३.८

सूरेः १.१२२.११; १२; ३.३१.१४; ५.३३.८; १०.१३.१

सूर्तं १०.८२.४

सूर्म्यम् ८.६९.१२

सूर्म्याः ७.१.३

सूर्य १.५०.४; ७; ८; ११; ४.३१.१५; ५.४०.५; ६.५०.२; ७.६०.१; ६२.२; ८.९३.१; ४; १०१.११; १२; १०.३७.३–५; ७–१०; १५८.५

सूर्यः १.२३.१७; ३५.७; ४३.५; ४६.१०; ५६.४; ८३.५; ८४.१; ९०.८; १०१.३; १०५.१२; ११५.१; २; ५; १२४.१; १४६.४; १५७.१; १६०.१; १९१.८; ९; २.११.२०; २३.२; २४.९; ३.१४.४; ३०.१२; ५४.१९; ४.१.१७; १३.१; १४.२; २६.१; ५८.४; ५.४४.७; ४५.२; ९; १०; ५४.५; ५९.३; ६३.४; ६.४.३;

६; १२.१; ३०.२; ४८.२१; ६१.९; ७.८.४; ३५.८; ३६.१; ४७.४; ६०.२; ४; ६१.१; ६२.१; ६३.१; ७९.१; ८१.२; ८.३.२०; १२.७; १८.९; २५.१९; ३२.२३; ४३.३२; ४८.७; ५६.५; ५८.२; ७०.२; ९.५.११; ४१.५; ५४.३; ६३.१३; ६४.९; ३०; ८४.२; ८६.२९; १०.३५.८; ३७.२; ६०.११; ७७.३; ८८.६; ८९.२; ९०.१३; १३८.२–४; १५८.१; १५९.१; १७०.३

सूर्यःऽइव ४.३८.१०; ८.६.१०; १०२.१५; ९.५४.२; १०.६९.२; १७८.३

सूर्यऽत्वचः ७.५९.११

सूर्यऽत्वचम् ८.९१.७

सूर्यऽत्वचा १.४७.९; ८.८.२

सूर्यम् १.७.३; २३.२१; ३२.४; ३५.९; ५०.१; १०; ५१.४; ५२.८; १००.६; १८; ११२.१३; ११७.५; १३०.२[२]; १५१.५; १६४.२५; १७५.४; २.१२.७; १९.३; ५; ३.३१.१५; ३२.८; ३४.९; ३९.५; ४४.२; ४.१३.२; ३; २५.४; ३०.४; ६; ५.२७.६; ४०.६; ९; ६३.७; ८५.२; ६.१७.३; ५; ३०.५; ५२.५; ७२.१; २; ७.४४.३; ६०.३; ६६.१५; ७८.३; ८०.२; ८२.३; ९९.४; १०४.२४; ८.३.६; ६.२०; ७.२२; १२.३०; २५.२१; २९.१०; ५२.१०; ८९.७; ९८.२; ९९.३; ९.४.६; १७.५; २३.२; २८.५; ३७.४; ४२.१; ६३.७; ८६.२२; ९१.६; ९७.३१; १०७.७; २०; ११०.३; १०.९.७; १६.३; ३१.८; ३५.२; ४३.५; ५७.४; ५८.८; ५९.४; ६; ६०.५; ६२.३; ६५.११; ६७.५; ७२.७; ८८.११; १४१.३; १५४.५; १५६.४; १७१.४

सूर्यम्ऽइव ५.२७.६

सूर्यऽरश्मिः १०.१३९.१

सूर्यऽश्वितः १०.९४.५

सूर्यस्य १.१४.९; ४७.७; ४८.७; ९२.१२; १०८.१२; १०९.७; ११३.९; ११५.३; ४; ६; ११६.१७; ११७.१३; ११८.५; १२२.२; १२३.१२; १२४.८; १३७.२; १६४.१४; २.११.६; १९.४; ३३.१; ३.५.५; २२.३; ३१.१७; ४९.४; ५३.१५; ४.११.१; १३.४; १७.१४; २८.२; ४०.१; ४३.२; ५.४.४; २९.५; १०; ३७.१; ४०.८; ५९.५; ६२.१; ८; ६९.३; ७६.३; ७९.८; ८१.४; ६.२०.५; ३१.३; ५८.३; ६३.५; ७.२.१; ६.७; ३०.२; ४१.४; ६३.२; ७५.५; ७६.३; ८१.२; ९८.६; ८.१२.९; ७२.१६; १०१.२; ९.१.६; ६१.८; ७१.९; ७२.३; ७५.१; ७६.४; ८६.३२; ९३.१; ९६.५; ९७.३३; ११३.३; १०.३.२; ७.३; १०.९; २७.२१; ३५.५; ३७.६; ४९.७; ५९.५; ६६.२; ११२.३; १२३.१; १३९.४; १५१.५

सूर्यस्यऽइव १.१००.२; १३५.९; ५.५५.३; ४; ७.३३.८; ९.६४.७; ६९.६; १०.४८.३; ९१.४

सूर्या ५.७३.५; १०.८५.७; १०; १२

सूर्याऽइव १.१६७.५

सूर्याः ८.७०.५

सूर्याःऽइव १.६४.२; ८.३.१६; ३४.१७

सूर्याचन्द्रमसा १.१०२.२

सूर्याचन्द्रमसौ १०.१९०.३

सूर्याचन्द्रमसौऽइव ५.५१.१५

सूर्यात् ५.४२.९; ६.५९.८; १०.१८१.३

सूर्याम् ४.४४.१; १०.८५.९; १५; ३४; ३८

सूर्यामासा ८.९४.२; १०.६४.३; ६८.१०; ९२.१२; ९३.५

सूर्याय १.२४.८; ११३.१६; १२३.३; ५.३३.४; ८५.१; ७.८७.१; ८.७.८; १०.१४.१२; ३७.१; ९६.११; १११.३

सूर्यायाः १.१८४.३; ४.४३.६; ६.६३.६; १०.८५.६; ८; १३; १४; ३५

सूर्यायै ६.५८.४; ८.२२.१; १०.८५.१७

सूर्यावसु इति ७.६८.३

सूर्यासः १.१२५.६; ९.१०१.१२; १०.८८.१८

सूर्ये १.२३.१७; ५९.३; ६१.१५; १०४.६;

सेचते १०.९६.१
सेतवः ९.७३.४
सेतुः ८.६७.८
सेतुम् ९.४१.२
सेतू इति ७.६५.३
सेतृऽभिः ७.८४.२
सेतौ १०.६७.४
सेद् ७.५९.७
सेदुतः ८.२५.८; १०.११४.३
सेदथुः ७.७०.१
सेदथुः ४.५६.७
सेदिम १.८९.२; ५.८.४; ८.४९.६
सेदिरे १.२५.१३; ४.७.५; ५.८.२; ६.१५.८; ८.१०२.१८; १०.२१.७
सेदुः ३.३१.९; ४.१.१३; ६.११; ५०.३; ५.३.४; ६.३०.३; ७.३३.९; १०.७३.११; १३०.२
सेदुषः ५.१५.२
सेध ६.४४.९; ८.६०.२०; १०.२५.७
सेध ६.४७.२९; ८.७९.९^{2}; १०.९८.१२; १६६.३
सेधत १०.७६.४
सेधत ८.१८.१०; १०.१७५.२
सेधतम् १.३४.११; १५७.४; ८.३५.१६–१८
सेधति ९.७१.८
सेधति १.७९.१२; ७.१५.१०; ८.२३.१३
सेधतु १०.३६.४
सेधन् ९.११०.१२
सेधन्ति १.१०५.११
सेधन्तु १०.१००.८
सेधीः १०.२७.२०
सेनया ८.७५.७; १०.१५६.२
सेना ९.९६.१; १०.१४२.४
सेनाऽइव १.६६.४; १४३.५; ७.३.४
सेनाः १.१८६.९; २.३३.११; ५.३०.९; ७.२५.१; १०.१०३.१; ४; ७
सेनाऽजुवा १.११६.१
सेनाऽनीः ७.२०.५; ९.९६.१; १०.३४.१२; ८४.२

सेनाभिः १०.२३.१
सेनाम् १.३३.६
सेन्यः १.८१.२; ७.३०.२
सेपुः ६.२९.१
सेवते १०.११७.२
सेहानः ८.३६.१–६; ३७.२
सेहानायाः १०.१५९.२
सैर्याः १.१९१.३
सो इति १.१९१.११; १०.११.३; २३.४; ६३.१६
सोत ८.१.१७
सोत ८.१.१९; ९.१०८.७
सोतुः ८.२.२३
सोतन ८.४.१३
सोतरि १०.७६.२; १००.९
सोतवे १.२८.१
सोता ४.३.३; ७.९२.२; ८.३३.१२
सोतारः ९.१६.१; १०९.११
सोतारः ८.२.२५; ९.६२.१८
सोतु १०.७६.६
सोतुः ७.२२.१
सोतुम् ८.१९.१८
सोतृऽभिः ८.४९.५
सोतृऽभिः १.२८.८; ४.२९.२; ९.३०.२; ८६.१२; ९६.१६; १०७.८; २६
सोतोः १०.८६.१
सोत्वासः १०.१६०.२
सोभरयः ८.१९.३२
सोभरिम् ८.५.२६
सोभरी ८.२२.१५
सोभरीणाम् ८.२०.८
सोभरीऽयवः ८.२०.२
सोभरे ८.१९.२; २०.१९; २२.२
सोभर्याः ८.१०३.१४
सोम १.९१.९–११; १३; १५; १७; ८.४८.७; ८; ९.४.७; २४.३; ३१.३; ४०.६; ४३.६; ५५.१; ६१.२४; ६२.२५; ६३.३०; ६७.२८; ६८.७; ७९.३; ८६.२३; १००.२
सोम १.४३.७; ९^{2}; ९१.१; २; ३^{2}; ४–८;

१२; १४; १६; १८; १९; २१–२३; १३.५; १६४.१९; १८७.९; ४.२८.१; ५; ६.५१.१४; ५२.३; ७.१०४.२५; ८.४८.४[२]; ६; ९; १३; १५; ७८.८; ७९.३; ७; ८; ९.१.१; २.१; ४.१–३; ६.१; ८.३; ८; ९.७; ११.७–९; १४.८; १६.८; १७.५; १९.१; २; ७; २०.३; ५; ७; २२.७; २३.६; २४.४; २९.३; ४; ३०.३; ३१.४; ३२.४; ३३.६; ३६.२; ६; ४०.३; ४; ४१.६; ४२.६; ४३.४; ४६.५; ५१.४; ५५.३; ५६.३; ५९.१; ३; ६०.४; ६१.५; ६; १५; २३; ६२.२७; ६३.१; ११; १६; १८; २३; २४; २८; २९; ६४.१; ८; २५; २६; ३०; ६५.१३; १८; १९; २१; ६६.२; ३; ५–७; १५; १६; १८; ६७.१; ५; ६; १३; १५; १६; १९; २६; ३०[२]; ६८.१०; ६९.७; ८; ७०.९; ७४.९; ७५.५; ७६.३; ७८.२; ५; ८०.२; ४; ५; ८१.३; ८२.२; ४; ८५.१; ४; ५; ८६.५; १८; २२; २४; ३०; ३७–३९; ४७; ४८; ८७.९; ८८.३; ४[२]; ८[२]; ८९.७; ९०.५; ९१.६; ९२.४; ९४.५; ९६.३; ४; ११; १३; १६; २४; ९७.१४; १५; १८; २५; २७; ३३; ३६; ४२; ४८; ५०; ५८; ९८.१०; १००.३; ५; ६; १०६.४; ७; १०७.४; ६; १०; १२; १९; २०; २२–२४; १०८.१; १५; १०९.१; २; ४; ५; ७; १०; १८; ११०.२; ७; १२; ११३.२; ४[२]; ११४.१; ३; ४; १०.२५.२–८; ५७.६; ५९.४; ८५.४; १०७.२; १२४.६; १२८.५; १३९.४

सोमऽअद्‌ः १०.९४.९

सोमऽआहुतः १.९४.१४

सोमः १.१८.४; ५; २३.२०; ४५.१०; ४७.१; ६५.५; ८०.२; ८४.१; ८६.४; ९१.२०[३]; १०८.२; ६; १३५.२[२]; १३६.४; १३७.३; १६४.३५; १७७.३; ४; १९१.६; २.१२.१४; १८.६; ४०.६; ४१.४; ३.३५.६; ७; ३६.६; ४४.१; ५०.१; ५८.९; ६२.१३–१५; ४.२४.५; ४९.२; ५८.९; ५.३६.२; ४०.२; ४३.५; ४४.१४; १५; ४६.४; ५१.४; ६.२९.४; ३४.४; ३८.४; ४१.३–५; ४३.१–४; ४४.१–३; २४; ४७.४; ७५.१२; १८; ७.२४.२; २६.१; २; २९.१; ३५.७; ४९.४; ६४.५; ६५.५; ९८.५; १०४.९; १२; १३; ८.३.२०; ९.४; १३.३२; १७.६; ७; ११; २२.८; ३२.१६; ४८.१०; ११; ६४.१०; ६६.१५; ७९.१; ८२.५; ७; ८; ९२.२४; ९४.४; ९६.२१; १००.२; १०४.९; ९.२.५; १२.३–५; ८; १३.१; १६.४; १७.३; १८.१; २०.६; २३.५; २४.७; २५.५; २७.३; २८.२; ६; ३०.४; ३४.२; ३६.५; ३७.१; ५; ४२.५; ४३.३; ४४.२; ३; ५; ४७.१; ३; ५४.३; ५६.१; २; ६१.२५; ६२.१६; ३०; ६३.३; १३; ६५.२०; ६६.२९; ६७.११; ६८.९; ६९.१; ४; ७०.७; ७१.९; ७२.१; ४; ५; ७; ७४.७; ७८.४; ८१.२; ८२.१; ८४.२–४; ८६.३; ७; ९; १३; १६; १९; २१; ८७.४; ७; ८८.१; ५; ८९.१; ९२.३; ६; ९६.१; ५–७; ९; १५; १७; १८; २३; ९७.१०; २१; ३५; ३७; ३९–४१; ४५; ४६; ५६; ९९.६; १०१.६; ७; १६; १०३.४; १०६.२; १०; १०७.१; ७–९; ११; १७; १८; १०८.१३; १०९.१९; ११०.१०; १०.९.६; १६.६; ३०.५; ३२.९; ३५.२; ४८.१०; ५९.७; ६५.१; २; ८५.१; २; ९; ४०; ४१; ८९.५; ६; ९१.१५; १००.४; १०३.८; १०४.१; १०८.११; १०९.२; ११२.५; ११६.३; १२४.४; १३०.४; १५४.१; १६९.३; १७३.३; १७४.२

सोमःऽइव ६.८.१

सोमकः ४.१५.९

सोमऽकामम् १.१०४.९; ८.६१.२

सोमऽगोपाः १०.४५.५; १२

२२.१५; २४.१; २८.१; ३०.३; १३; १५; ३६.८; ३९.२; ४८.५; ४९.१०; ६५.१०; ७६.७; ८; ८५.३[२]; ९४.१३; ९६.१३; ११२.६; ११६.१; ८; १२५.२; १४१.३; १४८.२; १६०.२–४; १७३.६

सोमऽमादः ७.२१.२

सोमम्ऽइव १.११६.२४

सोमरभःऽतरेभ्यः १०.७६.५

सोमऽराज्ञीः १०.९७.१८; १९

सोमऽवतीम् १०.९७.७

सोमऽवत्या १०.११३.८

सोमऽवृद्ध ३.३९.७

सोमऽवृद्धः ६.१९.५

सोमऽशितम् ७.१०४.१९

सोमऽशिताः १०.१०८.८

सोमऽसुत् ७.६८.४

सोमऽसुतः १.८९.४

सोमऽसुता ७.९३.५

सोमऽसुतिम् ७.९३.६

सोमसुत्ऽभिः ४.२४.८; ८.४६.२६

सोमऽसुत्वा १.११३.१८

सोमस्य १.४.२; १६.३; २२.१; २३.२; ३४.२; ४६.५; १२; १३; ४७.९; ५५.२; ८५.१०; ८७.५; १०८.१; ३; ५–१२; १०९.२; ११७.१; ११९.९; १३४.१; १३६.६; १३९.२; २.८.६; १४.४; १५.२–९; १६.६; १७.१; ३.१.१; १२.३; ४०.७; ४२.४; ५३.२; ४.२०.४; २६.७; ३२.१७; ३५.२; ४९.५; ५.२९.३; ४३.४; ७१.३; ६.२८.५; ४९.१०; ६८.११; ६९.५; ७; ८.१.२०; ४.१२; १२.१२; १४.७; १७.१५; ३२.१; २८; ३४.१०; ३७.१–६; ४८.१४; ५३.४; ६५.३; ६८.१४; ७२.१७; ७६.६; ७७.४; ८५.१–९; ९२.५; २३; ९४.१०–१२; ९७.११; ९.१२.२; ८०.१; ८१.१; ८७.८; १०.५५.८; ८५.५; १०४.६; ११३.१; ११४.५; ११६.२; ११९.१–१३; १६७.३

सोमस्यऽइव १०.३४.१; १४९.५

सोमाः १.२.१; १३५.६; १३७.१; ३.३६.२; ४०.४; ४२.५; ४.१४.४; १७.६; ५.३०.११; ८.२.७; १०; २८[२]; ५२.१०; ९३.२५; ९.८.१; १२.१; १३.३; १६.५; १७.१; २१.१; २३.१; ३३.३; ४२.३; ४६.२; ६२.२२; ६३.४; २५; ६४.६; २८; ६९.९; ८७.५; ८८.६; ९७.२०; २६; ९८.११; १०१.४; १०; १०.४२.८; ४६.७; ७८.२; ९६.६

सोमाःऽइव ५.२७.५

सोमात् ७.३३.२

सोमान् ३.३६.३; ७.९८.२; १०.२८.३; ४२.५

सोमानम् १.१८.१

सोमानाम् १.१३४.६; ४.३२.१४; ४७.२; ८.९३.३३

सोमापूषणा २.४०.१; ३

सोमापूषणौ २.४०.५

सोमापूषऽभ्याम् २.४०.२

सोमाय ८.४८.१२; ९.११.४; ६५.७; १०३.१

सोमारुद्रा ६.७४.१–३

सोमारुद्रौ ६.७४.४

सोमासः १.५.५; ७; १६.६; २३.१; ५३.६; १३५.६; १३७.१; २; १६८.३; ३.३२.१५; ३६.३; ४; ४६.४; ४.४२.६; ५.३०.१०; ५१.७; ७.३२.४; ८.९.१४; ७६.८; ८२.२; ९३.६; ९.१०.१; ३; १७.२; २२.१; ३; २३.४; २४.१; ३१.१; ३२.१; ३३.१; ४६.३; ६३.१५; ६४.४; ६५.२२; १०१.८; १२; १०७.१४; १०.४३.४; ७; ४८.४

सोमिनः १.२२.४; ४९.१; १५१.२; ७.१०३.८; ८.१७.३; २४.२९; ४५.१६; ६२.१; ६; १०.४४.५; ५७.१; ९४.१; १७१.१; २

सोमिनः ७.३२.९

सोमिनि ७.३२.१२

सोमी ४.२५.५; ८.३४.९

स्त्रियाः ८.३३.१७
स्त्री ५.६१.६; ८.३३.१९; १०.८६.६
स्त्रीभिः १०.२७.१०
स्त्रैणानि १०.९५.१५
स्थ १.१५.२; १३९.११[२]; १७१.२; ४.३४.६; ३६.७; ५.६०.६; ६.५०.७; ५१.६; १५; ५२.१३; ७.४३.४; ८.७.१२; ३०.२; ८३.९; १०.९.१; १८.६; ३०.१२; ३६.१०; ६१.२७; ६३.२
स्थ २.२९.४; ५.५७.२; ६१.१; ७.१०३.७; ८.५५.४; ६७.५; १०.९४.११; ९७.९
स्थः १.१७.२; ४७.७; १०८.८–११; ३.५४.१६; ५.७३.१; ८.८.१४; १०.१; ५; ३८.१; ९.१९.२; १०.१०६.२
स्थः १.१०८.३; १५७.६[२]; २.३०.६; ५.७२.२; ६.६९.६; ८.७३.४; १०.४०.६
स्थन १.१०५.५; ५.८७.६; ८.३०.४; ९.६९.८; १०.६३.६
स्थन ५.५९.३; ८.१८.१५; १०.९४.१०[२]; ९७.९
स्थविरः १.१७१.५; १०.१०३.५
स्थविरम् १.५४.८; ४.१८.१०; २०.६; १०.५१.१
स्थविरस्य ३.४६.१; ६.१८.१२; ३७.५; ४७.८; ७.९३.२; १००.३
स्थविरा १.१८१.७
स्थविराय ६.३२.१
स्थविरासः ७.६७.४
स्थविरेभिः ६.१.११; ७.२४.४
स्थऽश्वः २.३८.८
स्थाः १.८०.१४; २.२७.४; ६.२४.९; १०.३५.९; ८८.४
स्थाः ४.३०.१२
स्थाःऽरश्मानः ५.८७.५
स्थाणुम् १०.४०.१३
स्थात् १.६८.१; २.३.१०; १५.७; ३.१५.६; ३६.९; ५.५३.९; ७.८७.६
स्थातु ५.५३.८; ७.३४.५; ८.२०.१
स्थातुः १.३३.५; ६.४१.३; ४९.६; ८.२४.१७; ३३.१२; ४६.१
स्थातुम् १०.१०६.२
स्थाता ३.४५.२
स्थाताम् १.७०.२
स्थातारः ५.८७.६
स्थातारा १.१८१.३
स्थातारा ऽइव १०.५९.१
स्थाति २.३१.३
स्थातुः १.५८.५; ६८.१; ७०.४; १५९.३; २.३१.५; ४.५३.६; ६.५०.७; ७.६०.२; १०.६३.८
स्थातॄन् १.७२.६
स्थात्रे १.१६४.१५
स्थार्थः ४.४६.४; ८.५.२८
स्थानम् ५.७६.४; ७.७०.१
स्थानानि ७.७०.३; ८.५९.६
स्थापयन्ति १०.१०२.१०
स्थापयसे १०.१२०.७
स्थाम् ९.८५.११
स्थाम् २.२७.१७; २८.११; २९.७
स्थामं १.१३९.४
स्थाविरीः ९.८६.४
स्थिरः १.१०१.४; २.४१.१०; ८.३३.९; ९२.२८
स्थिरऽधन्वने ७.४६.१
स्थिरऽपीतम् १०.७१.५
स्थिरम् १.३७.९; ३९.३; ६४.१५; १२७.३; ३.३५.४; ५.३०.४; ८.३२.१४; १०.६१.२०; ११७.२; १२०.४; १३४.२
स्थिरस्य ५.५२.२
स्थिरा १.३९.२; १२७.४; १६७.७; २.३३.१४; ४.४.५; ७.१०; ७.५६.७; ८.१९.२०; २०.१; १२; १०.११६.५
स्थिराऽइव १०.११६.६
स्थिराः १.३८.१२; ८.६६.२
स्थिराणि १.१२७.४; ८.१४.९; १०.८९.६
स्थिराय ३.३०.२; ६.२४.८; १०.९६.७
स्थिरे ८.४५.४१

स्थिरेभिः २.३३.९
स्थिरैः १.८९.८
स्थिरौ ३.५३.१७
स्थिविऽभ्यः १०.६८.३
स्थिविऽमन्तः १०.२७.१५
स्थुः १.२४.७; १६७.९; ५.१५.३; ७.१८.३; १०.५७.१
स्थूणा ५.६२.७; ८.१७.१४
स्थूणाऽइव १.५९.१; ५.४५.२
स्थूणाम् १०.१८.१३
स्थूरम् ६.१९.१०; ८.१.३४; ४.१९; २१.१; २४.२९; ५४.८; १०.१५६.३
स्थूरयूपऽवत् ८.२३.२४
स्थूरयोः ६.२९.२
स्थूरस्य ४.२१.४
स्थूरि १०.१३१.३
स्थेयाम ६.४७.८; ७.९५.५; ८.२७.२०
स्नातुः १.१०४.३
स्नाती ५.८०.५
स्नात्वाः १०.७१.७
स्नीहितीषु १.७४.२
स्नुना ४.२८.२; ८.७.७; ९.९७.१६; १९
स्नुऽभिः ५.६०.७; ८७.४; ७.८८.३; ८.४६.१८; ९.१०७.८
स्नेहितीः ८.९६.१३
स्नोः ४.२७.४
स्पट् ५.५९.१; ८.६१.१५; १०.३५.८
स्पन्दने ३.५३.१९
स्पन्द्रः ६.१२.५
स्पन्द्रम् १०.४२.५
स्पन्द्रा १.१८०.९
स्पन्द्राः ५.५२.८
स्पन्द्रासः ५.५२.३; ८७.३
स्परत् १.१६१.५
स्परसे ८.२०.८
स्परिति स्वः ९.७०.१०
स्पर्तम् ७.७१.५
स्पर्धन्ते ६.१४.३; ७.८५.२; ९.९४.१
स्पर्धमानाः १.३३.५
स्पर्धमाने इति ७.९३.५
स्पर्शयस्व १०.११२.३
स्पशः १.२५.१३; ३३.८; ४.४.३; ६.६७.५; ७.६१.३; ८७.३; ८.४७.११; ९.७३.४; ७; १०.१०.८
स्पशम् ४.१३.३
स्पार्हः ४.१.१२; ४७.१
स्पार्हम् १.३१.१४; ७.८१.३; ८.४५.४०-४२; १०.४९.१०; ५५.६
स्पार्हया ७.७२.१
स्पार्हऽराधाः ४.१६.१६
स्पार्हऽवीरम् ५.५४.१४
स्पार्हऽवीराः ७.९१.५
स्पार्हस्य ८.२४.८
स्पार्हा १.१२३.६; १३५.२; २.२३.९; ४.१.६; ७
स्पार्हाः ७.१५.५; ९.१०२.५; १०.२.६; २६.१; ६८.३
स्पार्हाणि ७.५९.६
स्पार्हाभिः ७.५८.३; ८४.३
स्पार्हे २.१.१२; ७.५६.२१
स्पाशयस्व १.१७६.३
स्पूर्धन् ६.६७.९
स्पूर्धसे ५.६४.४
स्पृणवाम ५.४४.१०
स्पृणुहि १०.८७.७
स्पृतम् १०.३९.६
स्पृधः १.८.३; १७४.५; १७९.३; २.११.१९; ५.४४.७; ५५.६; ६.५.६; ६.६; २०.९; २५.२; ९; ४५.१८; ४९.१५; ८.१४.१३; ९२.३२; ९९.५; ६; ९.७.५; २०.१; १०.१८.९; १००.१२; ११३.४; १६७.२
स्पृधानम् ३.३१.४
स्पृधाम् १.११९.१०; १७४.१०
स्पृधि ७.८२.९
स्पृधि ५.३.९; ८.६६.१४
स्पृश ४.३.१५; ४.२; ७.२.१; ८.९६.११; १०.८७.२

स्पृशत १०.७०.५
स्पृशन्ति १.६२.११
स्पृशन्ति १.३६.३
स्पृशामसि १०.१३७.७
स्पृशामि १०.१२५.७
स्पृहयत्ऽवर्णः २.१०.५
स्पृहयन्ति ८.२.१८
स्पृहयाय्यः ६.१५.१२; ७.४.९
स्पृहयाय्यस्य ८.९७.१५
स्पृहयाय्याणि ६.७.३
स्पृहयेत् १.४१.९
स्फुरीः ६.६१.१४
स्फातिम् १.१८८.९
स्फिग्यम् ८.४.८
स्फिग्या ३.३२.११
स्फिरम् ८.१.२३
स्फुर ४.३.१४
स्फुरत् १.८४.८
स्फुरन्ति १०.३४.९
स्फुरान् ६.६७.११
स्फूर्जयन् १०.८७.११
स्म १.१२.५; ८; १५.१०; २६.३; २८.६; ३७.१५[२]; ४२.२; ५१.१२; १०२.३; ५; १०४.५; १२७.६; ९; १२८.५; १२९.२; ३; १३३.७; १६९.३; ५; १७३.११; १२; १८०.७[२]; ८; २.१२.५; ३१.२; ३.३०.४; ६२.१; ४.३.१०; १०.७; १६.१७; २९.२; ३१.७–९; ३८.४–६; ८[२]; ९; ४०.३; ४३.३; ५.७.४[२]; ५; ७; ८; ९.३–५; २३.४; ४५.४; ५२.८; ९; ५३.५; ५४.६; ५६.७; ६.२.२; १२.५; १५.९; १७.१४; २५.७; ४४.१८[२]; ४६.१०–१२; ६५.४; ६६.६; ७.३.२; १५.१३; २१.९; ३२.१५; ५६.२२; ८३.५; ८८.६; ८.१.२१; ७.२१; २१.१०; २४.६; २५.१५; २७.४; १४; ४४.११; ६०.१०; ८६.३; ९२.२६; ९.२०.२; ८७.६; ९; १०.१२.५; २७.२४; ३९.८; ३३.१; ६६.१०; ८७.२३; ९५.५[२]; ८; ९६.१०; १०२.२; ४; ६; १३४.२; १३६.७ १७८.३
स्मः ८.२१.६
स्मः ८.१०२.३
स्मत् १.५१.१५; १००.१३; १८६.६; ८; २.४.९; ५.४१.१५; १९; ८७.८; ७.३.८; ८.१८.४; २०.१८; २६.१९; १०.६१.८
स्मत्ऽइभम् १०.४९.४
स्मत्ऽइष्टाः ७.८७.३
स्मत्ऽऊध्नीः १.७३.६
स्मत्ऽदिष्टयः ७.१८.२३
स्मत्ऽदिष्टिः ३.४५.५
स्मत्ऽदिष्टीन् ६.६३.९
स्मत्ऽपुरंधिः ८.३४.६
स्मदभीशू इति स्मत्ऽअभीशू ८.२५.२४
स्मदिष्टी इति स्मत्ऽदिष्टी १०.६२.१०
स्मद्रातिऽसाचः ८.२८.२
स्मयते १.९२.६
स्मयन्त १.१६८.८
स्मयमानः २.४.६
स्मयमानाभिः १.७९.२
स्मयमानासः ४.५८.८
स्मयेते इति ३.४.६
स्मराथः १०.१०६.९
स्मरेथाम् ७.१०४.७
स्मसि १.२९.१; ३७.१५; ५.७४.६; ८.१८.२२; ४६.१; ९.९७.२७
स्मसि १.५७.५; २.४१.१६; ६.५४.९; ८.१८.१९; ३२.७; ४७.८; ४८.८; ६६.१३; ९२.३२
स्य ४.१६.२; ५.८५.८; ६.४०.१; ९.९५.५; ९७.१८
स्यः १.१६१.४; २.३१.३; ४; ३३.७; ३६.५; ३८.१; ४.३८.७; ४०.४; ४५.१; ५.३०.१; ५६.७; ६.२.३; ५०.१३; ७१.१; ४; ७.८.२; २३.३; ३८.१; ६०.२; ६७.७; ६८.९; ६९.५; ८.२५.१९; २७.१२; ६४.७; ९.३.१०; ३८.१; ४–६; ६२.१३; ८४.४; ८७.४; ८९.१; ९६.१५; ९७.४६;

९८.२; ३; १०८.५; १०.८६.२२; ९२.१२; १७६.३
स्यतम् ६.७४.३; १०.१४३.२
स्यताम् २.४०.४
स्यति १०.६१.२०
स्यतु १.१४२.१०; २.३.९
स्यध्वम् १०.३०.११
स्यन्ता १०.२२.४
स्यन्ति १.८५.५
स्यन्दते ९.८०.३
स्यन्दन्ताम् ५.८३.८
स्यन्दमानाः १.३२.२
स्यन्दयध्यै ४.२२.७
स्यन्दस्व ९.६७.२८
स्यन्नाः ५.५३.७
स्यस्व १.१०१.१०
स्यस्वेति स्यस्व ३.४.९; ७.२.९
स्या १.८८.६; १०४.५; ११९.९; १६५.६; १७८.१; १८१.८; ४.५२.१; ५.६.४; ६.६१.७; ६५.१; ७.७५.४; ८०.२; ९५.४; ८.१८.७; २६.१८; ४६.३३
स्याः ८.४४.२३
स्याः १.१७४.१०; ४.१६.१८; ६.३३.५; ७.१.८; ९; १०.११.९; १२.९; ६९.६
स्यात् १.१७.६; ३.१.२३; ५.११; ६.११; ७.११; १५.७; २२.५; २३.५; ७.३४.२१; ८.२.१३; १९.२६
स्यात् १.३८.४; १६७.१०; १८२.८; ३.३९.८; ६२.३; ६.६८.६; ७; ८.१४.१; १०.३१.४; ११७.७
स्यात ५.८७.९
स्यातन १.३८.४
स्यातम् १.१२०.७; ३.३८.९
स्याताम् १.१०४.३; ४.४१.६
स्याम् ६.५०.९; ८.१४.२; १९.२५; ४४.२३
स्याम् १.११६.२५; ३.१५.१; ६.५०.९; ६३.११; ७.१.१३; ८.४४.१८
स्याम १.४.६; २.११.१; १३; ५.३१.१३; ३८.५[२]; ५३.१४; १५; ६५.५; ७.१८.३; २०.८; ४०.१; ६६.१३; ८१.४; ८.१९.७; ३५; ४४.२४; ४७.५; ६३.१०; ९.६१.२४; ९८.५; १०.३८.२; ६६.१२; १२६.४
स्याम १.२४.१५; ५१.१५; ७३.८; ९४.१३; १५; ९८.१; १०५.१९; १२१.१५; १५०.३; १६४.४०; १७८.५; १८०.९; १८५.४; २.२.१२; ८.६; ११.१२; १८.८; २४.१५; २७.७; १६; २८.२; ३; ३८.१०; ३.१.१६; २१; ३०.१८; ३९.७; ८; ५५.२२; ५९.३; ४; ४.८.५; १६.२१; १७.९; २१; १९.११; २०.११; २१.११; २२.११; २३.११; २४.११; २९.५; ४१.१०; ११; ५०.६; ५१.१०; ११; ५६.४; ५.४.१; ८; ६.८; २०.४[२]; ४२.१७; ४३.१६; ४५.११; ४९.४; ५४.१३; ५५.१०; ६२.९; ७०.२; ८५.८; ६.१९.१३; २६.८; ३३.५; ४७.१२; १३; ५२.५; ७१.२; ६; ७.१.२०; २५; ४.४; ७; १४.३; १७.७; १९.७; २१.९; ३४.२४; २५; ३७.४; ४१.३; ४[२]; ५; ४८.२; ५२.१; ५४.२; ५६.२४; २५; ६०.१; ६६.९; ८७.७; ९२.४; ८.४०.१२; ४३.३०; ४८.१२; १३; ५३.७; ९.३५.३; ८६.३८; ८९.७; ९५.५; १०.१४.६; २२.१२; २९.२; ३१.१; ३५.१४; ३६.१२; ६४.११; १२१.१०; १२८.३; १३१.६; ७; १३२.२; १४८.३
स्यालात् १.१०९.२
स्युः ८.४४.२३
स्युः ६.२८.१
स्युरिति स्युः २.४.९; ८.७०.५
स्युरिति स्युः १.२४.७; १२३.१३; ६.६३.१०; १०.२०.८; ८९.१५
स्यूतम् १.३१.१५
स्यूमऽइव ३.६१.४
स्यूमऽगभस्तिः १.१२२.१५
स्यूमऽगभस्तिम् ७.७१.३
स्यूमऽगृभे ६.३६.२
स्यूमना १.११३.१७

५४.१५; ६६.२; ८०.१; ६.२९.३; ६०.२[२]; ७२.१; ७३.३; ७.१०.२; ३४.१९; ८१.४; ८८.२; ९०.६; ८.३.१३; १५.२; १२; ४६.८; ४९.८; ७६.४; ९८.३; ९.४.२; ७.४; ४८.४; ५९.४; ६१.१८; ७४.१; ८६.१४; ९०.४; ९१.६; ९८.८; ११३.७; १०.२०.२; ४३.४; ९; ६१.१४; ६५.१; १४; ६६.४; ९; ८८.२; १२३.७; १२४.६; १३६.१; १५४.२; १७०.४; १९०.३

स्वःऽगे १०.९५.१८

स्वःऽचक्षाः ९.९७.४६

स्वःऽचनाः ९.८४.५

स्वःऽजित् ९.२७.२; ७८.४

स्वःऽजितम् १०.१६७.२

स्वःऽजितं २.२१.१

स्वःऽजेषे १.१३२.२

स्वःऽदृक् ७.५८.२

स्वःऽदृशः १.४४.९; १५५.५; २.२४.४; ७.३७.२; ८३.२; ९.१३.९; ७६.४

स्वःऽदृशम् ३.२.१४; ५.२६.२; ७.३२.२२; ९.६५.११

स्वःऽदृशा ५.६३.२

स्वःऽनरः ५.५४.१०

स्वःऽनरम् २.२.१; ५.६४.१; ६.१५.४; ८.३.१२; १२.२; १९.१; ९.७०.६; १०.६५.४

स्वःऽनरात् ४.२१.३

स्वःऽनरे ५.१८.४; ८.६.३९; ६५.२; १०३.१४

स्वःऽपतिः ८.४४.१८

स्वःऽपतिम् ८.९७.११

स्वःपती इति स्वःऽपती ९.१९.२

स्वःऽभानुः ५.४०.५; ९

स्वःऽभानोः ५.४०.६; ८

स्वःऽमीळ्हस्य १.१६९.२

स्वःऽमीळ्हे १.५६.५; ६३.६; ४.१६.१५

स्वःऽमीळ्हेषु १.१३०.८; ८.६८.५

स्वःऽयर्वः ३.३०.२०; ५०.४

स्वःऽवत् १.१७३.१; १८५.३; ६.१९.९; ३५.२; ४७.८; १०.३६.३

स्वःऽवति १०.६३.१५

स्वःऽवती १.१६८.७; ५.३४.१; १०.११.३

स्वःऽवतीः १.१०.८; ११९.८; ५.२.११; ८.४०.१०; ११

स्वःऽवतीम् १.१३६.३

स्वःऽवते १.५९.४

स्वःऽवन्तः ६.५०.२

स्वःऽवान् ६.२२.३; ३७.१; ८.९७.१

स्वःऽवित् १.९६.४; ३.३.१०; ८.४८.१५; ९.८६.३; १०९.८

स्वःऽविदः ९.२१.१; ९७.३९; १०१.१०; १०६.१; ९; १०७.१४; १०८.२; १०.४३.१; ६५.१४

स्वःऽविदम् १.५२.१; २.२३.३; ३.३.५; २६.१; ५१.२; ५.४४.१; ८.१३.५; ९.८.९; ८४.५; १०६.४; १०.५६.६; १०७.४

स्वःऽविदा ६.३९.४; ७.६७.३

स्वःऽविदा ८.८.७

स्वःऽविदि १०.८८.१

स्वःऽविदे ९.९४.२

स्वःऽसाः १.१००.१३; २.१८.१; ३.३४.४; ७.९७.७; ९.९६.१८; १०.१२०.८

स्वःऽसाता १.१३१.६; ४.१६.९; ६.१७.८; ३३.४; ९.८८.२; १०.९९.३

स्वःऽसाम् १.६१.३; ९१.२१; ५.४५.११; १०.८.६; ४७.५

स्वऽक्षत्रम् १.५४.३; ५.३५.४

स्वऽक्षत्रया ५.४८.१

स्वऽक्षत्रेभिः १.१६५.५

स्वऽगूर्ता ४.१९.१०

स्वऽगूर्ताः १.१४०.१३; ६.६८.४; १०.९५.७

स्वऽगोपा १०.३१.१०

स्वऽचन्द्रम् १.५२.९

स्वजध्वम् १०.१०१.१०

स्वजन्ते १०.४३.१

स्वऽजन्मना ७.१.१२

स्वऽजाः १.१६८.२

स्वजाते १०.१०.१३; १४

स्वप ७.५५.२–४
स्वपःऽतमः ४.१७.४
स्वपःऽतमम् १.६१.६
स्वऽपतिः १०.२७.८; ३१.४; ४४.१
स्वपन् ५.४४.१३
स्वपन्तः १०.१६४.३
स्वऽपूभिः ७.५६.३
स्वप्नः ७.८६.६
स्वप्नऽनंशनः १०.८६.२१
स्वप्नस्य १.१२०.१२
स्वप्नाय ८.२.१८
स्वप्ने २.२८.१०
स्वप्नेन २.१५.९; १०.१६२.६
स्वब्दीऽइव ८.३३.२
स्वऽभानवः १.३७.२; ८२.२; ५.५३.४
स्वऽभानवः ८.२०.४
स्वऽभानवे ५.५४.१; ६.४८.१२
स्वभानो इति स्वऽभानो ६.६४.४
स्वभिष्टिऽसुम्नः ६.२०.८
स्वभूतिऽओजाः १.५२.१२
स्वम् १.४६.९; ५८.२; ७५.५; १२८.१; ३.७.६; ३१.१०; ५.५८.७; ५९.१; ६.२०.११; २८.२; ४१.१; ७.२३.२; ५६.२४; ८२.६; ८.७२.१४; ९.६३.६; १०.१.३; १२.१; १३.२; ५६.२; ८५.३०
स्वऽयतासः १.१६६.४
स्वयम् १.८७.३; १२२.९; १२९.६; ८; १५८.५; २.३५.१४; ४.१८.५; १०; ५०.८; ५.१२.५; ४४.८; ४६.१; ५५.२; ८७.२; ६.५१.७; ७.८.५; ५६.११; ८.४.१२; ६६.१५; ९.२१.२; ४७.४; १०.७.६; २७.१२; २८.११; ५०.६; ८१.५; ६; ९१.५; १२५.५
स्वयम्ऽजाः ७.४९.२
स्वयम्ऽभूः १०.८३.४
स्वऽयशाः ७.२२.५; १०.४९.११
स्वयशःऽतरः ३.४५.५; ५.१७.२
स्वयशःऽतरम् ५.८२.२; ८.६०.११
स्वयशःऽभिः १.९५.९; १२९.८
स्वऽयशसः १.१३६.७; ७.८५.३; ८.६७.१३; १०.७५.९; १७७.५
स्वऽयशसम् १.९५.२; ९.९८.६; १०.९२.१४; १०५.९
स्वऽयशसे १.१२९.३; ५.४८.१
स्वऽयशाः १.९५.५; ७.३७.४; १०.९२.९
स्वया ५.५८.५; ७.३.९; ८६.२
स्वऽयावन् ८.२५.१२
स्वऽयुः २.४.७; ३.४५.५
स्वऽयुक्ताः १.१६८.४
स्वयुक्तिऽभिः १.५०.९; ११९.४
स्वयुक्ऽभिः १०.६७.८; ८९.७
स्वयुग्वऽभिः ९.१११.१[2]
स्वऽयुजः १०.७८.२
स्वर् १.१०.४; ८.१३.२७; ९.९७.३
स्वरणम् १.१८.१
स्वरन्ति १.१५१.५; ५.५४.२; १२; ८.३३.२; ९.८५.३
स्वरन्ति ९.८५.३
स्वरन्तु ८.१३.२८
स्वरवः ३.८.६; ९; १०; ४.५१.२
स्वऽराजः १.१८१.२; २.२८.१; ३.४६.१; ५.५८.१; ७.६६.६; ८.९४.४; १०.१२०.८
स्वऽराजम् १.३६.७; ३.४९.२; ८.६१.२; ६९.१७; ८१.४
स्वऽराजे १.५१.१५; ७.१०१.५; ८.१२.१४
स्वऽराज्यम् १.८०.१–१६; ८४.१०–१२; २.८.५; ५.८२.२; ८.९३.११
स्वऽराज्ये ५.६६.६
स्वऽराट् १.६१.९; ३.४५.५; ७.८२.२; ८.४६.२८; १०.१५.१४
स्वराति ८.६९.९
स्वरितारः १.१६६.११
स्व१रिति स्वः १.५२.१२; १२९.२; १३१.२; २.२४.३; ३.३१.१९; ५.१४.४; ४६.३; ८३.४; ७.४४.१; ६६.९; ८.५०.८; ७२.१५; ८९.४; ९.९.९; ७६.२; १०.२७.२४; ३६.१; ६८.९; १०७.८; १२१.५; १६७.१; १८९.१

स्वरीणाम् १०.६८.७
स्वरुः ४.६.३; ८.४५.२
स्वरुम् १.९२.५
स्वरूणाम् ७.३५.७
स्वरे ८.७२.७
स्वरेण १.६२.४
स्वऽरोचिः ३.३८.४
स्वऽरोचिषः ५.८७.५
स्वरौ १.१६२.९
स्वर्थे इति सुऽअर्थे १.९५.१
स्वर्थः १.६२.४
स्वर्थम् १.३२.२; ६१.६; १२१.४; ४.१७.४; ५.३०.८; ५६.४; ७.१०४.४; १०.१७७.२
स्वऽर्वसुः ५.४४.७
स्वऽर्वान् १.३५.१०; ११८.१; ३.५४.१२; ६.४७.१२; १३; ६८.५; १०.९२.९; १३१.६; ७
स्वऽर्विद्युतः ५.८७.३
स्वर्वृक्तिऽभिः १०.२१.१
स्वऽर्वृजम् १०.३८.५
स्वऽर्वृष्टिम् १.५२.५; १४
स्वऽशोचिः ६.६६.६
स्वश्वऽयुः ८.४५.७
स्वसरम् ६.६८.१०; ८.९९.१
स्वसरस्य ३.६१.४; ५.६२.२
स्वसराणि १.३.८; ३४.७; २.१९.२; ३४.५; ३.६०.६
स्वसरे ९.९४.२
स्वसरेषु २.२.२; ३४.८; ८.८८.१
स्वसा १.१२३.५; १२४.८; १८०.२; १९१.६; २.५.६; ३२.६; ८.१०१.१५; १०.१०.११
स्वसारः १.६२.१०; ७१.१; १६४.३; १९१.१४; २.५.५; ३.२९.१३; ४.६.८; २२.७; ७.६६.१५; ८.५९.४; ९.१.७; ६५.१; ७१.५; ८२.३; ८६.३६; ८९.४; ९१.१; ९३.१; ९८.६; १०.१२०.९
स्वसारः ३.३३.९
स्वसारम् १.९२.११; १०.३.३; १०.१२; १०८.९; १२७.३
स्वसारा १.१७८.२; १८५.५; ३.५४.७
स्वसारौ ३.५५.११
स्वसुः ४.५२.१; ६.५५.४; ५; ७.७१.१; १०.१७२.४
स्वऽसृत् १.८७.४
स्वऽसृतः १.६४.११
स्वसृऽत्वम् १०.१०८.१०
स्वसृऽभिः ९.७२.३; १०.९४.४
स्वसृः ६.६१.९; १०.५.५
स्वसृणाम् १.१२४.९; ३.१.३; ११
स्वऽसेतवः ८.३९.१०
स्वऽसेतुः १०.६१.१६
स्वस्तये १.१.९; २२.१२; ३५.१; ८९.५; ९७.८; २.२.६; ३२.८; ३.१०.८; ३०.१८; ४.३१.११; ३९.४; ५.१७.५; २८.२; ५०.५; ५१.१२^{२}; १३^{२}; ६४.६; ६.१५.१८; ५७.१; ६; ७.३९.२; ८.१८.२०; ३१.११; ९.६४.३०; ७५.५; ९६.४; १०.३६.१२; ६३.३–१४; ६५.१०; ६६.१; १४; १२६.५; १७८.१; २
स्वस्ति १.८९.६^{४}; ११६.६; ८; ११७.१५; १७४.९; २.९.६; १५.५; ३३.३; ३८.९; ३.३१.२०; ५३.२०; ४.११.६; ५.४.११; १६.५; ४२.४; १५; ५१.११^{४}; १२; १३; १४^{४}; १५; ६.४.८; २०.६; १२; ४७.८; ११; ८.१६.११; ३१.११; ४८.८; ९.९७.३६; १०.७.१; १४.११; ३५.३–१२; ५९.६; ६३.१५^{४}
स्वस्तिः ३.३८.९; १०.५९.७; ६३.१६
स्वस्तिऽगाम् ६.५१.१६; ८.६९.१६
स्वस्तिऽदाः १०.१७.५; ११६.२; १५२.२
स्वस्तिऽभिः १.१८९.२; ५.५३.१४; ७.१.२०; २५; ३.१०; ४.१०; ७.७; ८.७; ९.६; ११.५; १२.३; १३.३; १४.३; १९.११; २०.१०; २१.१०; २२.९; २३.६; २४.६; २५.६; २६.५; २७.५; २८.५; २९.५; ३०.५; ३४.२५; ३५.१५; ३६.९; ३७.८; ३९.७; ४०.७; ४१.७; ४२.६; ४३.५; ४५.४; ४६.४; ४७.४; ४८.४; ५१.३;

४.१५.७; ५.३०.१; ३६.५; ४०.४; ६.२३.१; ४; ७.२३.३; ३२.४; ८.६.३६; १०.१०४.१; ६; ११६.४

हरिम् १.१२१.८; ३.४४.४; ९.२६.५; ३०.५; ३२.२; ३८.२; ३९.६; ५०.३; ५३.४; ६२.१८; ६३.१७; ६५.८; ७२.१; ८६.२५; २७; ८९.३; ९६.२; ९८.७; ९९.२; १००.७; १०९.१२; २१; १०.९६.२; १०१.१०

हरिमन्युऽसायकः १०.९६.३

हरिमाणम् १.५०.११; १२[२]

हरिम्ऽभरः १०.९६.४

हरिऽयूपीयायाम् ६.२७.५

हरिऽयोगम् १.५६.१

हरिऽयोजनाय १.६२.१३

हरिऽवः १.३.६; ३३.५; १६५.३; १६७.१; १७३.१३; १७४.६; १७५.१; ३.३०.२; ४७.४; ५१.६; ४.१६.२१; १७.२१; १९.९; ११; २०.११; २१.११; २२.७; ११; २३.११; २४.११; ५.३१.२; ३६.२; ४; ४२.४; ६.१९.६; २२.३; ४१.३; ४४.१०; ७.१९.७; २५.४; २९.१; ३७.४; ८.२.१३; २१.६; २४.३; ५; ४०.९; ५३.८; ६१.३; ९९.२; १०.४९.११; ६१.२२; ९६.१३; १०४.२; ६

हरिऽवते ३.५२.७

हरिऽवन्तम् १०.९६.२; ७

हरिऽवर्पसम् ३.४४.३; १०.९६.१

हरिऽवान् १.८१.४; ७.२०.४; ३२.१२; १०.९६.१०

हरिऽव्रतम् ३.३.५

हरिऽशिप्रः १०.९६.४

हरिऽशिप्रम् १०.९६.१२

हरिऽश्मशारुः १०.९६.८

हरिऽश्रियम् ८.१५.४; ५०.१०

हरिऽसाचः १०.९४.१२

हरिऽस्थाः १.१९१.१०–१३; ६.१७.२

हरिऽस्थाम् ३.४९.२

हरी इति १.५.४; ६.२; १०.३; १६.२; २०.२; ५५.७; ६३.२; ८१.३; ८२.१–६; ८४.२; ३; ६; १११.१; १२१.८; १६१.६; १६२.२१; १६५.४; १७४.४; १७७.१; ४; १८१.५; २.११.६; ७; १६.६; १८.३; ७; ३.३२.१; ३५.१; २; ४; ५; ४३.४; ६०.२; ४.१५.८; ३२.१५; ३३.१०; ३५.५; ५.२७.२; ४३.५; ५६.६; ६.२०.९; ४०.१; ५७.३; ७.१९.६; ३६.४; ८.१.२५; २.२७; ३.१७; ४.११; १४; ६.४५; १२.१५; २५–२८; १३.१०; २३; २७; ३१; १४.१२; १७.२; ३२.२९; ३०; ३३.११; ३४.९; ४५.३९; ६८.१५; ७०.७; ९३.२४; ९८.९; १०.२३.२; ३; ४४.२; ४९.२; ९३.८; ९४.९; ९६.१; २; ६–९; १०५.२; ११४.९; १६०.१

हरीइवेति हरीऽइव १.२८.७

हरीणाम् ४.४८.५; ५.३३.२; ८.२४.१४; २५.२३; १०.२३.१

हरीणाम् ८.२४.१७; ३३.१२; ४६.१; ९.१०५.५

हरे ९.६४.१४

हरे ९.२५.१; ११३.५

हरेः ९.६६.२५

हर्मि १.६१.१

हर्म्यम् ७.५५.६

हर्म्यस्य १.१२१.१; ९.७१.४; ७८.३

हर्म्या १.१६६.४

हर्म्ये ५.३२.५; ८.५.२३; १०.११४.१०

हर्म्येभ्यः ७.७६.२

हर्म्येषु १०.४६.३; ७३.१०

हर्म्येऽस्थाः ७.५६.१६

हर्य १.५७.४; १४४.७; ३.४०.२; ८.४४.२; १०.७०.१; ११२.७; १२२.२

हर्यत ५.५४.१५; ८.४४.५

हर्यतः १.५५.४; ५७.२; ३.५.३; ४४.१; ९.२५.४; ४३.१; ३; ६५.२५; ८६.२६; ४२; ९८.८; १०६.१३; १०७.१३; १६; १०.११.६; २६.७; ९६.४; १०

हर्यतम् १.९३.७
हर्यतम् २.२१.१; ९.२६.५; ९६.१७; ९८.७; १०.९४.८; ९६.१; ५; ११
हर्यतम् १.९३.१
हर्यतस्य ८.७२.१८; १००.५; १०.९६.९; १०; १२३.२
हर्यता ८.१२.२५–२८; १०.९६.६
हर्यताभ्याम् ८.६.३६
हर्यताय १.१३०.२; ९.९९.१
हर्यति ४.५८.८
हर्यते १०.९६.६; १०५.१
हर्यते ५.५७.१
हर्यथ १.१६१.८
हर्यन् ४.२४.७; १०.४.३; ९६.१२
हर्यन् ३.४४.२[२]
हर्यन्तम् ३.४४.५; १०.९६.१२
हर्यन्ति १.१६५.४
हर्यमाणः ३.६.४; १०.९६.११
हर्यश्वऽप्रसूताः ३.३०.१२
हर्यसि १०.९६.५; ११
हर्याः ५.२.११
हर्यामसि १०.११६.८
हर्योः १.७.२; ३.४५.२; ४.१६.११; ८.३३.४
हर्षतः १.१२७.६
हर्षते ९.९६.१; १०.३०.५
हर्षते १.५१.७; ९.७०.५
हर्षमाणः ४.३८.३
हर्षमाणासः १०.८४.१
हर्षय ८.१५.१३; १०.१६.१४; १०३.१०
हर्षयन् ९.१११.३
हर्षयन्त ४.३७.२
हर्षसे ४.२१.९
हर्षस्व ८.१९.२९; १०.११२.१
हर्षुऽमन्तः ८.१६.४
हर्ष्याः १.५६.५; ८.६८.१४
हवः ८.१३.३१–३३; १०.७४.२
हवते १.१८३.५; २.३३.५; ६.३७.१; ८.८५.३
हवते १.१०५.१७; ३.२०.१; ५.४२.१५; ६.२६.२; ७.२२.६; ५६.१८; ७३.१; ८.८६.१–३; ९.८०.१; १०.१५०.५
हवनम् ८.५२.७; ५४.४
हवनऽश्रुत् २.३३.१५
हवनऽश्रुतः ६.५२.१०; १०.६४.६
हवनऽश्रुतः ८.६७.५
हवनऽश्रुतम् १.१०.१०; ८.१२.२३
हवनऽश्रुता ५.७५.५
हवनऽश्रुता ६.५९.१०; ७.८३.३; ८.८.७
हवनऽस्यदम् १.५२.१
हवना ६.६९.४
हवनानि ५.५६.२; ६.३४.४; ३५.३; ७.६८.२; १०.८१.७
हवनाय ६.६३.२
हवनेषु १.१०२.१०; १०.६१.३
हवन्त १.१२.२; १०.११८.५
हवन्ते १.४५.५; ६; ११७.१०; २.१२.९; ३.४३.२; ५.३५.६; ६.२५.६; ३३.२; ७.२६.२; ३०.२; ६९.६; ८२.९; ८.१.३; ६.३७; १५.१२; ३४.४; ६६.१२; ६८.५; १०.१७.९; २५.९
हवन्ते १.२३.३; ४७.४; ६३.६; १४२.१३; ३.३२.१४; ४३.१; ५८.४; ४.२५.८; ४२.५; ६.२१.१; ७.२७.१; ७४.१; ८३.६; ८.५.१७; १६.५; ४६.१२; १०.१७.७; ४८.१
हवम् १.२.१; १०.९; १७.२; २३.८; २५.१९; ३०.८; ४५.३; ४७.२; ४८.१०; ८६.२; ९३.१; ११४.११; १२१.३; १२२.११; १४२.१३; १७८.३; १८१.७; १८३.५; २.१०.२; ११.१; २४.१५; ४१.४; १३; १५; ३.६२.२; ४.९.७; ५.१४.५; २४.२; ४३.११; ७४.१०; ७५.१–९; ७८.५; ८७.८; ९; ६.२१.१०; २३.४; २४.२; ४५.११; ४६.६; ५०.५; ६; १०; ५२.७; १३; ६०.१५; ६२.७; ६९.७; ७.२२.४; २८.२; ६७.१०; ६९.८; ८२.८; ९४.२; ८.१.२७; ३.१४; १८; ६.१८; ७.९; १३.७; २२.१२; २६.१०;

८.४८.१२; १३; ९६.८; १०.१४.१; ४; २०.८; ३०.३; ४०.४; ६५.६; ८१.६; ९०.६; ९५.१८; ९८.४; १२१.१; २; ४–९; १२४.६; १५९.४; १६१.१; ३; ४; १६८.४; १७३.३; ६; १७४.१; ४; १९१.३

हविषि ६.५२.१७; १०.८१.५; ९१.८

हविषे १०.१६.१२

हविष्मः ९.८३.५

हविष्मतः १.५७.२; १७३.१२

हविष्मता १.१२८.२²; १५६.१; ७.६७.१; १०.३९.१

हविष्मती ७.१.६; ८.२३.२२; ६०.१

हविष्मतीः ८.६.२७; १३.१६

हविष्मतीम् ३.१९.२

हविष्मते १.१३.१; ३.१०.४; ५.२.१२; १०.४३.८; १२५.२

हविष्मत्ऽभिः ३.२९.२

हविष्मन्तः १.१४.५; ३६.२; ६०.२; ११४.८; ३.१३.२; २६.१; २७.१; १४; ४१.७; ५.९.१; ७.११.२; ८.५.१७; ७४.२; १०.३०.२; ७०.३; ७७.१; ९१.९; १२२.४

हविष्मन्तम् ४.४५.७; ८.९.६

हविष्मान् १.१२.९; १२७.१०; १५७.६; १६२.२२; १६७.६; १८०.३; १८१.९; १८३.३; ५; ४.२.८; ४१.१; ६.१०.६; १६.४६; ७३.१; ७.१.१६; ७०.६; ८५.४; ९.९६.१२; १०.४२.४

हविष्यम् १.१६२.४

हविष्षु ९.७.२

हवींषि १.९४.४; १७०.५; २.९.३; ३७.५; ३.३५.७; ७.५७.६; १०.२.२; ६.३; १५.८; ११; १२; ७०.८; १०; ११०.१०; ११६.८

हवीतवे ८.१०१.४

हवीमन् ६.६३.४; ७.५६.१५

हवीमनि ७.८३.४; १०.६४.४; ९९.१२

हवीमऽभिः १.१२.२; १३१.६²; १५९.२; २.३३.५

हवे १.११८.११; ६.५२.१६; ८.१३.१३²; ९.८८.३; १०.१२८.८

हवेते इति २.१२.८

हवेभिः ७.१९.९

हवेषु ७.२.७; ३५.१२; ३८.७; १०.४.१; १५.१; १०३.११; १८२.२

हवेऽहवे ६.४७.११

हव्यऽअत् ७.३४.१४

हव्यः १.३३.२; १००.१; १०१.६; ११६.६; १२९.६; १४४.३; २.२३.१३; ३७.२; ३.५.३; ४९.३; ४.२४.२; ५.१७.४; ३३.५; ६.१८.६; २२.१; ४५.११; ७.२२.७; ३२.२४; ३८.१; ८.१.२८; १६.८; २०.२०; ७०.८²; ७१.१५; ९०.१; ९६.२१²; १०.६.७; ३८.४; ३९.१; ८९.१०

हव्यऽजुष्टिम् १.१५२.७; ७.६५.४

हव्यऽदातये ५.२६.४; ५१.१; ५; ६.१६.१०; ४८.२; ८.३५.९; १०१.१

हव्यदातिऽभिः ४.८.५; ८.१९.१३; २३.१५; २१

हव्यऽदातिम् ३.२.८; ५.५५.१०; ६.१.९; ४७.२८; ७.१६.९; १०.७.७

हव्यम् ६.२१.१; ७.३०.२; ८.९६.२०; १०.३९.१०

हव्यम् १.१२८.६; १३६.१; १४२.१२; २.३.२; १०; ११; ३२.६; ३.१८.३; ५९.१; ४.९.६; २६.४; ५.४.८; १६.२; २९.३; ८६.६; ६.२.१०; १५.१०; ७.१.२३; ४.१; ३९.६; ४७.३; ६४.१; ६७.७; ८६.२; ९९.७; १००.७; ८.१९.१; १०.८.५; १२.२; १४.१५; १६.९; ५२.१; ८०.४; ११०.१०

हव्यऽवाट् ५.६.५

हव्यऽवाट् १.१२.६; ६७.१; ३.२.२; ११.२; २७.५; ५.४.२; २८.५; ८.५६.५; १०.१२४.१

हुव्यऽवाहः ३.४३.१

हुव्यऽवाहन् १.३६.१०; ४४.५; ३.९.६; १०.११८.५; १५०.१

हुव्यऽवाहनः १.४४.२; ५.११.४; २५.४; ६.१६.२३; ७.१५.६; ८.२३.६; १०.११९.१३

हुव्यऽवाहनम् २.४१.१९; ५.८.६; २८.६; ८.१९.२१

हुव्यऽवाहनीः १०.१८८.३

हुव्यऽवाहम् १.१२.२; ४४.८; १२८.८; ३.५.१०; १०.९; १७.४; २९.७; ४.८.१; ६.१५.४; ८; ७.१०.३; ११.४; १७.६; ८.४४.३; १०२.१७; १८; १०.८.६; ४६.४; १०; ५२.३; ४; ११८.९

हुव्यऽसूदः १.९३.१२; ४.५०.५

हव्या २.३९.१; ६.६१.१२

हुव्या १.७४.६; ७५.१; ९१.४; ९३.११; १०५.१४; १२७.८; १२८.७; १३९.३; १४२.११; १७१.४; १८७.११; १८८.१; २.२.६; ३.२१.१; ४; ५४.२२; ४.९.५; ५.७.३; ९.१; १४.१; १८.१; ६.१२.२; १५.१४; ४७.२८; ५२.११; ७.१.१८; २.२; ९.१; ५६.१२; ५९.५; ८.१९.११; २०.९; १०; १६; २३.६; २७.६; ४४.१; ५; ६०.१५; १०.१५.४; २०.५; ७६.७; १२८.४; १७६.२

हव्याः ६.२१.१

हुव्यानि १.७४.४; १०१.१०; १२७.६; १३५.३; ४; १४२.१३; १८८.१०; ३.५२.२; ५३.१; ६२.४; ४.१५.३; ५.५.१०; ६.६०.१५; ७.६८.१; ८.९.१४; १९.२४; २३.२६; ३८.५; ४४.८; ७४.३; १०१.७; १०; १०.१५.१२; १६.११; ५१.५

हुव्याय १.४५.६; ३.२९.४; ५.१४.३

हव्यासु १०.१४७.२

हुव्येन ४.४२.१०; ६.५२.८

हुव्येभिः १.१५३.१; ४.४२.९; ७.८.१; ८४.१; ८.२६.३; ७४.६; १०.२४.२

हुव्यैः २.२.५; २६.४; ३.३१.११; ४.२.१; ५.३.८; ४.७; ६.१.१०; ७.३.७; ६३.५; ६८.४

हुसनाम् ९.११२.४

हसाय १०.१८.३

हुस्कुतारम् ४.७.३

हुस्कारात् १.२३.१२

हस्कृतिः ८.८९.६

हस्तः २.३३.७; १०.६०.१२

हुस्तऽगृह्य १०.८५.२६; १०९.२

हुस्तऽग्राभस्य १०.१८.८

हुस्तऽघ्नः ६.७५.१४

हस्तऽच्युती ७.१.१

हस्तऽच्युतेभिः ९.११.५

हस्तम् ६.५४.१०; ८.२४.५; १०.४७.१; ८५.३६

हस्तऽयतः ५.४५.७; १०.७६.२

हस्तयोः १.२४.४; ३८.१; ५५.८; ८१.४; १३५.९; १६२.९; १७६.३; ६.३१.१; ४५.८; ९.१८.४; ९०.१

हस्तऽवन्तम् १०.३४.९

हस्ता ४.२१.९; ८.६८.३

हस्ताऽइव २.३९.७

हस्तात् ३.३५.१०; १०.१८.९

हस्ताभ्याम् १०.१३७.७

हस्ताय ८.७०.२

हस्तासः ४.५८.३

हुस्तिनः १.६४.७; ३.३६.७; ९.८०.५

हुस्तिऽभिः ५.६४.७

हुस्ती ४.१६.१४

हस्ते १.६७.२; ७२.१; ११४.५; १२८.६; २.१६.२; ३.३९.६; ६.१६.४०; १८.९; २२.९; २९.२; ७.२८.२; ४५.१; ८.२९.३–५; ७०.१२; ७८.१०; ९.८९.६; १०.९७.११

हस्तेन १०.१०९.३

हस्तेभिः ४.२.१४

हस्तेषु १.३७.३; १६८.३

हस्तैः ९.७९.४

हिरण्यवर्तनी इति हिरण्यऽवर्तनी १.९२.१८; ५.७५.२; ३; ८.५.११; ८.१; ८७.५
हिरण्यऽवाशीः ७.९७.७
हिरण्यऽवाशिभिः ८.७.३२
हिरण्यवाशीमत्ऽतम १.४२.६
हिरण्यऽवित् ९.८६.३९
हिरण्यऽवीनाम् ८.६५.१०
हिरण्यऽशम्यम् १.३५.४
हिरण्यऽशिप्राः २.३४.३
हिरण्यऽश्रृङ्गः १.१६३.९
हिरण्यऽसंदृक् २.३५.१०
हिरण्यऽसंदृशः ६.१६.३८; ८.५.३८
हिरण्यऽस्तूपः १०.१४९.५
हिरण्यस्यऽइव १.११७.१२
हिरण्यऽहस्तः १.३५.१०
हिरण्यऽहस्तम् १.११६.१३; ११७.२४
हिरण्या ४.१७.११; ९.९७.५०
हिरण्यानाम् ४.३२.१९
हिरण्यानि १.१६२.१६
हिरण्येन १.३३.८
हिरण्यैः १.१२२.२; २.३३.९; ५.६०.४; ७.९०.६
हिरिऽशिप्रः २.२.५; ६.२९.६
हिरिऽश्मश्रुः ५.७.७
हिरिऽश्मश्रुम् १०.४६.५
हिरिमशः १०.१०५.७
हिरीमान् १०.१०५.७
हिरुक् १.१६४.३२
हिषे ७.७.१
हीळः ८.१८.१९
हीळितः १.८०.५
हीळितस्य ७.४६.४
हीना १०.३४.१०
हीयताम् ६.५२.१; ७.१०४.१०
हीये १०.३४.५
हुतासः ६.५०.१५
हुरः ४.३.१३
हुरःऽचितः ९.९८.११
हुरःऽचितम् १.४२.३

हुरुक् ९.७७.५
हुवत् ८.२६.१६
हुवतः ६.२१.१०
हुवध्यै १.१२२.४; ५; ५.४१.३; ४३.८; ४५.४
हुवन्यति १.११९.९
हुवानः ३.४१.१; ५.४३.१०; १३; ६.२१.१०; ७.७.३; ३०.३; ८.७४.१३; १०.११२.३
हुवानाः ४.१.१३; ६.५०.१४
हुवामहे ५.५६.८; १०.५७.३
हुवे १.१७.७; ९; ३०.९[2]; ७६.४; १३८.२; १८१.९; १८५.३; ६; २.४.१; ३८.९; ५.४६.३; ७३.२; ६.५.१; ५०.१; ७.४२.२; ६१.६; ६७.४; ८.१.१०; ५.२४; १०.५; २२.१५; ३२.४; ५८.३; ६५.३; ६६.१; १०२.५
हुवे १.२.७; २३.५; १११.४; ११९.१; २.२९.१; ३२.४; ३७.२; ३.१२.४; २०.५; ५.१८.३; ४०.३; ५६.९; ६.४५.७; १९; ६०.४; १३; ६२.१; ७.१६.१; ३२.३; ४४.१; ५६.१०; ६५.१; ८.१०.२; ३; १३.३३; २३.७; २६.१; ३५.२२–२४; ४४.१३; ६८.४; ७६.१; ९४.१०–१२; १०२.४; ६; ९.५.७; ९; १०.१४.५; १९.४; ३६.१; ६१.४; ६६.१; १५०.४
हुवेम ६.५७.१; ८.६०.१७
हुवेम १.१२७.२; १८०.१०; १८४.१; २.१७.८; ३.३०.२२; ३१.२२; ३२.१७; ३४.११; ३५.११; ३६.११; ३८.१०; ३९.९; ४३.८; ४७.५; ४८.५; ४९.५; ५०.५; ४.१६.१६; ४४.१; ६.१९.४; ११; ४९.१०; ७.४१.१; २; ४४.२; ७१.१; ९०.७; ९१.७; ९७.५; ८.२३.२०; २७.१३; ९६.२०; ९.६८.१०; १०.४५.१२; ६३.११; ८१.७; ८९.१८; १०४.११; १२६.५; १६०.५; १७८.१
हुवेय ८.९.१३
हूतः ४.१५.७; १०.८४.२; १०७.५
हूतासः ६.५०.४

हूमहे ८.२६.२४
हूमहे १.१०.१०; ८९.३; ५; ५.३५.३; ६.४६.३; ६; ८.५१.५; ८३.६
हूयते १.३४.१०; १०१.६
हूयते १.२६.६; ३६.६; १३५.२; ५.६.५; ८.८२.५; १०.१५१.१
हूयन्ते ८.७६.८
हूयमानः १.१०४.९; २.१८.४; ४.२९.२; ५.४३.५; १०.२८.३; ११६.१; १२२.५
हूयमानम् ४.२३.३
हूयमाना ४.४३.४; ६.६७.३; ७.६८.८
हूयमानाः २.३.५; ४.३४.६
हूयसे ३.४०.९; ८.४.१; ६५.१
हूयसे १.१९.१; ८.१७.१२; २१.१४; ८२.४
हृणानस्य १.२५.२
हृणायन्तम् १.१३२.४
हृणीताम् ८.१०३.१२
हृणीते ७.८६.३
हृणीथाः ८.२.१९
हृणीयमानः ५.२.८
हृणीषे २.३३.१५
हृणीषे ७.१०४.१४
हृत्तः १०.११.६
हृत्ऽभिः १.११६.१७; ८.४३.३१
हृत्ऽरोगम् १.५०.११
हृत्ऽसु १.१६८.३; १७९.५; ५.८५.२; ८.२.१२; १८.१५; ४८.१२; १०.४०.१२; ६४.२; १०३.१२
हृत्सुऽअसः १.८४.१६
हृदः १.२४.१२; ६०.३; २.३५.२; ३.३९.१; ५.३१.९; ७.१०१.५; १०.५.१
हृदम्ऽसनिः ९.६१.१४
हृदयम् ६.५३.८; १०.१०.१३; ३४.९; ९५.१७
हृदयऽविधः १.२४.८
हृदयस्य ७.३३.९
हृदया ६.५३.५; ७
हृदयात् १०.१६३.३
हृदयानि १०.८५.४७; ९५.१५; १९१.४
हृदये १.१२२.९; ६.९.६; १०.८७.४; १३
हृदयेषु १०.८४.७
हृदय्यया १०.१५१.४
हृदा १.६१.२; ६७.२; १०५.१५; १४६.४; १७१.२; ३.२६.८; ४.५८.६; ५.४.१०; ५६.२; ६.१६.४७; २८.५; ७.९८.२; ८.२०.१८; ७६.८; ७७.९; ९.५३.२; १०.७१.८; ९१.१४; ११९.५; १२३.६; १७७.१
हृदि १.३२.१४; ९१.१३; २.२३.१६; ३.४२.८; ४.४१.१; ४३.१; ५८.११; ६.५३.६; ७.८६.८; ९.७३.८; १०.३२.९; ९१.१३; १२९.४
हृदिऽस्पृक् १.१६.७
हृदिऽस्पृशः १०.२५.२; ४७.७
हृदिऽस्पृशम् ४.१०.१
हृदे १.४३.१; ७३.१०; ४.३७.२; ५.११.५; ८.१७.६; ४८.४; ७९.७; ८२.३; १००.५; ९.७२.७; ८६.२१; १०.८६.१५; ९७.१८; १८६.१
हृद्यम् ५.४२.२
हृद्या १०.७३.६
हृद्यात् ४.५८.५
हृषितम् १.१०३.७
हृषीवतः १.१२७.६
हृषीवन्तः २.३१.१
हृष्यति १०.८६.७
हेळः १.२४.१४; ९४.१२; ११४.४; १७१.१; ४.१.४; ६.६२.८; ७.८४.२
हेळांसि ६.४८.१०
हेळे ७.६२.४
हेत १०.३०.९
हेतयः १.१९०.४; ८.५०.२
हेतारः ९.६२.६
हेतारम् ८.९९.७
हेतिः २.३३.१४; ६.१८.१०; २८.७; ८.६७.२०; १०.८९.१२; १६५.२; ३
हेतिम् १.१०३.३; १२१.१०; ३.३०.१७; ६.५२.३; ६२.९; ७५.१४; १०.१४२.३

होतॄन् २.३४.१४; १०.३५.१०; ६१.१
होत्रम् १.७६.४; २.१.२; ३.१७.२; १०.२.२; ५३.४; ५; ९१.१०; ९८.४; ५
होत्रया १.१२९.७; १५१.३
होत्रऽवाहम् ५.२६.७
होत्रा १.१८.८; १२०.१; १४२.९; २.१.११; ३.६२.३; ४.२.१०; १०.६४.१५
होत्राः ४.४८.१; ५.८१.१; ८.९३.२३; १०.१७.११
होत्राणि ३.४.५
होत्रात् २.३६.१; ३७.१[2]; ४; १०.५१.४
होत्राभिः १.३६.७; १२२.९; २.२.८; ७.६०.९; ८.१२.२०; ५३.७; ५४.६; १०.११.५
होत्राम् १.२२.१०; ७.१०४.६; ८.१०१.८; १०.४०.४; ६३.७
होत्राय ६.११.१; १०.९८.७
होत्राऽविदः १०.१५.९
होत्राऽविदम् ५.८.३
होत्रियम् १.८३.२
होत्रे ३.१०.५
होम १.९.९; ८४.१८
होमनि ३.६०.७; ८.६३.४
होषि ६.४४.१४
ह्नुतः ८.३१.७
ह्यः ८.६६.७; ९९.१; १०.५५.५
ह्रदम् १.५२.७; ३.४५.३; १०.४३.७; १०२.४
ह्रदाः १०.१४२.८
ह्रदाःऽइव ३.३६.८; १०.७१.७
ह्रदेऽचक्षुः १०.९५.६
ह्रादुनिम् १.३२.१३
ह्रादुनिऽवृतः ५.५४.३
ह्रुणाति १.१६६.१२
ह्रुतः ६.४.५; ९.६१.२७
ह्लादिकाऽवति १०.१६.१४
ह्लादिके १०.१६.१४
ह्वय ५.५३.१६
ह्वयति १०.१४६.४
ह्वयन्ति १०.१६०.२
ह्वयन्ते १०.११२.७
ह्वयन्ते १.१०२.६; ४.२४.३; ३९.५; १०.४२.४; ८०.५
ह्वयामसि ६.२६.१; ३३.४; ४१.५
ह्वयामहे १.४७.१०; ११४.४; ५; १०.४०.४
ह्वयामि १.३५.१[4]; ६.४७.११; ७.३४.८
ह्वये १.१३.३; ७; ८; १०; १२; २१.१; २२.५; १२; २३.१८; ११२.२४; १६४.२६; ५.५६.१; ५; १०.३६.७; १०१.१
ह्वरः २.२३.६; ५.२०.२
ह्वरते १.१४१.१
ह्वरांसि ६.४८.१०; ९.३.२; ६३.४; १०६.१३
ह्वारः १.१४१.७; १८०.३
ह्वारे २.२.४
ह्वार्यः ६.२.८
ह्वार्याणाम् ५.९.४

॥ श्रीः ॥

॥ अकारादिवर्णक्रमेणोत्तरपदसूची ॥

भूतऽअंशः
तृप्तऽअंशवः
उपऽअंशु
सुमत्ऽअंशुः
विऽअंसः
विऽअंसम्
सम्ऽअकृण्वन्
विऽअक्तः
विऽअक्तम्
सम्ऽअक्तम्
आलऽअक्ता
विऽअक्ता
विऽअक्ताः
सम्ऽअक्ताः
विऽअक्ताम्
चतुःऽअक्षः
सहस्रऽअक्षः
हिरण्यऽअक्षः
अधिऽअक्षः
षट्ऽअक्षम्
सम्ऽअक्षम्
अधिऽअक्षम्
परिऽअक्षरत्
सम्ऽअक्षरन्
सहस्रऽअक्षरा
अनक्षा
सहस्रऽअक्षा
अघःऽअक्षाः
भूरिऽअक्षाः
अनक्षासः
सहस्रऽअक्षेण
अधिऽअक्षेण
चतुःऽअक्षौ
सुऽअक्सः
अवऽअख्यत्
सम्ऽअगच्छन्त
उत्ऽअगाः
सुऽअग्मयः
इद्धऽअग्नयः
समिद्धऽअग्निः
अनग्निऽत्राः
अनग्निऽदग्धाः
जमत्ऽअग्निना
इन्द्राग्निऽभ्याम्
अग्निम्ऽअग्निम्
इन्द्राग्नी इति
इन्द्राग्नी इति
इन्द्राग्नी इति
दीर्घग्नी इति दीर्दिऽअग्नी
इन्द्राग्न्योः
सम्ऽअग्मत
अग्रम्ऽअग्रम्
अर्थःऽअग्रया
गोऽअग्रया
गोऽअग्राः
चन्द्रऽअग्राः
ज्योतिःऽअग्राः
गोऽअग्रान्
तपुःऽअग्राभिः
गोऽअग्राम्
केवलऽअघः
आरेऽअघाः
आरेऽअघाम्
सम्ऽअङ्क्ते
परिऽअङ्ग्याते
सर्वऽअङ्ग
सुऽअङ्गः
चतुःऽअङ्गः
वीळुऽअङ्गः
अङ्गम्ऽअङ्गम्
वीळुऽअङ्गम्
सुऽअङ्गा
अङ्गात्ऽअङ्गात्
सुऽअङ्गुरिः
सुऽअङ्गुरे
दशऽअङ्गुलम्
वीळुऽअङ्गे
चराचरः
अनूचः
अनूची इति
देवद्रीचा
घृताची
आऽअच्य
अपीच्यम्
देवाच्या
पूतनाजः
सम्ऽअजग्रभीत्
अपऽअजन्
गोऽअजनासः
अश्वऽअजनि
मन्द्रऽअजनी
पूतनाजम्
सुनिःऽअजम्
सम्ऽअजाति
उत्ऽअजायन्त
सम्ऽअजासि
निःऽअजे
सम्ऽअज्यसे
पूतनाज्ये
पूतनाज्येषु
उरुऽअज्रे
असमृष्टाञ्चः

ऋजुऽअञ्चः
सध्र्यञ्चः
सुऽअञ्चः
उत्ऽअञ्चनः
निऽअञ्चनम्
सुऽअञ्चम्
सध्र्यञ्चा
सुऽअञ्चाः
सम्ऽअञ्जन्
अभिऽअञ्जनम्
विऽअञ्जनम्
आऽअञ्जनेन
सम्ऽअञ्जन्ति
वृषत्ऽअञ्जयः
स्त्रेदाञ्जिऽभिः
करम्भऽअत्
क्रव्यऽअत्
विश्वऽअत्
सुयवसऽअत्
हव्यऽअत्
निःऽअतक्षत
निःऽअततंसतम्
मेध्यऽअतिथिः
नीपऽअतिथिम्
मेधऽअतिथिम्
मेध्यऽअतिथिम्
मेध्यऽअतिथे
मित्रऽअतिथेः
मेध्यऽअतिथेः
नीपऽअतिथौ
मेध्यऽअतिथौ
अनतिद्भुता
अवऽअतिरः
अवऽअतिरत्
अधिऽअतिष्ठत्
परिऽअतिष्ठत्
दुरत्येतु इति दुःऽअत्येतु
आमऽअदः
क्रव्यऽअदः
पुरुषऽअदः
मधुऽअदः
यवऽअदः
यवसऽअदः
सुहुतऽअदः
सोमऽअदः
हविःऽअदः
ऊर्जऽअदः
अनदतीः
क्रव्यऽअदम्
विश्वऽअदम्
सम्ऽअदहः
क्रव्यऽअदे
अद्यऽअद्य
हविःऽअद्यम्
हविःऽअद्याय
अग्रेऽअद्वाना
सम्ऽअधत्त
अधिऽअधत्तम्
अवऽअधुः
विऽअध्वनः
प्रऽअध्वने
सुऽअध्वर
सुऽअध्वरः
दाशुऽअध्वरः
सुऽअध्वरम्
जीरऽअध्वरम्
दाशुऽअध्वरम्
सुऽअध्वरा
दाशुऽअध्वराय
सुऽअध्वरासः
सुऽअध्वरे
कृष्णऽअध्वा
विऽअनत्
अविऽअनत्
अपऽअनती
पुरुऽअनीक
सुऽअनीक
त्रिऽअनीकः
चतुःऽअनीकः
ज्योतिःऽअनीकः
तिग्मऽअनीकम्
शतऽअनीकाः
सम्ऽअनीकेषु
अननुऽकृत्यम्
अननुऽकृत्या
अननुऽदः
अननुऽदम्
अननुऽदिष्टः
अननुऽभूतीः
सत्यानृते इति
अनन्तः
अनन्तम्
सम्ऽअन्तम्
दशऽअन्तरुष्यात्
विष्टऽअन्ता
सम्ऽअन्ता
अनन्तान्
अनन्तासः
ईर्मऽअन्तासः
बहुलऽअन्तासः
अनन्ते
दूरेअन्ते इति दूरेऽअन्ते
समन्ते इति सम्ऽअन्ते
अनन्तैः
घृतऽअन्नः
द्रुऽअन्नः
सर्पिःऽअन्नः
पीवःऽअन्नान्
बहुऽअन्नाम्
उक्षऽअन्नाय
तत्ऽअन्नाय
वशाऽअन्नाय
वृषभऽअन्नाय
घृतऽअन्नौ
अन्यत्ऽअन्यत्
अन्यम्ऽअन्यम्
अन्याऽअन्या

अन्याम्ऽअन्याम्
अपऽअप
तत्ऽअपः
अनपऽच्युतः
अनपऽच्युतम्
अनपऽच्युता
स्वपःऽतमम्
आश्वपःऽतरेभ्यः
सुऽअपत्यम्
सुऽअपत्यस्य
अनपत्यानि
सुऽअपत्यानि
सुऽअपत्याय
सुऽअपत्ये
सुऽअपत्यै
पूर्वम्ऽअपरम्
अनपऽवृत्
अनपऽव्ययन्तः
परिऽअपश्यत्
सम्ऽअपश्यन्त
सुऽअपसः
विद्मनाऽअपसः
सरऽअपसः
नर्यऽअपसम्
तत्ऽअपसे
अनपऽस्फुरः
अनपऽस्फुरन्तीम्
अनपऽस्फुराम्
सुऽअपस्यते
सुऽअपस्यमानः
सुऽअपस्यया
सुऽअपस्या
सुऽअपाः
तत्ऽअपाः
सुऽअपाक्
अर्थःऽअपाष्टिः
अनपिऽनद्धम्
सुऽअपिवात
अनसम्

सुऽअप्नसः
अनप्नसः
दानऽअप्नसः
दीर्घऽअप्साः
सहस्रऽअप्साः
विश्वऽअप्सुम्
अभिऽअभि
अनभिऽद्रुहा
अवऽअभिनत्
शिवऽअभिमर्शनः
बहुलऽअभिमानः
अनभिम्लातऽवर्णः
अनभिऽशस्ता
सुऽअभिष्टयः
सुऽअभिष्टि
सुऽअभिष्टिः
सुऽअभिष्टिम्
स्वभिष्टिऽसुम्नः
अनभीशुः
सुऽअभीशुः
हिरण्यऽअभीशुः
दशाभीशुऽभ्यः
हिरण्यऽअभीशुम्
स्मदभीशू इति स्मत्ऽअभीशू
सुऽअभीशून्
परिऽअभूवन्
परिऽअभूषत्
निःऽअमन्थतम्
उत्ऽअमन्दिषुः
तृष्टऽअमया
स्तनयत्ऽअमाः
अनमीवः
अनमीवम्
अनमीवस्य
अनमीवाः
अनमीवाम्
अनमीवासः
त्र्यम्बकम्
उत्ऽअयत्

सुप्रऽअयनतमम्
आऽअयनम्
निऽअयनम्
निःऽअयनम्
पराऽअयनम्
विऽअयनम्
सुप्रऽअयनाः
उत्ऽअयनात्
आऽअयने
उपऽअयने
पराऽअयने
सम्ऽअयन्ते
अनवायम्
परिऽअयाः
आऽअये
उत्ऽअये
सम्ऽअयोधयः
सुऽअरंकृतेन
सम्ऽअरणम्
आऽअरणे
उपऽअरणे
सम्ऽअरणे
आऽअरणेषु
सम्ऽअरन्त
द्वादशऽअरम्
सम्ऽअराणः
सुऽअरिः
दशऽअरित्रः
सुऽअरित्राम्
नित्यऽअरित्राम्
शतऽअरित्राम्
कवऽअरिभ्यः
अकवऽअरिम्
अकवऽअरी
त्रिऽअरुणः
त्रिऽअरुणाय
त्रिऽअरुषीणाम्
उपऽअरे
सम्ऽअरे

पञ्चऽअरे
षट्ऽअरे
उक्थऽअर्काः
सुऽअर्काः
उत्ऽअर्के
सुऽअर्कैः
सहस्रऽअर्घम्
धनऽअर्चम्
शतऽअर्चसम्
सुऽअर्चिः
गोऽअर्णसः
धन्वऽअर्णसः
मधुऽअर्णसः
गोऽअर्णसम्
गोऽअर्णसा
गोऽअर्णसि
स्वादुःऽअर्णाः
अनुऽअर्तिता
अवर्तिम्
अवर्त्या
तूर्णिऽअर्थः
दूरेऽअर्थः
सुऽअर्थम्
निऽअर्थम्
सद्यःऽअर्थम्
कत्ऽअर्था
तदित्ऽअर्थाः
तूर्णिऽअर्थाः
समुद्रऽअर्थाः
निऽअर्थात्
निऽअर्थानि
कुचित्ऽअर्थिनम्
स्वर्थे इति सुऽअर्थे
प्रतिऽअर्धिः
प्रतिऽअर्धिम्
प्रऽअर्पणः
प्रऽअर्प्य
साधुऽअर्याः
अनर्शऽरातिम्

अनर्वणः
अनर्वणम्
अनर्वाणम्
अनर्वन्
अनर्वम्
अनर्वा
अनर्वाणः
अनर्वाणम्
अभिऽअर्षन्
विऽअल्कशा
उत्ऽअवता
उपऽअवति
अनवद्य
अनवद्यः
आरेऽअवद्यः
मिथःऽअवद्यपेभिः
अनवद्यम्
गुहत्ऽअवद्यम्
अनवद्यऽरूपाः
अनवद्यस्य
अनवद्या
अनवद्याः
अनवद्याभिः
अनवद्यासः
अनवद्यैः
दशावनिऽभ्यः
अपऽअवपः
अपऽअवपत्
अनवऽपृग्णा
अनवऽब्रवः
अनवभ्रऽराधसः
शतऽअवयम्
सम्ऽअवर्तयत्
सुऽअवसः
अनवसः
सुऽअवसम्
सुऽअवसा
उपऽअवसृज
निरवस्य

अनवऽस्यन्तः
अनवऽह्वरम्
अनवायम्
अतिऽअविः
प्रऽअविता
भर्गेऽअविता
प्रऽअवितारः
अनुऽअविन्दत्
त्रिऽअविम्
अतिऽअविम्
सम्ऽअविव्यक्
देवऽअवीः
प्रऽअवीः
सुप्रऽअवीः
सम्ऽअवृक्त
अपऽअवृणोः
अनुऽअवैत्
दुःप्रऽअव्यः
देवऽअव्यः
सुप्रऽअव्यः
देवऽअव्यम्
सुप्रऽअव्यम्
सुप्रऽअव्ये
साशनानशने इति
सम्ऽअशीत
अनश्नन्
अनश्रवः
चतुःऽअश्रिः
त्रिःऽअश्रिम्
चतुःऽअश्रिम्
शतऽअश्रिम्
अजऽअश्व
रोहित्ऽअश्व
रोहित्ऽअश्व
वाध्रिऽअश्व
श्यावऽअश्व
हरिऽअश्व
सुऽअश्वः
अनश्वः

वध्रिऽअश्वः
अजऽअश्वः
इष्टऽअश्वः
ऋज्रऽअश्वः
जीरऽअश्वः
निन्दितऽअश्वः
पृषत्ऽअश्वः
रोहित्ऽअश्वः
विऽअश्वः
श्यावऽअश्वः
सत्ऽअश्वः
सप्तऽअश्वः
संभृतऽअश्वः
हरिऽअश्वः
आश्वश्वऽतमाः
अनश्वऽदाम्
सुऽअश्वम्
अनश्वम्
अजऽअश्वम्
ऋज्रऽअश्वम्
जीरऽअश्वम्
द्रुवत्ऽअश्वम्
युक्तऽअश्वम्
विऽअश्वम्
शतऽअश्वम्
हरिऽअश्वम्
स्वश्वऽयुः
ऋज्रऽअश्वस्य
मारुतऽअश्वस्य
वध्रिऽअश्वस्य
वाध्रिऽअश्वस्य
श्यावऽअश्वस्य
हरिऽअश्वस्य
सुऽअश्वा
सुऽअश्वाः
अरुणऽअश्वाः
आशुऽअश्वाः
पिशङ्गऽअश्वाः
पीवःऽअश्वाः

पृषत्ऽअश्वाः
पृषत्ऽअश्वाः
पृषत्ऽअश्वान्
विऽअश्वान्
वध्रिऽअश्वाय
अघऽअश्वाय
हरिऽअश्वाय
सुऽअश्वासः
अनश्वासः
द्रोणिऽअश्वासः
पृषत्ऽअश्वासः
वैदत्ऽअश्विः
ऋज्रऽअश्वे
हरिऽअश्वेन
विऽअश्वेभ्यः
षट्ऽअश्वैः
आशुऽअश्व्यम्
सुऽअश्व्यम्
श्यावऽअश्व्यस्य
सुऽअश्व्या
असमष्टऽकाव्यः
निःऽअष्टाः
जरत्ऽअष्टिः
जरत्ऽअष्टिम्
सुऽअष्ट्रान्
हृत्सुऽअसः
परिऽअसर्पत
परिऽअसस्वजत्
गतऽअसुम्
अवऽअसृजः
उत्ऽअसृजः
अवऽअसृजत्
विऽअस्तः
अनस्थः
अनस्था
अधिऽअस्थाः
अधिऽअस्थात्
सम्ऽअस्थिथाः
सम्ऽअस्थिरन्

अस्मान्ऽअस्मान्
अस्मृतध्रु इत्यस्मृतऽध्रु
अस्मैऽअस्मै
अवऽअस्य
प्रऽअस्य
विऽअस्यन्
सम्ऽअस्वरन्
अहःऽअहः
अवऽअहन्
निःऽअहन्
प्रतिऽअहन्
विश्वाहा
पूर्वाह्णे
अह्नाऽअह्ना
तिरःऽअह्न्यम्
सम्ऽआकृणोषि
अनाकृतः
सम्ऽआकृतम्
अपऽआकृतिम्
द्वादशऽआकृतिम्
अनागसः
अनागसम्
उपऽआगहि
अनागाः
अनागाः
अनागाःऽत्वम्
अनागाःऽत्वे
अनागाःऽत्वेन
अनागान्
अनागाम्
सम्ऽआचक्रे
उत्ऽआचरत्
उपऽआचरत्
उपऽआचरेत्
उत्ऽआजत्
उत्ऽआजत
उपऽआजतु
उत्ऽआजन्
पृषत्ऽआज्यम्

सम्ऽआञ्जन्
सुऽआततः
सुऽआततम्
अनातुरम्
अनातुराः
शतऽआत्मा
शतऽआत्मानम्
दूरेऽआदिशम्
केवलऽआदी
दुःऽआधर्षम्
सुऽआधीः
दूरेऽआधीः
सुऽआधीभिः
अनाधृष्टः
अनाधृष्टम्
अनाधृष्टानि
अनाधृष्टाभिः
अनाधृष्टासः
अनाधृष्यम्
अनाधृष्या
अनाधृष्याः
दुःऽआध्यः
सुऽआध्यः
दुःऽआध्यम्
सुऽआध्यम्
दुःऽआध्ये
विऽआनः
सम्ऽआनजे
उत्ऽआनट्
अनानत
अनानतः
अनानतम्
अनानतस्य
अनानताः
विऽआनशिः
विऽआनशे
रीतिऽआपः
दुःऽआपना
रीतिऽआपा
अनापिः
देवऽआपिः
सुम्नेऽआपिः
देवऽआपिना
स्वापी इति सुऽआपी
देवऽआपे
सुऽआपे
अनाप्तः
अनाप्यम्
अनाभयिन्
अन्तरऽआभरः
सुऽआभुवः
अनाभुवः
सुऽआभुवम्
सुऽआभुवा
श्येनऽआभृतः
श्येनऽआभृतम्
उपऽआभृति
पुष्टिऽआमयी
अनामृणः
अभिऽआयंसेन्या
अनायतः
शम्ऽआयते
सम्ऽआयन्
अतिऽआयम्
सम्ऽआयमुः
विश्वऽआयवे
सुऽआयसम्
अतिऽआयातम्
उपऽआयातम्
अतिऽआयाहि
अग्रऽआयु
विश्वऽआयु
एकऽआयुः
क्षितऽआयुः
चित्रऽआयुः
दीर्घऽआयुः
विश्वऽआयुः
सुऽआयुजः
दीर्घायुऽत्वम्
दीर्घायुऽत्वाय
सुऽआयुध
सुऽआयुधः
तिग्मऽआयुधः
सुऽआयुधम्
सुऽआयुधस्य
सुऽआयुधाः
तिग्मऽआयुधाः
तिग्मऽआयुधाय
अनायुधासः
सुऽआयुधासः
तिग्मऽआयुधौ
विश्वायुऽपोषसम्
विश्वऽआयुम्
वृद्धऽआयुम्
अग्रऽआयुवः
दीर्घायुऽशोचिषम्
पूर्वऽआयुषम्
दीर्घऽआयुषम्
शतऽआयुषम्
शतऽआयुषा
अग्रऽआयुषे
शम्ऽआये
दीर्घायो इति दीर्घऽआयो
विश्वऽआयोः
उत्ऽआरः
सम्ऽआरत
अभिऽआरम्
अनारम्भणे
समाराणे इति सम्ऽआराणे
उत्ऽआरिथ
उपऽआरिम
शफऽआरुजः
शफऽआरुजम्
उपऽआरुहः
अनुऽआलेभिरे
सम्ऽआवर्तम्
परिऽआवर्ते

प्रतिऽआवर्तय
अभिऽआवर्तिने
अभिऽआवर्ती
सम्ऽआववर्ति
अनाविद्धया
परिऽआविवृत्सन्
अपऽआवृक्ताः
अनावृत्
दक्षिणाऽआवृतः
प्रावृतस्य
प्रावृताः
सुऽआवेशः
सुऽआवेशा
दुःऽआव्यम्
अनाशवः
सुऽआशितः
गोऽआशिरः
त्रिऽआशिरः
दधिऽआशिरः
यवऽआशिरः
रसऽआशिरः
गोऽआशिरम्
यवऽआशिरम्
सम्ऽआशिराम्
सुऽआशिषम्
दुःऽआशीः
अनाशीःऽदाम्
अनाशुना
प्राशुषाट्
अनाशोः
पुराऽआस
अनासः
सुऽआसः
चक्रम्ऽआसजः
अधिऽआसते
उपऽआसते
सम्ऽआसते
सुऽआसम्
स्वासस्थे इति सुऽआसस्थे

घृतऽआसुतिः
भूरिऽआसुतिः
सर्पिःऽआसुतिः
सर्पिःऽआसुतिम्
घृतासुती इति घृतऽआसुती
घृतासुती इति घृतऽआसुती
सर्पिरासुती इति सर्पिःऽआसुती
सर्पिःऽआसुते
सर्पिःऽआसुते
अनास्थाने
जुहुऽआस्यः
सप्तऽआस्यः
अश्मऽआस्यम्
सप्तऽआस्यम्
सप्तऽआस्ये
सप्तऽआस्येभिः
घृतऽआहवन
घृतऽआहवनम्
इष्कृतऽआहावम्
द्रोणऽआहावम्
सुऽआहुत
सुऽआहुतः
सोमऽआहुतः
सुऽआहुतम्
ऊर्जाऽआहुतिः
अनाहुतिम्
सम्ऽइङ्खयति
सम्ऽइत्
अप्रतिऽइत
अपरिऽइतः
अप्रतिऽइतः
उत्ऽइतः
निऽइतः
पराऽइतः
दुःऽइतम्
अपरिऽइतम्
अप्रतिऽइतम्
दुःऽइतम्
उपऽइतयः

धनऽइतयः
प्रतिऽइतये
दुःऽइतस्य
अप्रतिऽइतस्य
दुःऽइता
आऽइता
उत्ऽइता
अपरिऽइताः
सम्ऽइताः
दुःऽइतात्
दुःऽइतानि
सुविताय
दुःऽइताय
अपरिऽइतासः
आऽइतासः
उपऽइतिः
सम्ऽइतिः
अभिऽइतिम्
उत्ऽइतिम्
प्रऽइतिम्
सम्ऽइतिम्
अभिऽइतीः
सम्ऽइतीः
उत्ऽइते
अपिऽइतेः
दुःऽइतेभ्यः
अधिऽइतौ
आऽइतौ
उपऽइतौ
पराऽइतौ
समित्ऽभिः
अपिऽइत्य
अभिऽइत्य
आऽइत्य
प्रतिऽइत्य
प्रतीत्यम्
प्रतीत्येन
प्रातःऽइत्वः
प्रातःऽइत्वा

अधिऽइथ
सम्ऽइथा
सम्ऽइथानि
सम्ऽइथे
सम्ऽइथेषु
इदम्ऽइदम्
स्वऽइदुहव्यैः
अभिऽइद्धः
प्रऽइद्धः
सम्ऽइद्धः
देवऽइद्धम्
सम्ऽइद्धम्
सम्ऽइद्धस्य
सम्ऽइद्धाः
अभीद्धात्
सम्ऽइद्धे
देवऽइद्धेषु
सम्ऽइद्धेषु
सम्ऽइधः
सम्ऽइधम्
सम्ऽइधा
सम्ऽइधान्
सम्ऽइधानः
सम्ऽइधानम्
सम्ऽइधानस्य
सम्ऽइधाने
सम्ऽइधे
अनिध्मः
सुऽइध्मा
सम्ऽइध्यते
सम्ऽइध्यमानः
सम्ऽइध्यसे
सम्ऽइनक्षन्तः
उत्ऽइनक्षन्तम्
अनिनस्य
अनिन्द्रम्
इन्द्रम्ऽइन्द्रम्
अनिन्द्राः
अनिन्द्रान्
अनिन्द्राम्
अग्निम्ऽइन्धः
विश्वम्ऽइन्व
विश्वम्ऽइन्वः
विश्वम्ऽइन्वम्
विश्वम्ऽइन्वा
विश्वम्ऽइन्वाः
विश्वमिन्वे इति विश्वम्ऽइन्वे
विश्वम्ऽइन्वेभिः
स्मत्ऽइभम्
अधिऽइमसि
अधिऽइयति
उत्ऽइयर्षि
अनिराः
अनिराम्
अनिरेण
अंशाऽइव
अक्षराऽइव
अक्षीइवेत्यक्षीऽइव
अक्षेणऽइव
अग्निःऽइव
अग्निवान्ऽइव
अग्नेःऽइव
अग्नौऽइव
अग्रियाऽइव
अङ्कीऽइव
अजाऽइव
अञ्जःपाःऽइव
अञ्जसाऽइव
अतथाःऽइव
अत्यःऽइव
अत्यम्ऽइव
अत्याःऽइव
अत्यान्ऽइव
अत्रेःऽइव
अदितेःऽइव
अदुग्धाःऽइव
अधिऽइव
अध्वगौऽइव
अध्वरस्यऽइव
अध्वराऽइव
अनाशस्ताःऽइव
अन्धांसिऽइव
अन्यस्यऽइव
अन्याम्ऽइव
अपसाऽइव
अपाम्ऽइव
अपिऽइव
अपिहिताऽइव
अप्रशस्ताःऽइव
अभिवृताऽइव
अभीशून्ऽइव
अभ्रम्ऽइव
अभ्राऽइव
अभ्राणिऽइव
अभ्राताऽइव
अभ्रात्ऽइव
अभ्रियस्यऽइव
अभ्रियाऽइव
अमाऽइव
अमाजूःऽइव
अमृतात्ऽइव
अयाःऽइव
अयोद्धाऽइव
अरणाःऽइव
अराःऽइव
अरान्ऽइव
अरिताऽइव
अर्चाऽइव
अर्थम्ऽइव
अर्यमाऽइव
अर्वताऽइव
अर्वताम्ऽइव
अर्वान्ऽइव
अवतान्ऽइव
अवद्यम्ऽइव
अविताऽइव
अवीराम्ऽइव

क्षुद्राऽइव
क्षुम्पम्ऽइव
क्षेत्रम्ऽइव
क्षोणीःऽइव
क्षोत्रेणऽइव
खर्गलाऽइव
खृगलाऽइव
गन्धारीणाम्ऽइव
गर्तऽआरुगिव
गर्भःऽइव
गवाम्ऽइव
गाःऽइव
गातुयन्तिऽइव
गाम्ऽइव
गावःऽइव
गावाऽइव
गिरेःऽइव
गुहाऽइव
गृध्राऽइव
गोपाःऽइव
गोभिःऽइव
गोस्थात्ऽइव
गौःऽइव
गौराऽइव
गौरौऽइव
ग्रावाऽइव
ग्रावाणाऽइव
घनाऽइव
घर्माऽइव
घृणिऽइव
घृतम्ऽइव
घोषाऽइव
चक्रम्ऽइव
चक्रवाकाऽइव
चक्राऽइव
चक्रियाऽइव
चक्षुःऽइव
चक्षूंषिऽइव
चन्द्रमाःऽइव
चन्द्रम्ऽइव
चन्द्राऽइव
चमसाम्ऽइव
चम्विऽइव
चर्मऽइव
चर्मणीइवेति चर्मणीऽइव
चित्राऽइव
छायाऽइव
छायाम्ऽइव
जञ्झतीःऽइव
जनिधाःऽइव
जनीःऽइव
जन्मऽइव
जन्याऽइव
जयताम्ऽइव
जरणाऽइव
जरतीःऽइव
जायाऽइव
जारःऽइव
जारम्ऽइव
जारिणीऽइव
जीमूतस्यऽइव
जुजुवान्ऽइव
जूर्णाऽइव
जोष्टारःऽइव
तक्वीःऽइव
तळित्ऽइव
तनूत्यजाऽइव
तन्यतोःऽइव
तरन्तःऽइव
तष्टाऽइव
तस्कराःऽइव
तुविग्रीवाःऽइव
तोक्मऽइव
तोदस्यऽइव
त्रेधाऽइव
त्वष्टाऽइव
दक्षिणयाऽइव
दण्डाःऽइव
दधिक्रावाऽइव
दम्पतीइवेति दम्पतीऽइव
दामऽइव
दिवःऽइव
दिविऽइव
दिव्याऽइव
दिव्याःऽइव
दुघाःऽइव
दुर्मदाःऽइव
दूतम्ऽइव
दूताऽइव
दूर्वायाःऽइव
दृतेःऽइव
दृषदाऽइव
देवःऽइव
देवमानाऽइव
द्याम्ऽइव
द्यौःऽइव
द्रप्साःऽइव
द्रविणोदाःऽइव
द्रापिम्ऽइव
द्वाराऽइव
द्वौऽइव
धन्वऽइव
धन्वन्ऽइव
धर्मऽइव
धासिम्ऽइव
धिषणाऽइव
धीराऽइव
धुरिऽइव
धेनुःऽइव
धेनुम्ऽइव
धेनूःऽइव
ध्माताऽइव
नऽइव
नळाःऽइव
नद्याऽइव
नभ्याऽइव
नवस्वःऽइव

नष्टम्ऽइव
नाधमानाऽइव
नाभिःऽइव
नावम्ऽइव
नावाऽइव
नासत्याऽइव
नासाऽइव
निधयाऽइव
निधिम्ऽइव
निमिताऽइव
निम्नाऽइव
निम्नेनऽइव
निवनाऽइव
निष्ट्याःऽइव
नृतूःऽइव
नृत्यताम्ऽइव
नृपतीइवेति नृपतीऽइव
नैतोशाऽइव
नोधाःऽइव
पक्षाऽइव
पज्राऽइव
पणिनाऽइव
पतराऽइव
पतरौःऽइव
पतिःऽइव
पतिजुष्टाऽइव
पत्नीऽइव
पथाऽइव
पथ्याऽइव
पदाऽइव
पदेइवेति पदेऽइव
पयसाऽइव
परशुमान्ऽइव
परशोःऽइव
परश्वाऽइव
परिज्माऽइव
परिज्मानम्ऽइव
परिज्मानाऽइव
परिधीन्ऽइव
परिपदाम्ऽइव
परिपन्थीऽइव
परिवृक्ताऽइव
पर्जन्यःऽइव
पर्जन्यस्यऽइव
पर्णम्ऽइव
पर्णवीःऽइव
पर्वतःऽइव
पर्वतस्यऽइव
पर्वताःऽइव
पल्याऽइव
पशुःऽइव
पशुपाःऽइव
पश्वाऽइव
पात्रस्यऽइव
पात्राऽइव
पादाऽइव
पादौऽइव
पितराऽइव
पिताऽइव
पितुमतीऽइव
पितुमन्तम्ऽइव
पितुमान्ऽइव
पित्र्यस्यऽइव
पिप्युषीऽइव
पिशाःऽइव
पीप्यानाऽइव
पुत्रम्ऽइव
पुत्रायऽइव
पुरएताऽइव
पुरिऽइव
पुष्करिणीऽइव
पूताऽइव
पूर्वंगत्वाऽइव
पूर्वपाःऽइव
पूर्वान्ऽइव
पूर्वीऽइव
पूषाऽइव
पृक्षाःऽइव
पृथिवीम्ऽइव
पृष्ठाऽइव
प्रऽइव
प्रगर्धिनीऽइव
प्रघ्नताम्ऽइव
प्रजानतीऽइव
प्रतिचक्ष्यऽइव
प्रधीइवेति प्रधीऽइव
प्रधीन्ऽइव
प्रयःऽइव
प्रवताऽइव
प्रवासाऽइव
प्रस्नातीःऽइव
प्रस्फुरन्ऽइव
प्रायोगाऽइव
प्रीताःऽइव
बद्धम्ऽइव
बर्हिःऽइव
बाहुताऽइव
बिसखाःऽइव
बीजम्ऽइव
बृहतीइवेति बृहतीऽइव
बृहन्ताऽइव
ब्रह्मपुत्रःऽइव
ब्रह्माऽइव
ब्रह्माणाऽइव
भगःऽइव
भगम्ऽइव
भगस्यऽइव
भर्ताऽइव
भागम्ऽइव
भीःऽइव
भुरिजोःऽइव
भूमऽइव
भूषन्ऽइव
भ्राताऽइव
मंहनाऽइव
मघाऽइव

मण्डूकाःऽइव
मदन्ऽइव
मध्यमशीःऽइव
मनुषाऽइव
ममताऽइव
मर्यःऽइव
मरुताम्ऽइव
मर्यःऽइव
मर्याःऽइव
मर्यायऽइव
महान्ऽइव
महिषाऽइव
महिषाःऽइव
महिषान्ऽइव
महिषीऽइव
महीऽइव
मातराऽइव
माताऽइव
मातृमृष्टाऽइव
मानेनऽइव
मासाऽइव
मिताऽइव
मिताःऽइव
मित्रःऽइव
मित्रम्ऽइव
मित्राऽइव
मिथस्पृध्याऽइव
मीळ्हुष्मतीऽइव
मुक्षीजयाऽइव
मुनिःऽइव
मुष्टिहाऽइव
मृगाऽइव
मृगाःऽइव
मेताऽइव
मेधसातौऽइव
मेनेइवेति मेनेऽइव
मेषाऽइव
यत्ऽइव
यतीऽइव
यतीःऽइव
यथाऽइव
यन्ऽइव
यमाःऽइव
यमितवैऽइव
यमेइवेति यमेऽइव
यवम्ऽइव
यवसाऽइव
यह्वाःऽइव
याताऽइव
युगाऽइव
युजाऽइव
युधाऽइव
युध्यन्तःऽइव
युयुधिःऽइव
युवशाऽइव
यूथाऽइव
यूपाऽइव
योनाऽइव
योषाऽइव
रघुजाःऽइव
रघ्वीःऽइव
रथःऽइव
रथम्ऽइव
रथाःऽइव
रथान्ऽइव
रथियन्तीऽइव
रथीऽइव
रथीःऽइव
रथैःऽइव
रथ्याऽइव
रथ्याऽइव
रम्भिणीऽइव
रयिःऽइव
रयिम्ऽइव
रशनाम्ऽइव
रश्माऽइव
रश्मीन्ऽइव
रसाऽइव
रहसूःऽइव
राजपुत्राऽइव
राजाऽइव
राजानःऽइव
रुक्मःऽइव
रूपाऽइव
रेवान्ऽइव
रैवत्याऽइव
लिबुजाऽइव
वंशम्ऽइव
वंसगाऽइव
वक्ष्यन्तीऽइव
वत्सःऽइव
वत्सम्ऽइव
वधूःऽइव
वध्र्युःऽइव
वनाऽइव
वन्धुराऽइव
वपुषीऽइव
वप्राऽइव
वयःऽइव
वयाःऽइव
वयाम्ऽइव
वय्याऽइव
वराःऽइव
वरुणम्ऽइव
वर्मऽइव
वर्मीऽइव
वर्ष्यस्यऽइव
वसतौऽइव
वस्त्राऽइव
वस्त्रेणऽइव
वाःऽइव
वाजम्ऽइव
वाजयन्ऽइव
वाजाऽइव
वाजिनिऽइव
वाजीऽइव
वाणीःऽइव

वातःऽइव
वातम्ऽइव
वातस्यऽइव
वाताऽइव
वाताःऽइव
वायोःऽइव
वाशीऽइव
वाश्राऽइव
वाश्राःऽइव
वासयसिऽइव
विऽइव
विजःऽइव
विथुराऽइव
विदथानिऽइव
विदुष्याऽइव
विदुषीइवेति विदुषीऽइव
विधवाऽइव
विम्ऽइव
विशिखाःऽइव
विश्पतीइवेति विश्पतीऽइव
विश्याःऽइव
विश्वाऽइव
विषुद्रुहाऽइव
वृक्षाःऽइव
वृताऽइव
वृत्राऽइव
वृथाऽइव
वृषभस्यऽइव
वृषभाऽइव
वृषाऽइव
वृष्टिःऽइव
वृष्टिमान्ऽइव
वृष्टीऽइव
वृष्टेःऽइव
वेःऽइव
वेश्मऽइव
व्रजाऽइव
व्रततिःऽइव
व्रताऽइव

शंयूइवेति शंयूऽइव
शकटीःऽइव
शकुनस्यऽइव
शकुनाःऽइव
शतानीकाऽइव
शनकैःऽइव
शनैःऽइव
शफौऽइव
शमिताऽइव
शर्धांसिऽइव
शर्यहाऽइव
शाक्तस्यऽइव
शासुःऽइव
शिथिराऽइव
शीपालम्ऽइव
शुक्रःऽइव
शूरःऽइव
शूरस्यऽइव
शूराःऽइव
शृङ्गाऽइव
शृङ्गाणिऽइव
श्येनस्यऽइव
श्येनाऽइव
श्येनाःऽइव
श्येनान्ऽइव
श्येनौऽइव
श्रायन्तःऽइव
श्रुष्टीवाऽइव
श्रुष्टीवानाऽइव
श्रोष्टीऽइव
श्वघ्नीऽइव
श्वभ्राऽइव
श्वानाऽइव
संशिश्वरीःऽइव
सक्तुम्ऽइव
सखाऽइव
सद्मऽइव
सपत्नीःऽइव
सस्रिःऽइव

सस्रिम्ऽइव
सस्रीइवेति सस्रीऽइव
समनगाःऽइव
समनाऽइव
समनाऽइव
समितौऽइव
समुद्रःऽइव
समुद्रम्ऽइव
समुद्रस्यऽइव
समुद्रायऽइव
समृधाऽइव
सर्गम्ऽइव
सर्गान्ऽइव
सर्वताताऽइव
सवितःऽइव
ससताम्ऽइव
ससतीम्ऽइव
ससवांसम्ऽइव
सहस्रेणऽइव
साचीऽइव
साधारण्याऽइव
सामगाःऽइव
सारघाऽइव
सिंहम्ऽइव
सिंहाःऽइव
सिन्चतीःऽइव
सिन्धुःऽइव
सिन्धुम्ऽइव
सिन्धून्ऽइव
सिन्धोःऽइव
सिन्धौऽइव
सुदिनाऽइव
सुदुघाऽइव
सुदुघाम्ऽइव
सुदृशीऽइव
सुधिताऽइव
सुषिराम्ऽइव
सूर्यःऽइव
सूर्यम्ऽइव

सूर्यस्यऽइव
सूर्याऽइव
सूर्याःऽइव
सूर्याचन्द्रमसौऽइव
सूष्यन्त्याःऽइव
सृण्याऽइव
सेक्ताऽइव
सेनाऽइव
सोमःऽइव
सोमम्ऽइव
सोमस्यऽइव
सोमाःऽइव
स्कन्धांसिऽइव
स्तनयन्ऽइव
स्तनौऽइव
स्तुकाऽइव
स्तेनःऽइव
स्थाताराऽइव
स्थिराऽइव
स्थूणाऽइव
स्यूमऽइव
स्रुचाऽइव
स्रुचिऽइव
स्रुवाऽइव
स्वधितिःऽइव
स्वब्दीऽइव
स्वस्यऽइव
स्वेदाःऽइव
स्वेनऽइव
हंसाःऽइव
हंसैःऽइव
हंसौऽइव
हन्वाऽइव
हरिणौऽइव
हरीइवेति हरीऽइव
हस्ताऽइव
हस्तौऽइव
हस्ताऽइव
हारिद्रवाऽइव

हिताःऽइव
हितेनऽइव
हिमाऽइव
हिम्याऽइव
हिरण्यम्ऽइव
हिरण्यस्यऽइव
होताऽइव
ह्रदाःऽइव
गोऽइषः
नेमन्ऽइषः
सम्ऽइषः
गोऽइषः
प्रतिऽइषणिम्
तिग्मऽइषवः
क्षिप्रऽइषवे
इन्द्रऽइषितः
त्वाऽइषितः
देवऽइषितः
प्रऽइषितः
मर्त्यऽइषितः
युष्माऽइषितः
अश्वऽइषितम्
रजःऽइषितम्
शुनाऽइषितम्
इन्द्रऽइषिताः
प्रऽइषिताः
इन्द्रऽइषिताम्
इन्द्रेषिते इतीन्द्रऽइषिते
सुऽइषु
आसन्ऽइषून्
गोऽइषे
पशुऽइषे
अश्वम्ऽइष्टये
क्रन्दत्ऽइष्टये
गोऽइष्टये
भन्दत्ऽइष्टये
वस्यःऽइष्टये
स्मत्ऽइष्टाः
पश्वःऽइष्टिः

साधदिष्टिऽभिः
साधत्ऽइष्टिम्
गोऽइष्टिषु
अश्वम्ऽइष्टे
सुऽइष्टेन
आऽइष्टौ
गोऽइष्टौ
प्रतिऽइष्य
इहऽइह
इहेहऽमातरा
अस्तम्ऽईके
सम्ऽईके
निऽईक्षणम्
प्रऽईङ्खम्
समुद्रम्ऽईङ्खय
वाचम्ऽईङ्खयः
वाचम्ऽईङ्खयम्
प्रऽईङ्खे
समीची इति सम्ऽईची
सम्ऽईचीः
सम्ऽईचीनाः
सम्ऽईचीनासः
समीचीने इति सम्ऽईचीने
सम्ऽईच्योः
सम्ऽईजमानः
सम्ऽईधे
प्रतिऽईपम्
सम्ऽईयतुः
परिऽईयसे
परेयिऽवांसम्
पराऽईयुः
उपऽईयुषः
आऽईयुषीणाम्
आऽईयुषीम्
उत्ऽईरत्
उत्ऽईरते
उत्ऽईरयन्ति
उत्ऽईरयन्ती
उत्ऽईरयन्तीम्

श्रवःऽएषे
एषऽएष्या
अनेहः
अनेहसः
अनेहसम्
अनेहसा
अनेहा
निःऽएहि
निःऽऐतु
दुःऽओकम्
अगिराऽओकसः
तत्ऽओकसः
सम्ऽओकसः
दानऽओकसम्
तत्ऽओकसा
सम्ऽओकसा
तत्ऽओकसे
निऽओकसे
तत्ऽओकाः
निऽओकाः
सम्ऽओकाः
निऽओचनी
सुऽओजः
उत्ऽओजसः
धृष्णुऽओजसः
बाहुऽओजसः
तुविऽओजसम्
अभिभूतिऽओजसम्
उत्ऽओजसम्
धृष्णुऽओजसम्
वृष्टिऽओजसा
बाहुऽओजसा
सुऽओजाः
अभिभूतिऽओजाः
अमितऽओजाः
असमातिऽओजाः
ऋष्वऽओजाः
तत्ऽओजाः
बाहुऽओजाः
भूरिऽओजाः
विश्वऽओजाः
स्वभूतिऽओजाः
रथऽओळ्ह
दशऽओणये
दशऽओणिम्
दशऽओण्ये
विऽओदने
गोऽओपशा
विऽओम
विऽओमन्
विऽओमनः
विऽओमनि
दुरोषम्
दुरोषाः
दुरोषासः
सम्ऽओहम्
सम्ऽओहे
रेणुऽककाटः
त्रिऽककुप्
श्रुतऽकक्षः
उपऽकक्षासः
अपिऽकक्षे
अपिऽकक्षेभिः
अपिऽकक्ष्यम्
दशऽकक्ष्येभ्यः
सतीनऽकङ्कतः
प्रऽकङ्कताः
विऽकटे
त्रिऽकद्रुकेभिः
त्रिऽकद्रुकेषु
अभिऽकनिक्रदत्
अकनिष्ठासः
चतुःऽकपर्दा
दक्षिणतःऽकपर्दाः
अभयम्ऽकरः
आऽकरः
खजम्ऽकरः
यतम्ऽकरः
सत्राऽकरः
वनम्ऽकरणात्
सुऽकरम्
उभयम्ऽकरम्
काचित्ऽकरम्
इष्करम्
सुप्रऽकरस्नम्
आऽकरामहे
सुतेऽकरासः
आऽकरे
आश्रुत्ऽकर्ण
श्रुत्ऽकर्ण
कृधुऽकर्णी
श्रुत्ऽकर्णः
श्रुत्ऽकर्णम्
हिरण्यऽकर्णम्
अपिऽकर्णे
अष्टऽकर्ण्यः
इष्कर्त
अधिऽविकर्तनम्
निऽकर्तवे
इष्कर्ता
इष्कर्तारम्
इस्कर्तारम्
विश्वऽकर्मणा
भूरिऽकर्मणे
कर्मणिऽकर्मणि
कर्मन्ऽकर्मन्
विश्वऽकर्मन्
विश्वऽकर्मन्
वृषऽकर्मन्
सत्यऽकर्मन्
सुकर्मऽभिः
ऋतेऽकर्मम्
वीरऽकर्मम्
सुऽकर्मा
अकर्मा
विश्वऽकर्मा
साधुऽकर्मा

सुऽकर्माणः
विश्वऽकर्माणम्
विश्वऽकर्मेण
देवऽकर्मेभिः
अकामऽकर्शनः
अवऽकर्शयन्ति
अकल्पः
सम्ऽकल्पः
अकवाः
अकवाभिः
अकवारिम्
अकविषु
धारयत्कवी इति धारयत्ऽकवी
अकवेभिः
अकवैः
त्रिऽकशः
विऽकस्तम्
कामऽकातयः
ऋणऽकातिम्
पुत्रऽकाम
पुलुऽकामः
देवऽकामः
निऽकामः
यज्ञऽकामः
रायःऽकामः
अनुकामऽकृत्
निकामऽभिः
यथाऽकामम्
अनुऽकामम्
अपऽकामम्
प्रतिऽकामम्
निऽकामम्
श्रवःऽकामम्
सोमऽकामम्
त्वाम्ऽकामया
अनुऽकामा
देवऽकामा
निऽकामाः
गोऽकामाः
निऽकामाः
यत्कामाः
अन्नऽकामाय
क्षेमऽकामासः
निऽकामासः
पुत्रऽकामे
निऽकामैः
आऽकाय्यस्य
मेधाऽकारम्
ब्रह्मऽकाराः
हस्ऽकारात्
युत्ऽकारेण
असमष्टऽकाव्यः
प्रऽकाशः
सुऽकिंशुकम्
विऽकिल्बिषम्
देवऽकिल्बिषात्
ब्रह्मऽकिल्बिषे
सुऽकीर्तयः
सुऽकीर्तिः
सुऽकीर्तिम्
सुऽकीर्त्या
वीरऽकुक्षिम्
अकुत्र
पुरुऽकुत्सम्
इन्द्राकुत्सा
पुरुऽकुत्सानी
पुरुऽकुत्साय
पौरुऽकुत्सिम्
पौरुऽकुत्स्यः
पौरुऽकुत्स्यस्य
अकुध्र्यक्
प्रऽकुपितान्
अकुमारः
महाऽकुलः
आऽकूतिः
आऽकूत्या
अकूपारः
अकूपारस्य
तुविऽकूर्मिः
तुविकूर्मिऽतमः
तुविऽकूर्मिन्
तुविऽकूर्मिम्
इष्कृणुध्वम्
सम्ऽआकृणोषि
हिङ्ऽकृण्वती
आविःऽकृण्वतीम्
परिऽकृण्वन्
परिऽकृण्वन्ति
आविःऽकृण्वानः
आविःऽकृण्वाना
निःऽकृण्वानाः
अनुकामऽकृत्
अभिष्टिऽकृत्
आजिऽकृत्
ईशानऽकृत्
ऋषिऽकृत्
खजऽकृत्
ज्योतिःऽकृत्
तनूऽकृत्
पथिऽकृत्
पुरुऽकृत्
प्रशस्तिऽकृत्
भद्रऽकृत्
लोकऽकृत्
वयःऽकृत्
वरिवःऽकृत्
विजेषऽकृत्
सुऽकृत्
स्तेयऽकृत्
स्योनऽकृत्
उरुऽकृत्
खजऽकृत्
पुरुऽकृत्
रणऽकृत्
सहःऽकृत
सद्यःऽकृत
अरम्ऽकृतः

ईशानऽकृतः
ज्योतिःऽकृतः
दुःऽकृतः
दुघ्रऽकृतः
धान्यऽकृतः
ब्रह्मऽकृतः
यज्ञनिःऽकृतः
वयःऽकृतः
सुऽकृतः
हविःऽकृतः
अरम्ऽकृतः
परिऽकृतः
संस्कृतः
सहःऽकृतः
सुऽकृतः
अरम्ऽकृतम्
दुःऽकृतम्
मिथुऽकृतम्
सुऽकृतम्
हविःऽकृतम्
दुःऽकृतम्
निःऽकृतम्
यथाऽकृतम्
संस्कृतम्
अकृतम्
अनिःऽकृतम्
अन्यऽकृतम्
देवऽकृतम्
निःऽकृतम्
परिऽकृतम्
मर्त्यऽकृतम्
वषट्ऽकृतम्
विऽकृतम्
सम्ऽआकृतम्
सहःऽकृतम्
सुऽकृतम्
स्वाहाऽकृतम्
देवऽकृतस्य
सुऽकृतस्य

परिऽकृतस्थ
वषट्ऽकृतस्य
स्वाहाऽकृतस्य
ब्रह्मऽकृता
सुऽकृता
अकृता
सुऽकृता
इषुकृताऽइव
अरम्ऽकृताः
वषट्ऽकृताः
सुऽकृताः
अकृतात्
दुःऽकृतानि
सुऽकृतानि
मत्ऽकृतानि
विऽकृतानि
स्वाहाऽकृतानि
मन्त्रऽकृताम्
सुऽकृताम्
इष्कृतासः
परिऽकृतासः
वषट्ऽकृति
हविःऽकृति
अरम्ऽकृतिः
आऽकृतिः
इष्कृतिः
हस्कृतिः
निःऽकृतिम्
ब्रह्मऽकृतिम्
वषट्ऽकृतिम्
स्वाहाऽकृतिम्
हविःऽकृतिम्
निःऽकृतीः
स्वाहाऽकृतीषु
अरम्ऽकृते
दुःऽकृते
धर्मऽकृते
ब्रह्मऽकृते
सुऽकृते

अकृते
आऽकृते
कुहयाऽकृते
अन्यऽकृतेन
सुऽअरंकृतेन
सहःऽकृतेन
अन्यऽकृतेभ्यः
सुऽकृतोः
अदुःऽकृतौ
सुकृत्ऽतमाः
सुकृत्ऽतरः
सुकृत्ऽतराय
अकृत्तऽरुक्
पितृकृत्ऽतरेभ्यः
लोकऽकृत्नुम्
सुरूपऽकृत्नुम्
तनूकृत्ऽभ्यः
पथिकृत्ऽभ्यः
अस्खलीकृत्य
अरम्ऽकृत्य
विऽकृत्य
अननुऽकृत्यम्
सुऽकृत्यया
अननुऽकृत्या
सुऽकृत्या
वाजऽकृत्येषु
सुऽकृत्वनि
सुऽकृत्वने
पुरुऽकृत्वा
म्रक्षऽकृत्वा
निऽकृत्वानः
सुकृत्ऽसु
तनूऽकृथे
पुत्रऽकृथे
पुत्रऽकृथेषु
ऊर्ध्वऽकृशनम्
अकृषिऽवलाम्
विश्वऽकृष्टयः
विश्वऽकृष्टिः

विश्वऽकृष्टिम्
विश्वऽकृष्टीः
प्रऽकेतः
सुऽप्रकेतः
अप्रऽकेतम्
प्रऽकेतम्
सुऽप्रकेतम्
सुऽकेतवः
धूमऽकेतवः
अकेतवे
अज्ञातऽकेताः
सऽकेताः
धूमऽकेतुः
यज्ञऽकेतुः
धूमऽकेतुना
धूमऽकेतुम्
बृहत्ऽकेतुम्
भासाऽकेतुम्
सहस्रऽकेतुम्
सुऽप्रकेतेभिः
प्रऽकेतैः
सुऽप्रकेतैः
महिऽकेरवः
हरिऽकेश
शोचिःऽकेशः
हरिऽकेशः
हिरण्यऽकेशः
घृतऽकेशम्
शोचिःऽकेशम्
हरिऽकेशम्
वृक्षऽकेशाः
वायुऽकेशान्
हिरण्यऽकेश्या
अंसत्रऽकोशम्
यामऽकोशाः
वनऽक्रक्षम्
अवऽक्रक्षिणम्
पीतऽक्रतः
सुऽक्रतवः

सऽक्रतवः
ह्वेषऽक्रतवः
पूतऽक्रतायै
ऋजुऽक्रतुः
सुऽक्रतुः
अक्रतुः
अदब्धऽक्रतुः
अमितऽक्रतुः
कविऽक्रतुः
वृषऽक्रतुः
शतऽक्रतुः
सऽक्रतुः
विभुऽक्रतुम्
सुऽक्रतुम्
अदब्धऽक्रतुम्
अद्भुतऽक्रतुम्
अवार्यऽक्रतुम्
कविऽक्रतुम्
शतऽक्रतुम्
सुक्रतुऽयया
सुक्रतुऽयसे
सुक्रतुऽया
सुक्रतू इति सुऽक्रतू
अद्भुतक्रतू इत्यद्भुतऽक्रतू
शतक्रतू इति शतऽक्रतू
सक्रतू इति सऽक्रतू
सुक्रतू इति सुऽक्रतू
अक्रतून्
अभिऽक्रतूनाम्
अविहर्यतक्रतो इत्यविहर्यतऽक्रतो
कविक्रतो इति कविऽक्रतो
तुविक्रतो इति तुविऽक्रतो
वरेण्यक्रतो इति वरेण्यऽक्रतो
वृषक्रतो इति वृषऽक्रतो
शतक्रतो इति शतऽक्रतो
शतक्रतो इति शतऽक्रतो
संभृतक्रतो इति संभृतऽक्रतो
सुक्रतो इति सुऽक्रतो
सुक्रतो इति सुऽक्रतो

पूतऽक्रतौ
शतऽक्रत्वः
अभिऽक्रन्दन्
सम्ऽक्रन्दनः
सम्ऽक्रन्दनेन
शुचिऽक्रन्दम्
पर्जन्यऽक्रन्द्यम्
उरुऽक्रमः
निऽक्रमणम्
विऽक्रमणम्
विऽक्रमणेषु
उरुऽक्रमस्य
उरुऽक्रमा
अतिऽक्रमे
अभिऽक्रम्य
अक्रविऽहस्ताः
दधिऽक्राः
दधिऽक्राम्
रुधिऽक्राम्
अवऽक्रामन्तः
दधिऽक्रावा
दधिऽक्रावाणम्
दधिऽक्राव्णः
प्रऽक्रीळान्
प्रऽक्रीळिनः
अविऽक्रीतः
मित्रऽक्रुवः
सुतऽक्रे
परिऽक्रोशम्
सम्ऽक्रोशमानाः
अक्षतः
अभिऽक्षत्तारः
अभिऽक्षत्तः
चित्रऽक्षत्र
सुऽक्षत्र
सुऽक्षत्रः
सुपारऽक्षत्रः
सुऽक्षत्रम्
स्वऽक्षत्रम्

प्रियऽक्षत्राः
सुऽक्षत्रान्
स्वऽक्षत्राय
सुऽक्षत्रासः
देवऽक्षत्रे
स्वऽक्षत्रेभिः
महिऽक्षत्रौ
वर्षिष्ठऽक्षत्रौ
बाहुऽक्षदः
अभिऽक्षदाम्
स्वादुऽक्षद्मा
अन्तरिक्षम्
तुविऽक्षम्
सुऽक्षयम्
दिविऽक्षयम्
उरुऽक्षयाः
रथऽक्षयाणि
उरुऽक्षयेषु
अनुऽक्षरन्ति
अभिऽक्षरन्ति
अक्षरम्
अक्षरा
अक्षरा
अक्षराणाम्
अक्षरे
अक्षरेण
अन्तरिक्षस्य
अन्तरिक्षा
ऋभुक्षाः
अन्तरिक्षाणि
अन्तरिक्षात्
द्यावाक्षामा
द्यावाक्षामा
आऽक्षित्
अक्षितऽऊतयः
अक्षितऽऊतिः
अक्षितऽऊतिम्
अप्सुऽक्षितः
उपऽक्षितः
सुऽक्षितः
अधिऽक्षितः
अधिऽक्षितम्
अक्षितम्
अनुपऽक्षितम्
अप्रऽक्षितम्
अविऽक्षितम्
आऽक्षितम्
सुऽक्षितयः
सुऽक्षितये
अक्षितऽवसुम्
गैरिऽक्षितस्य
दिविऽक्षिता
परिऽक्षिता
अक्षिता
अविऽक्षितासः
अक्षिति
उरुऽक्षितिम्
सुऽक्षितिम्
धारयत्ऽक्षितिम्
धारयत्क्षिती इति धारयत्ऽक्षिती
सुऽक्षितीः
सुऽक्षितीनाम्
गिरिऽक्षिते
अक्षिते
परिऽक्षितोः
सुऽक्षितौ
उरुऽक्षितौ
बन्धुक्षित्ऽभ्यः
अभिऽक्षिपन्
अवऽक्षिपन्
उपऽक्षियन्तः
प्रतिऽक्षियन्तम्
अक्षियन्तम्
अधिऽक्षियन्ति
अक्षीयमाणम्
अक्षीयमाणा
पुरुऽक्षुः
पुरुऽक्षुम्
अन्तरिक्षे
अन्तरिक्षेण
उपऽक्षेतारः
उपऽक्षेति
अक्षेत्रऽवित्
सुऽक्षेत्रा
सुऽक्षेत्रिया
योगऽक्षेमम्
ध्रुवऽक्षेमा
ध्रुवऽक्षेमाः
ध्रुवऽक्षेमासः
पुरुक्षो इति पुरुऽक्षो
पुरुऽक्षोः
सुऽखः
अखनन्तः
सुऽखम्
आऽखरे
अखर्वम्
निऽखातम्
अमित्रऽखादः
अवऽखादः
प्रऽखादः
वृत्रऽखादः
वृत्रऽखादम्
सुऽखादयः
वृषऽखादयः
शुभ्रऽखादयः
सुऽखादये
विऽखादे
सुऽखे
सुऽखेषु
सुऽखैः
अभिऽख्या
अभिऽख्याता
अभिऽख्याय
प्रऽख्यै
विऽख्यै
अग्रेऽगः
वंसगः

सुऽगः
अभिऽगच्छति
संगच्छमाने इति सम्ऽगच्छमाने
निऽगच्छात्
मरुत्ऽगण
मरुत्ऽगणः
सऽगणः
सुमत्ऽगणः
गणम्ऽगणम्
सर्वःऽगणम्
मरुत्ऽगणाः
वृषऽगणाः
मरुत्ऽगणे
द्युऽगत्
सम्ऽगता
आऽगताः
पराऽगताः
निऽगतान्
सम्ऽगतानि
आऽगतायाम्
सम्ऽगतासः
सम्ऽगतिम्
आऽगतेन
आऽगतौ
अवऽगत्य
आऽगत्य
परिऽगत्य
सम्ऽगत्य
सम्ऽगत्याम्
पूर्वंगत्वाऽइव
सम्ऽगथे
अगदम्
विऽगदेषु
आऽगधिता
परिऽगधिता
उपऽगन्तवै
पुण्यऽगन्धाः
धूमऽगन्धिः
सुऽगन्धिना

सुऽगन्धिम्
आञ्जनऽगन्धिम्
वाजऽगन्ध्यम्
सुऽगभस्तयः
सुऽगभस्तिः
स्यूमऽगभस्तिः
पूर्णऽगभस्तिम्
सुऽगभस्तिम्
स्यूमऽगभस्तिम्
दुःऽगम्
फलिऽगम्
सुऽगम्
आऽगमत्
आऽगमन्
सम्ऽगमनः
सम्ऽगमनम्
सम्ऽगमनी
मक्षुम्ऽगमाभिः
सम्ऽगमामहै
अरम्ऽगमाय
आऽगमिष्ठः
आऽगमिष्ठा
आऽगमिष्ठाः
सम्ऽगमे
सम्ऽगमेषु
शम्ऽगयः
महाऽगयम्
शम्ऽगयीम्
अधिऽगर्त्यस्य
प्रऽगर्धिनः
प्रगर्धिनीऽइव
हिरण्यऽगर्भः
अर्धऽगर्भाः
कृष्णऽगर्भाः
पृश्निऽगर्भाः
चित्तऽगर्भासु
सुऽगवः
पुरःऽगवः
रुशत्ऽगवि

पुरःऽगवी
सम्ऽगवे
अभिऽगवे
सुऽगव्यम्
अगव्यूति
पुरःऽगव्यूति
उरुऽगव्यूतिः
दुःऽगहस्य
दुःऽगहा
दुःऽगहानि
उपऽआगहि
द्यौःऽगहे
दुःऽगा
सुऽगा
पुरःऽगाः
समनऽगाः
सुऽगाः
समनगाःऽइव
दुःऽगात्
तुरऽगातु
अरिष्टऽगातुः
सुगातुऽया
गात्रेऽगात्रे
ऋजुऽगाथ
सुऽगाधा
सुऽगान्
पृथुऽप्रगानम्
दुःऽगानि
सुऽगानि
तमःऽगाम्
सामऽगाम्
स्वस्तिऽगाम्
विगामऽभिः
उरुऽगाय
उरुऽगायः
उरुऽगायम्
अनुऽगायसम्
उरुऽगायस्य
उरुऽगाया

अतिथिऽग्वम्
दशऽग्वम्
अतिथिऽग्वस्य
एतऽग्वा
एतऽग्वाः
दशऽग्वाः
नवऽग्वाः
अतिथिऽग्वाय
दशऽग्वासः
नवऽग्वासः
दशऽग्विनः
शतऽग्विनः
शतऽग्विनम्
आतिथिऽग्वे
दशऽग्वे
नवऽग्वे
दशऽग्वैः
नवऽग्वैः
द्रुऽघनम्
निऽघनिघ्नते
विऽघनिना
अनुऽघुष्य
आघृणिः
आघृणे
आघृणे
विघृते इति विऽघृते
अघोरऽचक्षुः
आऽघोषते
आऽघोषन्
निऽघोषयः
निऽघोषयन्
आऽघोषयन्तः
असुरऽघ्नः
वृत्रऽघ्नः
हस्तऽघ्नः
अपुरुषऽघ्नः
अघ्नतः
अघ्नता
प्रघ्नताम्ऽइव

अवऽघ्नती
अघ्नते
अपऽघ्नन्
विऽघ्नन्
अपऽघ्नन्तः
विऽघ्नन्तः
अभिऽप्रघ्नन्ति
प्रतिऽघ्नन्ति
गोऽघ्नम्
पुरुषऽघ्नम्
अश्वऽघ्नस्य
दस्युऽघ्ना
वृत्रऽघ्ना
सुऽघ्नाय
वृत्रऽघ्नी
श्वऽघ्नी
सपत्नऽघ्नी
अपतिऽघ्नी
पारावतऽघ्नीम्
असुरऽघ्ने
अहिऽघ्ने
नृऽघ्ने
पर्णयऽघ्ने
वृत्रऽघ्ने
अहिऽघ्ने
अघ्न्यम्
अघ्न्यस्य
अघ्न्या
अघ्न्या
अघ्न्याः
अघ्न्याः
अघ्न्यानाम्
अघ्न्याभ्यः
अघ्न्याम्
अघ्न्यायाः
अघ्न्यायाः
अघ्न्ये
अघ्न्यौ
सम्ऽचक्रानः

आऽचक्रे
विऽचक्र
त्रिऽचक्रः
अनुऽचक्रदे
अचक्रम्
त्रिऽचक्रम्
सुऽचक्रम्
अश्मऽचक्रम्
उच्चाऽचक्रम्
एकऽचक्रम्
शतऽचक्रम्
सप्तऽचक्रम्
विऽचक्रमाणः
विऽचक्रमे
उरुऽचक्रयः
अचक्रया
निऽचक्रया
रोधऽचक्राः
आऽचक्राणः
प्रऽचक्राणम्
हिरण्यऽचक्रान्
उरुऽचक्रिः
आऽचक्रिः
अचक्रे इति
आऽचक्रे
उरुऽचक्रे
सुऽचक्रे
सप्तऽचक्रे
त्रिऽचक्रेण
अचक्रेभिः
प्रवत्ऽचक्रेषु
नृऽचक्षः
विश्वऽचक्षः
विऽचक्षण
विऽचक्षणः
विऽचक्षणम्
विऽचक्षणा
प्रतिऽचक्षणाय
सुऽप्रतिचक्षम्

अमीवऽचातनीः
निऽचाय्य
व्रतऽचारिणः
विऽचारिणि
ब्रह्मऽचारी
सम्ऽचिकित्वान्
आऽचिकेतत्
निऽचिक्यत्
ऋणऽचित्
ऋतऽचित्
मनःऽचित्
विपःऽचित्
ऋतऽचित्
कूऽचित्
अचितः
विपःऽचितः
सुऽचितः
हुरःऽचितः
निऽचितः
अचितम्
विपःऽचितम्
हुरःऽचितम्
आऽचितम्
आऽचिता
विपःऽचिता
विपःऽचिताम्
अर्पऽचितिम्
अचित्ते
विपःऽचिते
अचित्तम्
पूर्वऽचित्तये
अचित्तात्
अचित्तान्
अचित्तिः
अचित्तिऽभिः
अचित्तिम्
अचित्ती
अचित्रम्
अर्णाचित्ररथा

दानुऽचित्राः
अचित्रे
विऽचिनोति
विऽचिन्वन्
निऽचिरा
निऽचिराभ्याम्
निऽचिरासः
आऽचुच्युवीमहि
धुनीचुमुरी इति
निऽचुम्पुणः
विऽचृतम्
सम्ऽचृतम्
विऽचृत्ताः
प्रचेत इति प्रऽचेतः
प्रऽचेतः
पुरुऽचेतनः
अविऽचेतनानि
प्रऽचेतयन्
सुऽचेतसः
अचेतसः
अप्रऽचेतसः
अविऽचेतसः
प्रऽचेतसः
प्रऽचेतसः
विऽचेतसः
विऽचेतसः
सऽचेतसः
सुऽप्रचेतसः
सुऽचेतसम्
अचेतसम्
प्रऽचेतसम्
विऽचेतसम्
सऽचेतसम्
गम्भीरऽचेतसा
प्रऽचेतसा
प्रऽचेतसा
वत्सऽप्रचेतसा
विऽचेतसा
सऽचेतसा

प्रऽचेतसे
अचेताः
अप्रऽचेताः
दभ्रऽचेताः
प्रऽचेताः
विऽचेताः
सऽचेताः
सहस्रऽचेताः
अचेतानस्य
निऽचेतारः
निऽचेतारा
सुऽचेतुनम्
सुऽचेतुना
प्रऽचेतुने
निऽचेरुः
रध्रऽचोदः
अचोदते
ऋषिऽचोदनः
रध्रऽचोदनः
कीरिऽचोदनम्
रध्रऽचोदनम्
ब्रह्मऽचोदनीम्
प्रऽचोदय
प्रऽचोदयन्
प्रऽचोदयन्ता
प्रऽचोदयात्
अचोदसः
वातऽचोदितः
दुःऽच्यवनः
दुःऽच्यवनेन
अपऽच्यवम्
उपऽच्यवम्
प्रऽच्यवयन्तः
तुषुऽच्यवसः
भुवनऽच्यवानाम्
प्रतिऽच्यवीयसी
अच्युतऽच्युत्
मधुऽच्युत्
अच्युतऽच्युत्

धन्वऽच्युतः
ध्रुवऽच्युतः
पर्वतऽच्युतः
मदऽच्युतः
अच्युतः
अनपऽच्युतः
प्रऽच्युतः
बाहुऽच्युतः
मदऽच्युतः
शफऽच्युतः
अच्युतऽच्युत्
अच्युतऽच्युत्
ऋणऽच्युतम्
तुषुऽच्युतम्
मदऽच्युतम्
अच्युतम्
अनपऽच्युतम्
मदऽच्युता
अच्युता
अनपऽच्युता
मदऽच्युता
अच्युताः
विऽच्युताः
वृषऽच्युताः
अच्युतानाम्
अच्युतानि
अप्रऽच्युतानि
मदऽच्युति
हस्तऽच्युती
पर्वतऽच्युते
हस्तऽच्युतेभिः
प्रथमऽच्छत्
कविऽछदा
सहऽछन्दसः
सुच्छर्दिःऽतमे
अच्छायः
उखऽछित्
अच्छिद्यमानया
अच्छिद्रऽऊतिः

अच्छिद्रऽऊध्नी
अच्छिद्रम्
अच्छिद्रस्य
अच्छिद्रा
अच्छिद्राः
अच्छिन्नऽपत्राः
परिऽछिन्नाः
अच्छेदि
एकऽज
कृष्णऽजंहसः
रघुपत्मऽजंहाः
अजः
अतृष्णऽजः
अस्वप्नऽजः
तृष्णऽजः
आऽजगन्थ
आऽजगन्वान्
निःऽजगन्वान्
आऽजगाम
सम्ऽजग्मानः
सम्ऽजग्मानासु
उपऽजग्मुषः
उपऽजग्मुषे
पृथुऽजघने
निऽजघन्थ
निऽजघ्निः
अजघ्नुषी
अपऽजघ्नत्
अप्रऽजज्ञयः
प्रजज्ञिऽवान्
प्रऽजज्ञे
अधिऽजज्ञे
वाजऽजठरः
यातयत्ऽजनः
प्रऽजननम्
जनम्ऽजनम्
यातयत्ऽजनम्
सम्ऽजनयन्ति
यातयत्ऽजना

देवऽजनाः
सुऽजनिमा
सुऽजनिमानः
आऽजनिष्ठाः
जनेऽजने
जन्मन्ऽजन्मन्
शुचिऽजन्मनः
स्वऽजन्मना
सुजन्मनी इति सुजन्मनी
द्विऽजन्मा
भूरिऽजन्मा
द्विऽजन्मानः
भ्राजत्ऽजन्मानः
शुचिऽजन्मानः
द्विऽजन्मानम्
पाञ्चऽजन्यः
विश्वऽजन्यः
पाञ्चऽजन्यम्
विश्वऽजन्यम्
पाञ्चऽजन्यया
विश्वऽजन्या
सऽजन्या
विश्वऽजन्याः
प्रतिऽजन्यानि
विश्वऽजन्याम्
पाञ्चऽजन्यासु
विश्वजन्ये इति विश्वऽजन्ये
पाञ्चऽजन्येन
आऽजभार
एकऽजम्
तृष्णऽजम्
पलस्तिऽजमदग्नयः
विश्वामित्रजमदग्नी इति
तपुःऽजम्भ
तिग्मऽजम्भ
सुऽजम्भः
तपुःऽजम्भः
तिग्मऽजम्भः
वीळुऽजम्भम्

तपुःऽजम्भस्य
तिग्मऽजम्भस्य
तिग्मऽजम्भाय
धनम्ऽजय
धनम्ऽजयः
आऽजयन्
सम्ऽजयन्
विऽजयन्ते
धनम्ऽजयम्
प्रऽजया
सम्ऽजया
मुक्षीजयाऽइव
विऽजयाय
अजर
अजरः
अजरम्
अजरयू इति
आऽजरसाय
अजरा
अजराः
अजराणि
ज्योतिःऽजरायुः
अजरासः
अजरे इति
अजरेभिः
अजरेभ्यः
अजरैः
अजरौ
अपऽजर्गुराणः
परिऽजर्भुराणः
सम्ऽजर्भुराणः
विऽजर्भृतः
धीऽजवः
प्रऽजवः
मक्षुजवःऽतमा
धीऽजवनः
धीऽजवनम्
धीऽजवना
अजवसः

मनःऽजवसा
मनःऽजवाः
मनःऽजवेभिः
मनःऽजवेषु
अजस्य
अजस्र
अजस्रः
अजस्रम्
अजस्रया
अजस्रा
अजस्राः
अजस्रेण
अजस्रैः
प्रऽजह्रितानि
पुराऽजा
प्रऽजा
सनऽजा
सनऽजा
अद्रिऽजाः
अप्ऽजाः
अप्सुऽजाः
ऋतऽजाः
ऋतेऽजाः
गिरिऽजाः
गोऽजाः
दिवःऽजाः
दिविऽजाः
देवऽजाः
द्विऽजाः
नभःऽजाः
नवऽजाः
पुराऽजाः
पूर्वऽजाः
प्रऽजाः
प्रथमऽजाः
प्रवातेऽजाः
मनुष्यऽजाः
वनेऽजाः
सनऽजाः

सनःऽजाः
सहऽजाः
सहःऽजाः
सुऽप्रजाः
स्वऽजाः
स्वयम्ऽजाः
रघुजाःऽइव
ऋतऽजात
ऋतऽजात
तुविऽजात
प्रियऽजात
सुऽजात
ऋतऽप्रजात
सुऽजात
हरिऽजात
तुविऽजातः
पुरुऽजातः
आऽजातः
ऋतऽजातः
जातःऽजातः
नवऽजातः
प्रऽजातः
सुऽजातः
सुऽजातता
सुऽजातम्
अन्यऽजातम्
नवऽजातम्
प्रऽजातम्
मनुऽजातम्
वीरऽजातम्
सुऽजातम्
ऋतऽजातया
तुविऽजातयोः
अजातऽशत्रुः
अजातऽशत्रुम्
ऋतजातऽसत्याः
तुविऽजातस्य
पुरुऽप्रजातस्य
ऋतऽजातस्य

देवऽजातस्य
नवऽजातस्य
सुऽजाता
आऽजाता
सुऽजाता
तुविऽजाताः
सुऽजाताः
ऋतऽजाताः
गोऽजाताः
तुविऽजाताः
देवऽजाताः
वामऽजाताः
सुऽजाताः
सुऽजाताः
सुऽजाताः
सुऽजातान्
सुऽजातान्
अजातान्
ऋतऽप्रजाताम्
देवऽजाताय
सुऽजाताय
सुऽजातासः
सुऽजाते
सुऽजाते
तुविऽजातौ
सुऽजात्यम्
सुऽजात्यस्य
असजात्या
सुऽजात्यानाम्
सुऽजात्ये
सुऽजात्येन
तपःऽजान्
प्रतिऽजानते
प्रऽजानन्
विऽजानन्
अविऽजानन्
भद्रऽजानयः
सुमत्ऽजानये
विऽजानात्

सम्ऽजानानाः
साकम्ऽजानाम्
द्विऽजानिः
युवऽजानिः
वित्तऽजानिम्
आऽजानीः
विऽजानुषः
सहऽजानुषाणि
प्रऽजाभिः
प्रऽजाभ्यः
अग्रऽजाम्
अप्ऽजाम्
नभःऽजाम्
पुराऽजाम्
प्रऽजाम्
प्रथमऽजाम्
भरेषुऽजाम्
स्वऽजाम्
विऽजामन्
अजामयः
सप्तऽजामयः
सोमऽजामयः
विऽजामातुः
अजामि
देवऽजामिः
अजामिऽभिः
अजामिम्
अजामीन्
विऽजामीन्
उपऽजायते
विऽजायते
अभिऽजायन्त
ब्रह्मऽजाया
प्रऽजायाः
ब्रह्मऽजायाम्
प्रऽजायै
पूर्वजावरी इति पूर्वऽजावरी
प्रऽजासु
प्रऽजिगतः

आऽजिगाति
सम्ऽजिगीवान्
अभिजिघ्रन्ती इत्यभिऽजिघ्रन्ती
अप्ऽजित्
अप्सुऽजित्
अश्वऽजित्
गोऽजित्
धनऽजित्
रण्यऽजित्
रथऽजित्
विश्वऽजित्
संसृष्टऽजित्
सत्राऽजित्
समर्यऽजित्
सहस्रऽजित्
स्वःऽजित्
हिरण्यऽजित्
सहस्रऽजित्
गोऽजितः
ग्रामऽजितः
सत्राऽजितः
सम्ऽजितः
प्रातःऽजितम्
श्रवःऽजितम्
सम्ऽजितम्
स्वःऽजितम्
अपराऽजितम्
गोऽजिता
अपराऽजिता
पराऽजितासः
पुरःऽजिती
अप्ऽजिते
अश्वऽजिते
उर्वराऽजिते
गोऽजिते
धनऽजिते
नृऽजिते
विश्वऽजिते

सत्राऽजिते
स्वःऽजिते
सुऽजित्वरीः
सऽजित्वानम्
सऽजित्वाना
धियम्ऽजिन्वः
धियम्ऽजिन्वम्
धियम्ऽजिन्वा
विश्वऽजिन्वा
धियम्ऽजिन्वासः
पर्जन्यऽजिन्विताम्
अजिरऽशोचिषः
सम्ऽजिहानम्
उत्ऽजिहानाः
सुऽजिह्व
सुऽजिह्वः
मधुऽजिह्वः
मन्द्रऽजिह्वः
रम्ऽसुजिह्वः
शुचिऽजिह्वः
हिरण्यऽजिह्वः
सुऽजिह्वम्
प्राचाऽजिह्वम्
मधुऽजिह्वम्
मन्द्रऽजिह्वम्
गोशजिह्वस्य
मन्द्रऽजिह्वा
अग्निऽजिह्वाः
सुऽजिह्वाः
मधुऽजिह्वाः
सप्तऽजिह्वाः
उपऽजिह्विका
सुऽजिह्वौ
दीर्घऽजिह्वयम्
अजीतये
अजीतिम्
गोऽजीरया
उपऽजीवभित
अमाऽजुरः
धियाऽजुरः
निऽजुरः
अजुरम्
ऋतऽजुरम्
सनाऽजुरा
अजुर्यं
अजर्यः
अजुर्यम्
अजुर्यस्य
अजुर्या
अजर्याः
अजुर्यासः
धीऽजुवः
नभःऽजुवः
मनःऽजुवः
वयःऽजुवः
सद्यःऽजुवः
सनाऽजुवः
कशाःऽजुवम्
मनःऽजुवम्
वसुऽजुवम्
विश्वऽजुवम्
अपिऽजुवा
मनःऽजुवा
सेनाऽजुवा
देवऽजुष्टः
अजुष्टम्
देवऽजुष्टम्
अजुष्टा
देवऽजुष्टा
सुऽजुष्टा
अजुष्टात्
अजुष्टान्
अजुष्टानि
अजुष्टिः
हव्यऽजुष्टिम्
देवऽजुष्टैः
अजुष्टौ
आऽजुहोति
आऽजुह्वानः
आऽजुह्वानस्य
आऽजुह्वानाः
सऽजूः
अद्रिऽजूतः
आदित्यऽजूतः
इन्द्रऽजूतः
दम्ऽसुजूतः
देवऽजूतः
बाहुऽजूतः
ब्रह्मऽजूतः
वातऽजूतः
विप्रऽजूतः
श्येनऽजूतः
इन्द्रऽजूतम्
देवऽजूतम्
वातऽजूता
वातऽजूताः
दस्युऽजूताय
वातऽजूतासः
वृषऽजूतिः
प्रतिजूतिऽवर्पसः
देवऽजूते
यातुऽजूनाम्
सुऽजर्णिः
अजूर्यतः
निऽजूर्वति
निऽजूर्वथः
निऽजूर्वन्
सम्ऽजूर्वसि
निऽजूर्वाः
निऽजूर्वात्
विऽजृम्भते
पूर्वजे इति पूर्वऽजे
तृष्णऽजे
विऽजेन्यम्
स्वऽजेन्यम्
पूर्वऽजेभ्यः
विक्षेपऽकृत्

क्षेत्रऽजेषे
स्वःऽजेषे
विऽजेहमानः
सऽजोषः
सऽजोषसः
सऽजोषसः
सऽजोषसम्
विऽजोषसम्
सऽजोषसा
सऽजोषसौ
सऽजोषाः
अजोषाः
सऽजोषौ
अजोष्यः
आऽजोहुवानाः
मितऽज्ञवः
ऋतऽज्ञाः
पदऽज्ञाः
अज्ञाः
ऋतऽज्ञाः
ऋतऽज्ञाः
अज्ञातऽकेताः
आऽज्ञाता
अज्ञाताः
प्रऽज्ञातारः
अज्ञातेषु
सम्ऽज्ञानम्
ऋतऽज्ञाम्
अभिऽज्ञु
मितज्ञुऽभिः
परिऽज्मन्
परिऽज्मन्
परिऽज्मनः
परिऽज्मने
परिऽज्मनोः
द्विबर्हऽज्मा
परिऽज्मा
परिऽज्मानः
परिऽज्मानम्
परिज्मानाऽइव
परमऽज्याः
ऋतऽज्येन
अज्येष्ठाः
इन्द्रऽज्येष्ठाः
समुद्रऽज्येष्ठाः
इन्द्रऽज्येष्ठान्
अज्येष्ठासः
इन्द्रऽज्येष्ठासः
सुऽज्योतिषः
सुऽज्योतिषः
उरुऽज्रयः
उरुऽज्रयः
परिऽज्रयः
पृथुऽज्रयम्
उरुऽज्रयसम्
पृथुऽज्रयसे
पृथुऽज्रयाः
पृथुऽज्रयी
खरऽज्रुः
नवऽज्वारः
परिऽतंसयध्यै
सर्गऽतक्तः
परिऽतक्म्या
परिऽतक्म्यायाः
परिऽतक्म्यायाम्
परिऽतक्म्ये
विऽतक्षत्
तत्ऽतत्
आऽततः
विऽततः
सुऽआततः
निःऽततक्षतुः
निःऽततक्षुः
आऽततन्थ
आऽततन्वान्
आऽततम्
विऽततम्
सुऽआततम्
आऽतता
विऽतता
प्रऽतताः
विऽतताः
आऽततान
विऽततानि
विऽतते
शम्ऽतनवे
आऽतनिः
सम्ऽतनिः
सम्ऽतनिम्
अतप्तऽतनूः
विऽतनोति
दीर्घऽतन्तुः
त्रिऽतन्तुम्
सप्तऽतन्तुम्
अतन्द्रः
अतन्द्राः
अतन्द्रासः
त्रिऽतन्त्वते
अग्निऽतपः
आऽतपः
आऽतरः
अग्नितपःऽभिः
प्रऽतपन्
साम्ऽतपनाः
अतप्तऽतनूः
परिऽतप्तम्
निःऽतप्ता
अग्निऽतप्तेभिः
परिऽतप्य
अतप्यमाने इति
तम्ऽतम्
दीर्घऽतमाः
दुस्तरः
प्रऽतरणः
प्रऽतरणम्
सुऽतरणान्
प्रऽतरणीम्

दुस्तरम्
वृत्रऽतरम्
अवऽतरम्
प्रऽतरम्
रथम्ऽतरम्
विऽतरम्
दुस्तरस्य
दुस्तरा
सुऽतरा
दुस्तराः
सुतराः
दिवाऽतरात्
अविदुःऽतरासः
विऽतरित्रता
दुस्तरीतवे
प्रऽतरीता
दुस्तरीतु
सम्ऽतरुत्रम्
रथम्ऽतरे
सम्ऽतरेयुः
विऽततुरम्
विऽततुराणः
सुऽतर्माणम्
दस्युऽतर्हणा
स्वऽतवः
स्वऽतवः
प्रऽतवसः
स्वऽतवसः
स्वऽतवसः
प्रऽतवसे
स्वऽतवसे
स्वऽतवान्
अनिभृष्टऽतविषिः
सम्ऽतवीत्वत्
अतव्यान्
विभ्वऽतष्टः
सुऽतष्टः
विभ्वऽतष्टम्
सुऽतष्टम्

स्तोमऽतष्टा
विभ्वऽतष्टाः
स्तोमऽतष्टाः
स्तोमऽतष्टासः
सम्ऽतस्थानाः
विऽतस्थानाम्
संतस्थाने इति सम्ऽतस्थाने
आतस्थिऽवांसः
अवतस्थिऽवांसम्
आतस्थिऽवांसम्
आतस्थिऽवांसा
प्रऽतस्थुः
अपऽतस्थुषः
अतिऽतस्थौ
ताऽता
उत्तानः
उत्तानाम्
उत्तानायाम्
अविऽतारिणीम्
निऽतिक्ताः
निऽतिक्ति
अतिथिः
अतिथिऽग्वम्
अतिथिम्
प्रऽतिरन्
प्रऽतिरन्ती
प्रऽतिरन्ते
प्रऽतिरन्तौ
प्रऽतिरम्
विऽतिरे
अधिऽतिष्ठथः
अधिऽतिष्ठन्
उत्ऽतिष्ठन्
विऽतिष्ठन्
उपऽतिष्ठन्त
अतिष्ठन्तम्
आऽतिष्ठन्तम्
अतिष्ठन्तीनाम्
उपऽतिष्ठन्ते

उपऽतिष्ठमानः
उपऽतिष्ठमानाम्
विऽतिष्ठसे
अतीर्णम्
सुऽतीर्थम्
सुऽतीर्था
सुऽतुकः
सुऽतुका
सुऽतुकाः
सुऽतुकान्
सुऽतुकेभिः
आऽतुचि
आतुजी इत्याऽतुजी
आऽतुजे
तुञ्जेऽतुञ्जे
आऽतुतोद
अप्ऽतुरः
निःऽतुरः
मिथःऽतुरः
रध्रऽतुरः
अप्ऽतुरम्
आजिऽतुरम्
रजःऽतुरम्
रथऽतुरम्
वृत्रऽतुरम्
मिथःऽतुरा
विश्वऽतुरा
वृत्रऽतुरा
निःऽतुरे
रजःऽतूः
रथऽतूः
विश्वऽतूः
रथतूःऽभिः
अतूतुजिम्
अतूर्तः
अतूर्तऽदक्षा
अतूर्तऽपन्थाः
अतूर्तम्
अतूर्तम्

प्रऽतूर्तयः
प्रऽतूर्तये
विश्वऽतूर्तिः
सुऽप्रतूर्तिम्
प्रऽतूर्तिषु
सुप्रतूर्ती इति सुऽप्रतूर्ती
अतूर्तं
विऽतूर्य
अप्ऽतूर्यम्
शत्रुऽतूर्याय
अप्ऽतूर्ये
वृत्रऽतूर्ये
वृत्रऽतूर्येषु
प्रऽतूर्वतः
पृत्सुऽतूर्षु
अलातृणासः
आऽतृदः
प्रऽतृदः
अतृदिलासः
असुऽतृपः
पशुऽतृपम्
अतृपासः
असुऽतृपौ
अतृष्णुवन्तम्
अतृषिताः
अतृष्णऽजः
अतृष्यन्तीः
निऽतोदिनः
निऽतोशनम्
निऽतोशना
निऽतोशनासः
निऽतोशे
पुरुऽत्मानम्
आविःऽत्यः
तनूऽत्यजः
सुऽत्यजम्
तनूत्यजाऽइव
आविःऽत्यम्
पुरुऽत्रा

अनग्निऽत्राः
सुऽत्रात्रः
सुऽत्रात्रा
सुऽत्रात्रासः
सुऽत्रामा
सुऽत्रामाणम्
चतुःऽत्रिंशत्
त्रयःऽत्रिंशतम्
चतुःऽत्रिंशता
षट्ऽत्रिंशान्
हिरण्यऽत्वक्
विऽत्वक्षणः
प्रऽत्वक्षसः
भाऽत्वक्षसः
प्रऽत्वक्षसम्
प्रऽत्वक्षाणः
सूर्यऽत्वचः
सूर्यऽत्वचम्
सूर्यऽत्वचा
त्वम्ऽत्वम्
इन्द्रत्वाऽऊताः
वातऽत्विषः
अभिऽत्सरन्ति
अवऽत्सारस्य
अयःऽदंष्ट्रः
अयःऽदंष्ट्रान्
पुरुऽदंसम्
सुऽदंससः
सुऽदंससम्
पुरुऽदंससा
सुऽदंससा
पुरुऽदंससा
पुरुऽदंससा
पुरुऽदंसा
सुऽदंसाः
अननुऽदः
दानुऽदः
द्रविणःऽदः
द्रविणःऽदुः

सुऽदक्ष
सुऽदक्षः
पूतऽदक्षः
सुऽदक्षम्
घृतऽदक्षम्
पूतऽदक्षम्
पूतऽदक्षसः
पूतऽदक्षसा
पूतऽदक्षसा
सुऽदक्षस्य
सुऽदक्षा
अतूर्तऽदक्षा
घृतऽदक्षा
सुऽदक्षा
दीनऽदक्षाः
पूतऽदक्षाः
समानऽदक्षाः
पूतऽदक्षान्
सुऽदक्षिणः
सुऽदक्षिणम्
प्रयतऽदक्षिणम्
वज्रऽदक्षिणम्
सहस्रऽदक्षिणाः
अदक्षिणासः
प्रयतऽदक्षिणासः
प्रऽदक्षिणित्
सहस्रऽदक्षिणे
अग्निऽदग्धाः
अनग्निऽदग्धाः
अपश्चात्ऽदघ्वने
क्रिविःऽदती
त्वाऽदत्तः
युवाऽदत्तस्य
युष्माऽदत्तस्य
जमदग्निऽदत्ता
त्वाऽदत्तेभिः
गोऽदत्र
पुरुऽदत्र
सुऽदत्र

सुऽदत्रः
अदत्रऽया
पुराऽददः
सम्ऽदद्स्वान्
अनुऽददति
पुराऽददाति
प्रऽददातु
आददाथे इत्याऽददाथे
आऽददानः
आऽददानः
आऽददिः
पुराऽददिः
सम्ऽददिः
संददी इति सम्ऽददी
आऽददे
उपऽदद्यमाने
आऽदधत्
निऽदधन्
विऽदधत्
आऽदधते
आऽदधर्षन्
आऽदधर्षति
आऽदधाति
आऽदधानः
श्रत्ऽदधानः
निऽदधिरे
आऽदधुः
निऽदधुः
विऽदधुः
सम्ऽदधुः
आऽदधे
शुचिऽदन्
श्रेणिऽदन्
हिरण्यऽदन्तम्
अदब्धः
अदब्धऽधीतीन्
अदब्धम्
अदब्धव्रतऽप्रमतिः
अदब्धस्य

अदब्धा
अदब्धाः
अदब्धाः
अदब्धान्
अदब्धानि
अदब्धासः
अदब्धे इति
अदब्धेभिः
अदब्धैः
दुःऽदभ
दुःऽदभः
आऽदभत्
दुःऽदभम्
अदभा
दुःऽदभासः
आऽदभुः
आऽदभे
अदभ्रम्
अननुऽदम्
दमेऽदमे
अमित्रऽदम्भनः
अमित्रऽदम्भनम्
अदयः
विऽदयते
पुरम्ऽदर
पुरम्ऽदरः
पुरम्ऽदरम्
पुरम्ऽदरस्य
पुरम्ऽदरा
गोऽदरे
आऽदर्ता
आऽदर्दिरः
आऽदर्दिरासः
विश्वऽदर्शतः
विश्वऽदर्शतम्
सुदृशीऽतरः
चतुःऽदश
पञ्चऽदश
सुऽदशाः

पञ्चऽदशम्
पञ्चऽदशानि
द्रविणःऽदसः
पुरुऽदस्मम्
उपऽदस्यति
अविऽदस्यम्
सम्ऽदहन्तः
वाजऽदा
अश्वऽदाः
आत्मऽदाः
ओजःऽदाः
गोऽदाः
द्रविणःऽदाः
धनऽदाः
बलऽदाः
भूरिऽदाः
वस्त्रऽदाः
वाजऽदाः
वासःऽदाः
सहःऽदाः
सहस्रऽदाः
सुऽदाः
स्वस्तिऽदाः
हिरण्यऽदाः
भूरिऽदाः
द्रविणोदाःऽइव
सुदाःऽतराय
ऋश्यऽदात्
त्वाऽदातम्
ओजःऽदातमः
सहस्रऽदातमम्
हव्यऽदातये
अश्वऽदातरः
निऽदातारम्
हव्यदातिऽभिः
हव्यऽदातिम्
सुऽदातु
शतऽदातु
सहस्रऽदातु

बृहत्ऽदिवा
बृहत्ऽदिवाः
प्रऽदिवि
अहःऽदिवि
त्रिऽदिवे
दिवेऽदिवे
बृहत्ऽदिवेषु
बृहत्ऽदिवैः
आऽदिशः
प्रऽदिशः
आऽदिशम्
प्रऽदिशम्
प्रऽदिशा
आऽदिशाम्
प्रऽदिशि
आऽदिशे
अननुऽदिष्टः
स्मत्ऽदिष्टयः
प्रऽदिष्टाः
स्मत्ऽदिष्टिः
स्मदिष्टी इति स्मत्ऽदिष्टी
स्मत्ऽदिष्टीन्
सम्ऽदिहः
सुऽदीतयः
सुऽदीतये
सुदीतिऽभिः
सुऽदीतिम्
सुऽदीती
प्रऽदीदयत्
सुऽदीदितिम्
अविऽदीधयुम्
प्रऽदीध्याना
आऽदीध्ये
परिऽदीयथः
प्रतिऽदीव्ने
अतिऽदीव्य
अपदुःऽपदा
अदुःऽमखस्य
अदुःऽमङ्गलीः

अद्रिऽदुग्धः
अद्रिऽदुग्धाः
अप्रऽदुग्धाः
अदुग्धाःऽइव
सबःऽदुघः
शुक्रऽदुघस्य
सबःऽदुघा
सुऽदुघा
सबःऽदुघाः
सुऽदुघाः
सबःऽदुघाम्
सुऽदुघाम्
सबःऽदुघायाः
मधुदुघे इति मधुऽदुघे
सबर्दुघे इति सबःऽदुघे
सुदुघे इति सुऽदुघे
अदुःऽकृतौ
अदुच्छुनः
अभिऽदुद्रोह
शतऽदुरस्य
आऽदुरे
शतऽदुरेषु
अदुवः
गोऽदुहः
घृतऽदुहः
आऽदुहुः
गोऽदुहे
अग्निऽदूतः
त्वाऽदूतासः
पाकऽदूर्वा
उपऽदृक्
सम्ऽदृक्
स्वःऽदृक्
सुऽदृङ्
आऽदृत्य
अप्रऽदृपितः
अदृपिताय
अदृपितेभिः
अदृप्तः

अदृप्तऽक्रतुः
अदृप्तऽक्रतुम्
अदृप्तम्
प्रऽदृप्तिः
अदृप्यता
अहःऽदृशः
दूरेऽदृशः
यक्षऽदृशः
सम्ऽदृशः
सुऽदृशः
स्वःऽदृशः
दूरेऽदृशम्
सम्ऽदृशम्
सुऽदृशम्
सुऽसंदृशम्
स्वःऽदृशम्
दूरेऽदृशा
मिथुऽदृशा
स्वःऽदृशा
सम्ऽदृशि
सुऽदृशी
सुऽदृशीः
सुऽदृशीः
सुऽदृशीकः
चित्रऽदृशीकम्
दुःऽदृशीकम्
सुऽदृशीकम्
सुदृशीकऽरूपः
दूरेऽदृशे
सम्ऽदृशे
अनुऽदृश्य
विश्वऽदृष्टः
अदृष्टऽहा
अदृष्टाः
अदृष्टाः
विश्वऽदृष्टाः
अदृष्टान्
सम्ऽदृष्टिः
सम्ऽदृष्टौ

हविःऽदे
प्रऽदेदिशत्
आऽदेदिशानः
आऽदेदिशानान्
अनुऽदेयम्
मघऽदेयम्
बलऽदेयाय
मघऽदेयाय
राधःऽदेयाय
वसुऽदेयाय
अनुऽदेयी
वैरऽदेये
सुऽदेवः
अदेवः
अनृतऽदेवः
देवःऽदेवः
विश्वऽदेवः
सहऽदेवः
अदेवऽत्रात्
अर्धऽदेवम्
सुऽदेवम्
अदेवम्
अन्तिऽदेवम्
अवःऽदेवम्
आऽदेवम्
उग्रऽदेवम्
देवम्ऽदेवम्
विश्वऽदेवम्
अदेवऽयन्तम्
अदेवऽयुः
अदेवऽयुम्
अदेवऽयून्
अदेवऽयोः
अदेवस्य
देवस्यऽदेवस्य
वामऽदेवस्य
अदेवाः
सुऽदेवाः
मूरऽदेवाः

विश्वऽदेवाः
विश्वऽदेवाः
शिश्नऽदेवाः
अदेवात्
अदेवान्
मूरऽदेवान्
शिश्नऽदेवान्
अदेवानि
सुऽदेवाय
विश्वऽदेवाय
आऽदेवासः
अदेवीः
आऽदेवीः
आऽदेवे
अदेवेन
विश्वऽदेवैः
विश्वऽदेव्य
शौरऽदेव्यः
साहऽदेव्यः
विश्वऽदेव्यः
साहऽदेव्यम्
सुऽदेव्यम्
विश्वऽदेव्यम्
साहऽदेव्यात्
द्रविणःऽदेषु
तुविऽदेष्णम्
कुमारऽदेष्णाः
स्कम्भऽदेष्णाः
पुराऽदै
मधुऽदोघम्
सुदोघे इति सुऽदोघे
प्रऽदोधुवत्
प्रऽदोषम्
प्रतिऽदोषम्
विश्वऽदोहसः
सूदऽदोहसः
विश्वऽदोहसम्
द्रविणःऽदौ
रयिऽदौ

अभिऽद्यवः
द्यविंऽद्यवि
अभिऽद्यवे
वृष्टिऽद्यावः
पृथिवीद्यावा
वृष्टिऽद्यावा
विऽद्युत्
अद्युतः
विऽद्युतः
सुऽद्युतः
ऋष्टिऽविद्युतः
ऋष्टिऽविद्युतः
विऽद्युतः
विऽद्युतम्
विऽद्युता
सुऽद्युते
अभिद्युऽभिः
अद्युम्
अभिऽद्युम्
दशाऽद्युम्
ऋतऽद्युम्न
तुविऽद्युम्न
विभूतऽद्युम्नः
तुविऽद्युम्नम्
तुविऽद्युम्नस्य
पाशऽद्युम्नस्य
तुविऽद्युम्नाः
अभिष्टिऽद्युम्नाः
सुऽद्युम्नाम्
त्वेषऽद्युम्नाय
तुविऽद्युम्नासः
कमऽद्युवम्
एकऽद्यूः
अद्यूत्ये
सुऽद्योत्मा
सुऽद्योत्मानम्
पुरुऽद्रप्साः
मितऽद्रवः
सुऽद्रविणः

वाजऽद्रविणसः
निऽद्रा
रघुऽद्रु
मितऽद्रुः
रघुऽद्रुवः
अद्रुहः
पुरुऽद्रुहः
अद्रुहः
अद्रुहम्
अद्रुहा
अद्रुहा
अनभिऽद्रुहा
विघुद्रुहाऽइव
अद्रुहे
अभिऽद्रुहे
अद्रुह्वाणा
अद्रोघ
अद्रोघः
अद्रोघम्
अद्रोघम्
अद्रोघऽवाचम्
अद्रोघेण
अभिऽद्रोहम्
मितऽद्रौ
सुऽद्रवम्
अद्वयन्तम्
अद्वयाः
अद्वयाविनः
अद्वयाविनम्
अद्वयावी
अद्वयुम्
वृकऽद्वरसः
द्वाऽद्वा
आऽद्वादशम्
सहस्रऽद्वारम्
पृथमानऽद्विद्
अनृतऽद्विषः
पनिऽद्विषः
ब्रह्मऽद्विषः
असत्ऽद्विषः
ब्रह्मऽद्विषम्
ऋषिऽद्विषे
ब्रह्मऽद्विषे
अद्विषेण्यः
अद्विषेण्यम्
इन्द्रऽद्विष्टाम्
अद्वेषः
विऽद्वेषणम्
परिऽद्वेषसः
युतऽद्वेषसः
यवयत्ऽद्वेषसम्
विऽद्वेषसम्
वीळुऽद्वेषाः
तरत्ऽद्वेषाः
यवयत्ऽद्वेषाः
अद्वेषे इति
पृक्षुधः
वयःऽधः
त्रिऽधक्ष्यन्
महाऽधनम्
धनम्ऽधनम्
प्रऽधनस्य
महाऽधनस्य
धनेऽधने
प्रऽधने
महाऽधने
प्रऽधनेषु
सुऽधनौ
सऽधन्यः
शतऽधन्यम्
जीवऽधन्यम्
सऽधन्यम्
सऽधन्या
जीवऽधन्याः
प्रऽधन्यासु
स्थिरऽधन्वने
सुऽधन्वा
उग्रऽधन्वा
क्षिप्रऽधन्वा
सुऽधन्वानः
निऽधयः
परिऽधयः
प्रऽधयः
प्रतिऽधयः
निऽधया
पुरम्ऽधये
दुःऽधरम्
दुःऽधरीतुम्
विधर्तरिति विऽधर्तः
विऽधर्तरि
दुःऽधर्तवः
विऽधर्ता
विऽधर्मणा
विऽधर्मणि
विऽधर्मणे
विऽधर्मन्
विऽधर्मन्
स्वऽधर्मन्
सत्यऽधर्मा
सत्यऽधर्माणः
सत्यऽधर्माणम्
सत्यऽधर्माणा
दुःऽआधर्षम्
आऽधवम्
आऽधवे
अपऽधा
प्रतिऽधा
सुऽनिधा
धामऽधाः
धियम्ऽधाः
नामऽधाः
पयःऽधाः
रत्नऽधाः
रेतःऽधाः
वयःऽधाः
सत्रऽधाः
मण्डूरऽधाणिकीः

रत्नऽधातमः
वरिवःऽधातमः
सत्रऽधातमः
रत्नऽधातमम्
सत्रऽधातमम्
विधातरिति विऽधातः
त्रिऽधातवः
प्रतिऽधातवे
त्रिऽधाता
सम्ऽधाता
त्रिऽधातारः
त्रिऽधातु
त्रित्रिष्ठिऽधातु
सुऽधातु
सप्तऽधातु
त्रिऽधातुः
निऽधातुः
सप्तऽधातुः
त्रिऽधातुना
त्रिधातुऽभिः
त्रिऽधातुम्
त्रिधातुऽशृङ्गः
त्रिऽधातूनि
निऽधातोः
यातुऽधान
यातुऽधानः
सोमऽधानः
अपिधानऽवन्तम्
आऽधानम्
निऽधानम्
यातुऽधानम्
विऽधानम्
सोमऽधानम्
यातुऽधानस्य
अपिऽधाना
निऽधाना
यातुऽधाना
त्रिऽधाना
सोमऽधाना
यातुऽधानाः
सोमऽधानाः
यातुऽधानात्
यातुऽधानान्
अग्निऽधाने
यातुऽधान्यः
निऽधान्यम्
निधाऽपतिः
रत्नऽधाभिः
दुःऽधाम्
वयःऽधाम्
वरिवःऽधाम्
विपःऽधाम्
प्रियऽधामाय
कारुऽधायः
विश्वऽधायः
अरिऽधायसः
विश्वऽधायसः
गोऽधायसम्
भूरिऽधायसम्
विश्वऽधायसम्
हरिऽधायसम्
कारुऽधायाः
विश्वऽधायाः
निऽधायि
सुऽधारः
शतऽधारः
सहस्रऽधारः
मधुऽधारम्
शतऽधारम्
सहस्रऽधारम्
निऽधारयः
निऽधारयन्तः
सहस्रऽधारा
उरुधाराऽइव
द्विऽधाराः
सुऽधाराः
शतऽधाराः
उरुऽधाराम्
सहस्रऽधाराम्
त्रिऽधारे
भूरिधारे इति भूरिऽधारे
सहस्रऽधारे
विऽधावतः
अवऽधावति
प्रऽधावति
परिऽधावसि
आऽधिः
इषुऽधिः
निऽधिः
परिऽधिः
पुरम्ऽधिः
सुऽधितः
सुऽधितम्
मित्रऽधितये
नेमऽधिता
युत्रऽधिता
सुऽधिता
सुधिताऽइव
सुऽधिताः
दुःऽधितात्
मित्रऽधितानि
सुऽधितानि
वनऽधितिः
स्वऽधितिः
वसुऽधितिम्
स्वऽधितिम्
वसुधिती इति वसुऽधिती
सुऽधितेभिः
स्वऽधितौ
अभिऽधित्सते
निऽधिभिः
उत्सऽधिम्
उदऽधिम्
गर्भऽधिम्
निऽधिम्
परिऽधिम्
प्रऽधिम्

शेवऽधिम्
सम्ऽधिम्
पुरम्ऽधिम्
दीर्घऽधियः
नानाऽधियः
धियम्ऽधियम्
इत्थाऽधिये
निऽधिषु
पुरंधी इति पुरम्ऽधी
इत्थाऽधीः
पुरम्ऽधीः
विश्वतःऽधीः
आऽधीतम्
ऋतऽधीतयः
ऋतऽधीतयः
ऋतधीतिऽभिः
ऋतऽधीतिम्
अदब्धऽधीतीन्
अपिऽधीन्
इषुऽधीन्
निऽधीन्
परिऽधीन्
निऽधीनाम्
निऽधीयमानम्
प्रतिऽधीयमानम्
अधीरा
यज्ञऽधीराः
धीवतःऽधीवतः
आऽधीषमाणायाः
गोऽधुक्
सबःऽधुक्
काराधुनीऽइव
विऽधुम्
सबःऽधुम्
दुःऽधुरः
सुऽधुरः
सुऽधुरम्
सुऽधुरा
नृऽधूतः
वातऽउपधूतः
वृषऽधूतस्य
बभ्रुऽधूताः
अवऽधूनुषे
आऽधून्वते
अवऽधून्वानः
अनुऽधूपितासः
चरिष्णुऽधूमम्
अर्चत्ऽधूमासः
चर्षणिऽधृत्
चर्षणिऽधृतः
मनःऽधृतः
चर्षणिऽधृतः
चर्षणिऽधृतम्
चर्षणिऽधृता
आऽधृषः
आऽधृषे
प्रतिऽधृषे
अधृष्टः
अधृष्टम्
सुऽधृष्टमम्
सुधृष्टमे इति सुऽधृष्टमे
अधृष्टाः
अनाधृष्टानि
अधृष्टासः
संवृक्तऽधृष्णुम्
अनाधृष्याः
धियम्ऽधे
इषुऽधेः
उदऽधेः
विसृष्टऽधेना
विश्वऽधेनाः
विश्वऽधेनाम्
एकधेनुऽभिः
अधेनुम्
अधेन्वा
रत्नऽधेभिः
नामऽधेयम्
भागऽधेयम्
रत्नऽधेयम्
रत्नऽधेया
भागऽधेयानि
रत्नऽधेयानि
रत्नऽधेयाय
वयःऽधेयाय
वयःऽधै
स्वऽधैनवानाम्
आऽध्यः
दुःऽध्यः
सुऽध्यः
दुःऽध्या
पुरम्ऽध्या
इषुध्याऽइव
पुरम्ऽध्याम्
आऽध्यै
दुःऽध्यै
चित्रऽध्रजतिः
अध्रिजः
अध्रुक्
अक्ष्णयाऽध्रुक्
अन्तकऽध्रुक्
अभिऽध्रुक्
अस्मऽध्रुक्
अध्रुक्
वरुणऽध्रुतः
निऽध्रुवि
निऽध्रुविः
अस्मृतध्रु इत्यस्मृतऽध्रु
कृतऽध्वजः
अतिऽध्वसन्
अध्वस्मऽभिः
अध्वस्मानः
सत्यऽध्वृतम्
स्वप्नऽनंशनः
उषसानक्ता
अभिऽनक्षन्तः
अभिऽनक्षमाणाः
अनभ्राः

अनानतम्
मुष्टेऽनदि
निऽनद्धः
सम्ऽनद्धः
अनपिऽनद्धम्
अपिऽनद्धम्
अवऽनद्धम्
सम्ऽनद्धा
आऽनन्दम्
आऽनन्दाः
कुनन्नमा
तनू३ऽनपात्
तनूऽनपात्
तनूऽनपात्
तनू३ऽनपातम्
प्रनपादिति प्रऽनपात्
अभिऽनभ्यम्
आऽनमम्
सम्ऽनममानः
अनमस्युः
निऽनमे
विऽनयः
सम्ऽनयः
प्रऽनयन्त
प्रऽनयसि
सम्ऽनयानि
सम्ऽनयामसि
शिक्षाऽनरः
स्वःऽनरः
स्वःऽनरम्
सूनरम्
स्वःऽनरात्
स्वःऽनरे
पुनःऽनव
नवःऽनवः
सम्ऽनवामहे
नव्यम्ऽनव्यम्
नव्याःऽनव्याः
दुःऽनशः
दुःऽनशम्
दुःऽनशा
परिऽनशे
सम्ऽनशे
अनष्टऽपशुः
अनष्टऽवेदसम्
सम्ऽनसन्त
सम्ऽनसामहे
उरुऽनसौ
अक्षऽनहः
परिऽनहम्
शमीनहुषी इति
आऽनह्यमानः
त्रिऽनाके
वेकुऽनाटान्
अनाथम्
सऽनाभयः
त्रिऽनाभि
सऽनाभिः
वृषऽनाभिना
पुरुऽनामन्
अनामयित्नुऽभ्याम्
दुःऽनामा
सप्तऽनामा
सुमन्तुऽनामा
सऽनामाना
अनामि
अहिऽनाम्नाम्
सुहवीतुऽनाम्ने
उपऽनायम्
विऽनाशयन्
इन्द्रनासत्या
यज्ञनिःऽकृतः
अनिःऽकृतम्
सुनिःऽमथा
अनिःऽशस्ताः
पुरुनिःऽसिध्वानम्
अनिःऽस्तृतः
पुरुनिःऽस्थः
कर्मनिःऽस्थाम्
निःऽनिक्
विऽनिक्षे
निःऽनिजः
निःऽनिजम्
निःऽनिजा
निःऽनिजानः
निःऽनिजे
त्वाऽनिदः
देवऽनिदः
निदम्ऽनिदम्
सुऽनिधा
आऽनिनाय
प्रऽनिनाय
उत्ऽनिनीथः
अनिन्द्यः
अनिन्द्या
अनिन्द्राः
उपऽनिपद्यमानम्
अनिऽपद्यमानम्
केऽनिपानाम्
आकेऽनिपासः
पृश्निऽनिप्रेषितासः
अनिऽबद्धः
अनिऽबाधे
अनिऽभृष्टः
अनिभृष्टऽतविषिः
ऋतनिऽभ्यः
अनिऽमानः
अनिऽमिषः
अनिऽमिषम्
अनिऽमिषा
अनिऽमिषाः
दुःऽनियन्तवः
दुःऽनियन्तुः
घृतऽनिर्निक्
घृतऽनिर्निक्
चन्द्रऽनिर्निक्
हिरण्यऽनिर्निक्

अधिऽनिर्निजः
घृतऽनिर्निजः
वर्पऽनिर्निजः
सहस्रऽनिर्निजम्
सहस्रऽनिर्निजा
अश्वऽनिर्निजि
अनिऽविशमानाः
अनिऽवृतः
अनिऽशितम्
अनिशितऽसर्गाः
अनिपद्याय
अनिपद्याः
सुऽनिष्काः
मन्दिऽनिस्पृशः
ग्रामऽनीः
यज्ञऽनीः
वसुऽनीः
व्रतऽनीः
सेनाऽनीः
अनीळः
कृपऽनीळम्
सऽनीळाः
सऽनीळाभिः
सनीळे इति सऽनीळे
सऽनीळेभिः
आऽनीतः
युष्माऽनीतः
अवऽनीतम्
उपऽनीतम्
प्रऽनीतम्
सुऽनीतयः
प्रऽनीतयः
सुऽप्रनीतयः
युवाऽनीतस्य
उपऽनीता
उत्ऽनीताः
अवऽनीताय
प्रऽनीतिः
वर्पऽनीतिः

वामऽनीतिः
शर्धऽनीतिः
सहस्रऽनीतिः
सुऽनीतिः
सुऽप्रनीतिः
सुनीतिऽभिः
प्रनीतिऽभिः
अग्रऽनीतिम्
असुऽनीतिम्
सुऽप्रनीतिम्
प्रऽनीतिषु
ऋजुऽनीती
प्रऽनीती
सुऽनीती
सुऽप्रनीती
असुऽनीते
प्रऽनीतौ
सुऽनीथः
शतऽनीथः
सहस्रऽनीथः
सुऽनीथम्
शतऽनीथम्
पुरुऽनीथा
सुऽनीथाः
सहस्रऽनीथाः
सुऽनीथाय
सुऽनीथासः
पुरुऽनीथे
सुऽनीथे
दीर्घऽनीथे
नीथेऽनीथे
अधिऽनीयमानः
उत्ऽनीयमानाः
अनुत्तम्
अनुत्तऽमन्युः
अनुत्ता
अनुत्ताः
विऽतुदः
प्रतिऽनुदन्

पराऽनुदे
तुविऽनृम्ण
तुविऽनृम्ण
तुविऽनृम्णः
त्वेषऽनृम्णः
तुविऽनृम्णम्
पुरुऽनृम्णाय
मुञ्जऽनेजनम्
प्रनेतरिति प्रऽनेतः
प्रनेतरिति प्रऽनेतः
अभिऽनेता
आऽनेता
प्रऽनेता
प्रऽनेतारः
प्रऽनेतारम्
नाभानेदिष्ठः
अनेद्य
अनेद्यः
अनेद्याः
प्रऽनेनीः
अतिऽनेनीयमानः
हिरण्यऽनेमयः
सऽनेमि
अरिष्टऽनेमिः
अरिष्टऽनेमिम्
अरिष्टऽनेमे
प्रऽनेपत्
प्रऽनोदम्
आऽनोनवीति
अनुऽनोनुवतः
प्रऽन्यः
यज्ञऽन्यम्
यज्ञऽन्योः
गोऽन्योधाः
हिरण्यऽपक्षम्
पृथुऽपक्षसा
विऽपक्षसा
मांस्पचन्याः
पक्षऽपक्ष

त्रिऽपञ्चाशाः
अक्षिऽपत्
चतुःऽपत्
द्विऽपत्
उत्ऽपतन्
सम्ऽपतन्ति
अवऽपतन्तीः
निःऽपतन्त्योः
बृहस्पतये
जाःपतिः
नृऽपतिः
बृहस्पतिः
रथःऽपतिः
रयिऽपतिः
वनस्पतिः
विश्पतिः
शचीईऽपतिः
गृहऽपतिः
गोऽपतिः
ग्नाःऽपतिः
दक्षऽपतिः
निधाऽपतिः
प्रजाऽपतिः
वसुऽपतिः
वाजऽपतिः
सत्ऽपतिः
स्वऽपतिः
स्वःऽपतिः
हविःऽपतिः
अपतिऽघ्नी
बृहस्पतिना
बृहस्पतिऽप्रसूताः
वनस्पतिऽभिः
वनस्पतिऽभ्यः
नृऽपतिम्
बृहस्पतिम्
वनस्पतिम्
विश्पतिम्
शचीईऽपतिम्

गणऽपतिम्
गाथऽपतिम्
गृहऽपतिम्
गोऽपतिम्
जाःपतिम्
दम्ऽपतिम्
परिऽपतिम्
पूःऽपतिम्
मेधऽपतिम्
वसुऽपतिम्
व्राजऽपतिम्
श्रवयत्ऽपतिम्
सत्ऽपतिम्
सोमऽपतिम्
स्वःऽपतिम्
सदस्पती इति
गोपती इति गोऽपती
दंपती इति दम्ऽपती
नृपती इति नृऽपती
मदपती इति मदऽपती
वनस्पती इति
शचीपती इति शचीऽपती
सत्पती इति सत्ऽपती
सिन्धुपती इति सिन्धुऽपती
स्वःपती इति स्वःऽपती
वनस्पतीन्
सत्ऽपतीन्
वनस्पतीनाम्
अश्वऽपते
आजिऽपते
उर्वराऽपते
ऋतःऽपते
ऋतुऽपते
गणऽपते
गृहऽपते
गोऽपते
गोऽपते
द्युम्नऽपते
नृऽपते

प्रजाऽपते
बृहस्पते
बृहस्पते
मित्रऽपते
रयिऽपते
राधःऽपते
वनस्पते
वनस्पते
वसुऽपते
वसुऽपते
विश्पते
विश्पते
शचीऽपते
शचीऽपते
सत्ऽपते
सत्ऽपते
सोमऽपते
स्वधाऽपते
बृहस्पतेः
प्रऽपतेत्
वनस्पतौ
गोऽपतौ
यज्ञऽपतौ
असपत्नः
सपत्नऽघ्नी
सपत्नऽहा
सऽपत्नाः
सऽपत्नान्
सऽपत्नानाम्
शूरऽपत्नि
वसुऽपत्नी
सऽपत्नीं
सपत्नी इति सऽपत्नी
सुपत्नी इति सुऽपत्नी
इन्द्रऽपत्नी
गृहऽपत्नी
वाजऽपत्नी
वीरऽपत्नी
नृऽपत्नीः

सुऽपत्नीः
सुऽपत्नीः
अयंऽपत्नीः
दासऽपत्नीः
देवऽपत्नीः
दम्ऽसुपत्नीः
वृषऽपत्नीः
शूरऽपत्नीः
सुपत्नीःऽइव
ग्नाःपत्नीभिः
विश्पत्नीम्
सुऽपत्नीम्
विश्पत्न्यै
शतपत्ऽभिः
विऽपत्मनः
वीळुपत्मऽभिः
जाःपत्यम्
अधिऽपत्यम्
गार्हऽपत्यानि
गार्हऽपत्याय
गार्हऽपत्येन
क्षैत्रऽपत्येषु
शतऽपत्रः
अच्छिन्नऽपत्राः
आशुऽपत्वा
रघुऽपत्वा
श्येनऽपत्वा
रघुऽपत्वानः
पथःऽपथः
आऽपथयः
विऽपथयः
सुऽपथा
अनुऽपथाः
अन्तःऽपथाः
सुऽपथानि
प्रऽपथिन्
प्रपथिन्ऽतमम्
प्रऽपथी
प्रऽपथे

प्रऽपथेषु
आऽपथ्यः
अवऽपदः
द्विऽपदः
निःऽपदः
उत्तानऽपदः
चतुःऽपदः
परिऽपदम्
अधःऽपदम्
दुःऽपदा
द्विऽपदा
अपदुःऽपदा
चतुःऽपदा
अधःऽपदाः
अधःऽपदात्
प्रऽपदाभ्याम्
द्विऽपदाम्
परिपदाम्ऽइव
अपदी
अपदी इति
द्विऽपदी
सुऽपदी
अष्टाऽपदी
एकऽपदी
घृतऽपदी
चतुःऽपदी
नवऽपदी
अष्टाऽपदीभिः
अष्टाऽपदीम्
चतुःऽपदीम्
सप्तऽपदीम्
अपदे
द्विऽपदे
द्रुऽपदे
चतुःऽपदे
पदेऽपदे
मह्नाऽपदेन
द्रुऽपदेषु
प्रऽपदैः

अभिऽपद्य
निऽपद्यते
उपऽनिपद्यमानम्
अनिऽपद्यमानम्
आऽपनीफणत्
पुरुऽपन्थाः
अतूर्तऽपन्थाः
परिऽपन्थिनः
परिऽपन्थिनम्
परिपन्थीऽइव
पन्थम्ऽपन्थम्
सुऽपप्तनि
उपपप्तिऽवांसम्
आऽपप्राथ
आपप्रिऽवांसम्
आपप्रिऽवान्
आऽपमुषी
गोपम्
मधुऽपम्
अरित्रऽपरणीम्
एकऽपरस्य
पराऽपरा
अपराऽजितम्
अपराऽजिता
अपरिऽहृतम्
सोमऽपरिबाधः
अपरिऽविष्टम्
अपरिऽवृतः
दुःऽपरिहन्तु
अपरिऽह्वृतः
अपरिऽह्वृताः
गोऽपरीणसा
परुःऽपरुः
उपऽपर्चनम्
वातापर्जन्या
अग्नीपर्जन्यौ
सुऽपर्णः
सहस्रऽपर्णः
सुऽपर्णम्

सुऽपुर्णी
सुऽपुर्णाः
अश्वऽपर्णाः
हिरण्यऽपर्णाः
उत्तानऽपर्णे
अश्वऽपर्णैः
सुऽपुर्ण्यः
पर्वणाऽपर्वणा
शतऽपर्वणा
पर्वणिऽपर्वणि
इन्द्रापर्वता
इन्द्रापर्वता
अपर्वन्
सोमपर्वऽभिः
विऽपर्वम्
वृषऽपर्वा
पृथुऽपर्शवः
अपलाशः
सुऽपलाशम्
सुऽपलाशे
कृष्णऽपविः
शतऽपवित्राः
वीळुपविऽभिः
अपवीरवान्
दद्दशानऽपवेः
अनष्टऽपशुः
रुशत्ऽपशुः
अपश्चात्ऽदघ्वने
विऽपश्यति
अवऽपश्यन्
सम्ऽपश्यन्
प्रऽपश्यन्तः
परिऽपश्यन्ति
अभिऽपश्यन्ती
प्रऽपश्यमानः
सम्ऽपश्यमानाः
अपश्याः
वाजऽपस्त्यः
क्षीरऽपस्त्यः

त्रिऽपस्त्यम्
अश्वऽपस्त्यम्
वाजऽपस्त्यम्
अनुऽपस्पशानम्
अभिष्टिऽपा
गोपा
तनूऽपा
तपुःऽपा
पुरःऽपा
प्रऽपा
सोमऽपा
स्तिऽपा
गोपा
शुचिऽपा
अग्रेऽपाः
अञ्जःपाःऽइव
अधिऽपाः
अभिशस्तिऽपाः
ऋतऽपाः
ऋतुऽपाः
कुलऽपाः
गोपाः
तनूऽपाः
पथःऽपाः
पुरःऽपाः
पशुऽपाः
पूर्वऽपाः
व्रतऽपाः
शुक्रपूतऽपाः
शेवधिऽपाः
सुतऽपाः
सोमऽपाः
स्तिऽपाः
हरिऽपाः
हविःऽपाः
अनृतुऽपाः
ऋतुऽपाः
शुक्रपूतऽपाः
शुचिऽपाः

सुतऽपाः
सोमऽपाः
सोमऽपाः
पशुपाःऽइव
पूर्वपाःऽइव
अपाकऽचक्षसः
शृतऽपाकम्
क्षीरऽपाकम्
विऽपाका
पृथुऽपाजसः
सहस्रऽपाजसः
पृथुऽपाजसा
पृथुऽपाजसे
त्रिऽपाजस्यः
पृथुऽपाजाः
विऽपाट्
वृषऽपाणयः
सुऽपाणिः
पृथुऽपाणिः
वीळुऽपाणिः
हिरण्यऽपाणिः
वीळुपाणिऽभिः
द्रवत्पाणिऽभिः
हिरण्यपाणिऽभिः
सुऽपाणिम्
मधुऽपाणिम्
हिरण्यऽपाणिम्
सुपाणी इति सुऽपाणी
द्रवत्पाणी इति द्रवत्ऽपाणी
वीळुपाणी इति वीळुऽपाणी
सुपाणी इति सुऽपाणी
हिरण्यऽपाणे
अपात्
त्रिऽपात्
द्विऽपात्
एकऽपात्
चतुःऽपात्
तनूऽनपात्
विश्वतःऽपात्

सहस्रऽपात्
निऽपातः
नपातः
इन्द्रऽपातमः
सोमऽपातमः
सोमऽपातमम्
सोमऽपातमा
मधुऽपातमा
नृऽपाता
नृऽपातारः
निऽपाति
सहस्रऽपाथाः
अपादः
द्विऽपादः
शितिऽपादः
चतुःऽपादः
अपादम्
त्रिऽपादम्
पञ्चऽपादम्
सहस्रऽपादम्
निऽपादाः
द्विऽपादे
गोपान्
शृतऽपान्
इन्द्रऽपानः
देवऽपानः
नृऽपानः
अवऽपानम्
इन्द्रऽपानम्
जनऽपानम्
देवऽपानम्
नृऽपानम्
परिऽपानम्
आपान्तऽमन्युः
सुऽप्रपानम्
इन्द्रऽपानाः
अवऽपानात्
देवऽपानानि
वृषऽपानासः
आपानासः
अवऽपानेषु
वृषऽपानेषु
अग्रेऽपाभिः
ऋतुऽपाभिः
गोपाभिः
अञ्जःऽपाम्
अभिशस्तिऽपाम्
गोपाम्
तनूऽपाम्
निसिक्तऽपाम्
व्रतऽपाम्
शृतऽपाम्
सोमऽपाम्
कुण्डऽपाय्यः
नृऽपाय्यम्
पूर्वऽपाय्यम्
बहुऽपाय्यम्
बहुऽपाय्ये
अपारः
सुऽपारः
अकूपारः
सुपारऽक्षत्रः
सम्ऽपारणम्
अपारम्
सुऽपारम्
अतिऽपारयः
अकूपारस्य
सुऽपारा
सुऽपाराः
अपाराम्
सुऽपारासः
अपारे
अपारे इति
अपारेण
सुतऽपावन्
सोमऽपावन्
अभिशस्तिऽपावा
सोमऽपावा
हिरण्यऽपावाः
सुतऽपाव्नः
सोमऽपाव्नः
सोमऽपाव्नाम्
सुतऽपाव्ने
सोमऽपाव्ने
विऽपाशम्
विऽपाशि
भूरिऽपाशौ
आकेऽनिपासः
अभिऽपासि
निऽपासि
सम्ऽपिंषन्ति
सम्ऽपिणक्
हिरण्यऽपिण्डान्
अपितः
दक्षऽपितरः
मातरापितरा
दक्षऽपितरा
दक्षऽपितॄन्
सुऽपिप्र्य
अपऽपित्वम्
अभिऽपित्वम्
प्रऽपित्वम्
सऽपित्वम्
प्रऽपित्वात्
अभिऽपित्वे
आऽपित्वे
प्रऽपित्वे
अभिऽपित्वेषु
दानुऽपिन्वः
विऽपिपानः
विऽपिपानम्
विऽपिपानस्य
विऽपिपाना
सुऽपिप्पलाः
आऽपिप्यानम्
अतिऽपिप्रति
पिबऽपिब

सम्ऽपिबते
प्रऽपिबन्ति
प्रऽपिबन्ते
आऽपिब्दमानः
विश्वऽपिशः
सुऽपिशः
शुक्रऽपिशम्
विश्वऽपिशा
सुऽसंपिष्टम्
सम्ऽपिष्टात्
इन्द्रऽपीतम्
स्थिरऽपीतम्
नृऽपीतये
पूर्वऽपीतये
सोमऽपीतये
जीवपीतऽसर्गः
प्रऽपीताः
आऽपीतासः
पूर्वऽपीतिः
सपीतिऽभिः
नृऽपीतौ
सोमऽपीथम्
गोऽपीथाय
सोमऽपीथाय
गोऽपीथे
गोऽपीथ्याय
प्रतिऽपीयन्ति
सुऽपीवसः
कुत्सऽपुत्रम्
सुतऽपुत्रम्
सुऽपुत्रा
राजऽपुत्रा
वृत्रऽपुत्रा
जीवऽपुत्राः
देवऽपुत्राः
पुरुऽपुत्राम्
सुऽपुत्राम्
उग्रऽपुत्रे
देवपुत्रे इति देवऽपुत्रे

सुऽपुत्रे
अपुनरिति
पुनःऽपुनः
स्मत्ऽपुरंधिः
अपुरुषघ्नः
अपुरुषम्
विश्वऽपुषम्
विश्वऽपुषा
पुष्टम्ऽपुष्टम्
पुरुवारऽपुष्टिः
अपुष्पाः
अपुष्पाम्
शाचिऽपूजन
गभस्तिऽपूतः
निऽपूतः
परिऽपूतः
गभस्तिऽपूतम्
निऽपूतम्
सुऽपूतम्
धारऽपूताः
शकऽपूते
स्वऽपूभिः
आऽपूर्णः
सुऽपूर्णम्
सुऽपूर्णस्य
सुऽपूर्णाः
इष्टापूर्तेन
अहम्ऽपूर्वः
पूर्वःऽपूर्वः
अनुऽपूर्वम्
यथापूर्वम्
अपूर्व्यं
अपूर्व्यः
अपूर्व्यम्
अपूर्व्या
इन्द्रापूषणा
सोमापूषणा
सोमापूषणौ
सोमापूषऽभ्याम्

इन्द्रापूष्णोः
आऽपृक्
उपऽपृक्
विऽपृक्तः
सम्ऽपृक्ताः
विपृक्वत्
सुऽपृक्षः
अनवऽपृग्णा
सम्ऽपृङ्क्ते
आऽपृचः
सम्ऽपृचः
मधुऽपृचम्
घृतऽपृचा
आऽपृचे
विऽपृचे
विऽपृच्छते
विऽपृच्छम्
सम्ऽपृच्छम्
बन्धुऽपृच्छा
सम्ऽपृच्छे
आऽपृच्यः
आऽपृच्छ्यम्
प्रऽपृञ्चती
सम्ऽपृञ्चानः
सदाऽपृणः
अपृणतः
आऽपृणन्
आऽपृणन्तः
अपृणन्तः
अपृणन्तम्
अपृतन्यत्
द्यावापृथिवी इति
द्यावापृथिवी इति
दिवःपृथिव्योः
त्रिऽपृष्ठः
घृतऽपृष्ठः
नीलऽपृष्ठः
वीतऽपृष्ठः
शुनऽपृष्ठः

त्रिऽपृष्ठम्
अश्वऽपृष्ठम्
घृतऽपृष्ठम्
मधुऽपृष्ठम्
नीलऽपृष्ठम्
शितिऽपृष्ठस्य
शितिऽपृष्ठा
वीतऽपृष्ठा
घृतऽपृष्ठाः
नीलऽपृष्ठाः
वीतऽपृष्ठाः
सोमऽपृष्ठाय
सोमऽपृष्ठासः
त्रिऽपृष्ठे
त्रिऽपृष्ठैः
ऋदुऽपे
कीलालऽपे
शुचिऽपे
विऽपेततुः
मधुऽपेभिः
मिथःऽअवद्यपेभिः
मधुऽपेयः
अन्तःऽपेयम्
पूर्वऽपेयम्
मधुऽपेयम्
सोमऽपेयम्
मधुऽपेयाय
सुतऽपेयाय
सोमऽपेयाय
तुरःऽपेयै
नृऽपेशसः
सुऽपेशसः
पुरुऽपेशसम्
सुऽपेशसम्
अश्वऽपेशसम्
वाजऽपेशसम्
विश्वऽपेशसम्
शुचिऽपेशसम्
सुऽपेशसा
विश्वऽपेशसा
हिरण्यऽपेशसा
अपेशसे
ऋतऽपेशसे
सुऽपेशाः
वीरऽपेशाः
पुरुऽपेशासु
सहस्रऽपोषम्
विश्वायुऽपोषसम्
भूरिऽपोषिणः
सहस्रऽपोषिणम्
सहस्रऽपोष्यम्
गोपौ
छर्दिःऽपौ
जगत्ऽपौ
गोपौ
मधुऽपौ
सुतऽपौ
आऽप्यायमानः
आऽप्यायमानाः
प्रऽप्र
अप्रऽआयु
अप्रऽआयुषे
सुप्रऽअयनतमम्
सुप्रऽअयनाः
सुप्रऽअवीः
दुःप्रऽअव्यः
सुप्रऽअव्यः
सुप्रऽअव्ये
हिरण्यऽप्रउगम्
कृष्टिऽप्रः
सुऽप्रकेतः
अप्रऽकेतम्
सुऽप्रकेतम्
सुऽप्रकेतेभिः
सुऽप्रकेतैः
उपलऽप्रक्षिणी
उपऽप्रक्षे
पृथुऽप्रगानम्
पृथुऽप्रगामा
अभिऽप्रघ्नन्ति
अभिऽप्रचक्षे
अप्रऽचेतसः
सुऽप्रचेतसः
वत्सऽप्रचेतसा
अप्रऽचेताः
अप्रऽच्युतानि
अप्रऽजज्ञयः
अप्रजाः
बहुऽप्रजाः
सुऽप्रजाः
सुप्रजाःऽत्वम्
ऋतऽप्रजात
ऋतऽप्रजातः
पुरुऽप्रजातस्य
ऋतऽप्रजाताम्
सुऽप्रजाम्
सुऽप्रजाऽवतीम्
सर्गऽप्रतक्तः
अप्रता
अप्रति
अप्रतिः
अप्रतिऽइत
अप्रतिऽइतः
अप्रतिऽइतम्
अप्रतिऽइतस्य
सुऽप्रतिचक्षम्
तुविऽप्रतिम्
अप्रतिऽमानम्
अप्रतिऽस्कुतम्
सुऽप्रतीकः
घृतऽप्रतीकः
चारुऽप्रतीकः
पुरुधऽप्रतीकः
मधुऽप्रतीकः
सुऽप्रतीकम्
घृतऽप्रतीकम्
शुचिऽप्रतीकम्

सुऽप्रतीकस्थ
सुऽप्रतीका
घृतऽप्रतीका
त्वेषऽप्रतीका
घृतऽप्रतीकाम्
सुप्रतीके इति सुऽप्रतीके
अप्रतीनि
सुऽप्रतूः
सुऽप्रतूर्तिम्
सुप्रतूर्ती इति सुऽप्रतूर्ती
सुऽप्रथः
सुप्रथःऽतमम्
सुप्रथःऽतमे
सुऽप्रथाः
अप्रऽदुग्धाः
अप्रऽदृपितः
मानुषऽप्रधनाः
सहस्रऽप्रधनेषु
सुऽप्रनीतयः
सुऽप्रनीतिः
सुऽप्रनीतिम्
सुऽप्रनीती
सुऽप्रनीते
सुऽप्रपानम्
सुऽप्रपाने
अभिऽप्रभङ्गिनः
तुपलऽप्रभर्मा
वृषऽप्रभर्मा
अप्रऽभुः
अप्रऽभूती
अदब्धव्रतऽप्रमतिः
दशऽप्रमतिम्
अभिऽप्रमन्दुः
वाजऽप्रमहः
सहऽप्रमाः
वातऽप्रमियः
अभिऽप्रमुरा
अप्रऽमृष्यः
अप्रऽमृष्यम्
पृक्षऽप्रयजः
दीर्घऽप्रयज्युम्
उपऽप्रयन्
उपऽप्रयन्तः
विऽप्रयन्तः
परिऽप्रयन्तम्
हितऽप्रयसः
सुऽप्रयसम्
सुऽप्रयसा
हितऽप्रयसा
सुऽप्रयाः
घृतऽप्रयाः
परिऽप्रयाथ
सुप्रयावऽभिः
वृषऽप्रयाव्ने
अप्रऽयुच्छतः
अप्रयुच्छत्ऽभिः
अप्रऽयुच्छन्
अप्रऽयुताम्
अप्रयुत्वऽभिः
दासऽप्रवर्गम्
सुऽप्रवाचनम्
सुऽप्रवाचनाः
ऋतऽप्रवीतम्
अप्रऽवीता
अप्रऽवीताः
चोदऽप्रवृद्धः
अतिऽप्रशर्धयत्
कविऽप्रशस्तः
पुरुऽप्रशस्तः
पुरुऽप्रशस्तम्
पुरुऽप्रशस्ता
अप्रऽशस्ताः
अप्रशस्ताःऽइव
अप्रऽशस्तान्
वरुणऽप्रशिष्टाः
सम्ऽप्रश्नम्
घृतऽप्रसत्तः
दीर्घऽप्रसद्मनि
वाजऽप्रसूता
इन्द्रऽप्रसूताः
बृहस्पतिऽप्रसूताः
वाजऽप्रसूताः
हर्यश्वऽप्रसूताः
अप्रतिऽस्कुतः
अप्रतिऽस्कुतम्
परिऽप्रस्यन्दते
पुरःऽप्रस्रवणाः
अप्रऽहनम्
अप्रऽहितम्
कक्ष्यऽप्रा
अन्तरिक्षऽप्राः
क्रतुऽप्राः
चर्षणिऽप्राः
जरणिऽप्राः
रोदसिऽप्राः
सुऽप्राड्
अपिऽप्राणी
अन्तरिक्षऽप्राम्
कक्ष्यऽप्राम्
चर्षणिऽप्राम्
रथऽप्राम्
रोदसिऽप्राम्
अप्रामिऽसत्य
अप्रायुऽभिः
प्रायेऽप्राये
सुऽप्रावर्गम्
क्रतुऽप्रावा
पुरुऽप्रिय
हरिऽप्रिय
अभिऽप्रियः
परिऽप्रियः
पुरुऽप्रियः
कुधऽप्रियः
अभिऽप्रियम्
ब्रह्मऽप्रियम्
पुरुऽप्रियम्
प्रियम्ऽप्रियम्

पुरुऽप्रिया
अध्वऽप्रिया
यज्ञऽप्रिये
कण्वऽप्रिये
पुरुऽप्रिये
परिऽप्रीतः
सुऽप्रीतः
परिऽप्रीता
मनुऽप्रीतासः
उद्ऽप्रुतः
उद्ऽप्रुतम्
उपऽप्रुतम्
विऽप्रुतम्
कृष्णऽप्रुतौ
अन्तरिक्षप्रुत्ऽभिः
प्रऽप्रुथ्य
अभ्रऽप्रुषः
घृतऽप्रुषः
परिऽप्रुषः
घृतऽप्रुषम्
घृतऽप्रुषा
आऽप्रुषायन्
कामप्रेणऽइव
सुऽप्रैतुः
पुरुऽप्रैषः
पुरुऽप्रैषाः
अपऽप्रोथन्तः
अप्रोषिऽवान्
रथऽप्रोष्ठेषु
कशऽप्लकौ
घृतऽप्स्नः
देवप्सरःऽतमः
सुप्सरःऽतमम्
देवप्सरःऽतमम्
मधुऽप्सरसः
देवऽप्सराः
अप्सवः
अरुणऽप्सवः
अद्भुतऽप्सवः

प्रुषितऽप्सवः
वृषऽप्सवः
विश्वऽप्सु
अरुणऽप्सुः
विश्वऽप्सुः
वृषऽप्सुना
प्रुषितप्सुऽभिः
अरुणऽप्सुम्
प्रुषितऽप्सुम्
विश्वऽप्सुम्
ऋतप्सू इत्यृतऽप्सू
विश्वऽप्स्न्यः
विश्वऽप्स्न्यस्य
विश्वऽप्स्न्याय
प्रऽफर्व्यम्
सुऽफला
अफलाः
अफलाम्
अनिऽबद्धः
सुऽबद्धाम्
अबधिरम्
विऽबध्नते
अबन्धनः
पूतऽबन्धनी
सुऽबन्धवः
अबन्धवः
अमृतऽबन्धवः
गोऽबन्धवः
मृत्युऽबन्धवः
वाजऽबन्धवः
सऽबन्धवः
सुऽबन्धवे
ऋषिऽबन्धवे
द्विऽबन्धुः
सुऽबन्धुः
त्रिऽबन्धुः
तत्ऽबन्धुः
मृत्युऽबन्धुः
यज्ञऽबन्धुः

शुचिऽबन्धुः
अबन्धुना
सुऽबन्धुम्
पूतबन्धू इति पूतऽबन्धू
सबन्धू इति सऽबन्धू
समानबन्धू इति समानऽबन्धू
पृष्टबन्धो इति पृष्टऽबन्धो
सुबन्धो इति सुऽबन्धो
सुऽबन्धोः
देवऽबन्धोः
विऽबबाधे
विऽबभाज
आऽबभूथ
आऽबभूव
परिऽबभूव
उपऽबर्बृहत्
उपऽबर्हणम्
उपऽबर्हणीम्
निऽबर्हयः
द्विऽबर्हसः
द्विऽबर्हसम्
द्विऽबर्हाः
अद्रिऽबर्हाः
स्तीर्णऽबर्हिः
वृक्तऽबर्हिषः
वृक्तऽबर्हिषः
सद्मऽबर्हिषः
सुऽबर्हिषः
सुऽबर्हिषम्
चित्रऽबर्हिषम्
वृक्तऽबर्हिषम्
त्रिऽबर्हिषि
वृक्तऽबर्हिषे
स्तीर्णऽबर्हिषे
सऽबलः
अबलाः
इषुऽबलाः
उदुम्बली

निऽबाळ्हः
सुऽबाधः
परिऽबाधः
सुऽबाधः
आऽबाधः
विऽबाधः
तुविऽबाधम्
अपऽबाधमानः
परिऽबाधमानः
सुऽबाधसः
सम्ऽबाधात्
अबाधितः
निऽबाधितम्
प्रऽबाधिता
अनिऽबाधे
विऽबाध्ये
प्रऽबाबधाना
जिह्मऽबारम्
नीचीनऽबारम्
नीचीनऽबारे
विऽबाल्यम्
उग्रऽबाहवः
सुऽबाहुः
उग्रऽबाहुः
वज्रऽबाहुः
विश्वतःऽबाहुः
हिरण्यऽबाहुः
नृबाहुऽभ्याम्
वज्रऽबाहुम्
वज्रबाहू इति वज्रऽबाहू
वज्रबाहो इति वज्रऽबाहो
सुबाहो इति सुऽबाहो
सहस्रऽबाहे
अबिभ्युषः
अबिभ्युषा
प्रतिऽबुद्धाः
उषःऽबुधः
उषःऽबुधम्
प्रऽबुधाम्
प्रऽबुधि
उषःऽबुधे
पृथुऽबुध्नः
अद्रिऽबुध्नः
चन्द्रऽबुध्नः
पृथुऽबुध्नः
उच्चाऽबुध्नम्
पृथुऽबुध्नम्
सप्तऽबुध्नम्
अश्वऽबुध्नाः
उपरिऽबुध्नान्
आस्त्रऽबुध्नाय
पृथुऽबुध्नासः
अबुध्ने
अबुध्नेषु
अबुध्यम्
अश्वऽबुध्यम्
अबुध्यमानम्
प्रतिऽबुध्यमानाः
अबुध्यमानाः
अबुध्यमाने इति
अश्वऽबुध्यान्
इन्द्राबृहस्पती इति
इन्द्राबृहस्पती इति
जराऽबोध
विऽबोधनम्
प्रऽबोधयन्ती
प्रऽबोधयन्तीः
निऽबोधात्
निऽबोधिषत्
उपब्दिः
शतऽब्रध्नः
अनवऽब्रवः
उपऽब्रवामहै
ब्रह्मऽब्रह्म
इन्द्राब्रह्मणस्पती इति
सुऽब्रह्मण्यम्
अब्रह्मता
सुऽब्रह्मा
अब्रह्मा
कृतऽब्रह्मा
अब्रह्माणः
ओहऽब्रह्माणः
सुऽब्रह्माणम्
तुविऽब्रह्माणम्
अनुऽब्रुवाणः
प्रऽब्रुवाणः
प्रऽब्रुवाणा
उपऽब्रुवे
उपऽब्रूते
अभक्तम्
देवऽभक्तम्
सुऽभक्तम्
भगऽभक्तस्य
विऽभक्ता
विऽभक्ता
सुऽभक्ताः
विऽभक्तारम्
अभक्ते
जनऽभक्षः
धनऽभक्षेषु
सुऽभग
सुऽभगः
आऽभगः
सुभगऽत्वम्
सुऽभगम्
आऽभगम्
सुऽभगस्य
सुऽभगा
सुऽभगाः
सुऽभगान्
सुऽभगाम्
सुऽभगाय
सुऽभगासः
सुऽभगासः
सुऽभगे
सुऽभगे
सुऽभगे

सुभगे इति सुऽभगे
सुभगे इति सुऽभगे
प्रऽभङ्गम्
अभिऽभङ्गाय
प्रऽभङ्गी
विऽभजन्
विऽभजन्तः
विऽभजन्तम्
विऽभजासि
अभिऽभञ्जतीनाम्
प्रऽभञ्जन्
विऽभञ्जनुः
भद्रम्ऽभद्रम्
सुऽभद्रम्
सुऽभद्राम्
अभयतमेन
अभयम्
अभयम्ऽकरः
अभयानाम्
अभयानि
अभये
सुऽभरः
वाजम्ऽभरः
सम्ऽभरः
सहस्रम्ऽभरः
सुतम्ऽभरः
हरिम्ऽभरः
सम्ऽभरणम्
सम्ऽभरन्ति
सुऽभरम्
वाजम्ऽभरम्
सहस्रऽभरम्
सऽभरसः
विश्वऽभरसम्
विऽभराः
सुऽभराः
सऽभराः
वृषऽभरान्
सुऽभराम्
पुष्टिम्ऽभराय
सहःऽभरिः
भरेऽभरे
सहस्रऽभर्णसम्
अपऽभर्तवै
अपऽभर्ता
प्रऽभर्ता
प्रऽभर्तुम्
अनुऽभर्त्री
प्रऽभर्मणि
अरिष्टऽभर्मन्
वाजभर्मऽभिः
जातुऽभर्मा
वृषऽप्रभर्मा
सुऽभर्वाः
विऽभवः
प्रऽभवः
जञ्जणाऽभवन्
प्रऽभवन्तम्
अललाऽभवन्तीः
सचाऽभवम्
शम्ऽभविष्ठः
शम्ऽभविष्ठा
शम्ऽभविष्ठाः
सुभसत्ऽतरा
अभिऽभा
दूरेऽभाः
अभागः
सुऽभागाः
सुऽभागान्
विऽभागे
गोऽभाजः
पितुऽभाजः
पूर्वऽभाजः
रत्नऽभाजः
वामऽभाजः
अभाजः
पूर्वऽभाजम्
प्रथमऽभाजम्
श्वात्रऽभाजा
विऽभाति
विऽभाती
विऽभातीः
विऽभातीनाम्
विऽभातीम्
अहिऽभानवः
चित्रऽभानवः
स्वऽभानवः
स्वऽभानवः
स्वऽभानवे
विऽभानाम्
चित्रऽभानुः
बृहत्ऽभानुः
स्वःऽभानुः
चित्रऽभानुम्
विश्वऽभानुषु
चित्रभानो इति चित्रऽभानो
चित्रभानो इति चित्रऽभानो
बृहद्भानो इति बृहत्ऽभानो
विभानो इति विऽभानो
स्वभानो इति स्वऽभानो
स्वःऽभानोः
भूरिऽभारः
मुष्कऽभारः
अनूर्ध्वऽभासः
सुऽभासम्
आऽभासि
प्रऽभासि
विऽभासि
मांसऽभिक्षाम्
अद्रिऽभित्
उत्ऽभित्
गोत्रऽभित्
पूःऽभित्
पूर्भित्ऽतमम्
उत्ऽभिदः
उत्ऽभिदम्
गोत्रऽभिदम्

पुःऽभिदम्
उत्ऽभिदा
विऽभिद्य
पुःऽभिद्यम्
पुःऽभिद्ये
विऽभिनत्ति
विऽभिन्दुता
विऽभिन्दन्
विऽभिन्दुना
विभिन्दो इति विऽभिन्दो
विऽभिन्नम्
अभिन्ने
अवद्यऽभिया
विऽभीदकः
अभीरवः
अभीरुः
अभीर्वम्
विऽभीषणः
प्रऽभु
मयःऽभु
विऽभु
शम्ऽभु
सुऽभु
प्रऽभुः
मयःऽभुः
विऽभुः
शम्ऽभुः
अप्रऽभुः
अभुक्
स्तनऽभुजः
परिऽभुजत्
सम्ऽभुजम्
पुरुऽभुजा
पुरुऽभुजा
दशऽभुजिः
शतऽभुजिः
शतभुजिऽभिः
अभुञ्जतः
प्रऽभुञ्जती

उषःऽभुत्
मयःऽभुना
विभुऽभिः
प्रऽभुम्
विऽभुम्
आऽभुवः
परिऽभुवः
पुनःऽभुवः
मयःऽभुवः
शम्ऽभुवः
सचाऽभुवः
सुऽआभुवः
मयःऽभुवः
आऽभुवत्
आऽभुवम्
मयःऽभुवम्
शम्ऽभुवम्
सचाऽभुवम्
सुऽआभुवम्
पुनःऽभुवा
मयःऽभुवा
शम्ऽभुवा
सचाऽभुवा
सुऽआभुवा
शम्ऽभुवा
अभिऽभुवे
विश्वऽभुवे
सचाऽभुवे
शंभू इति शम्ऽभू
पुरुभू इति पुरुऽभू
शंभू इति शम्ऽभू
अभिऽभूः
परिऽभूः
पुनःऽभूः
पुरःऽभूः
मयःऽभूः
सचाऽभूः
स्वयम्ऽभूः
प्रऽभूतः

विऽभूतम्
परिऽभूतमम्
रुऽभूतमा
[illegible]ऽभूतयः
प्रऽभूतये
अभिऽभूतरम्
प्रऽभूता
अभिऽभूति
अभिभूतिऽओजाः
अभिऽभूतिः
विऽभूतिः
परिभूतिऽभिः
अभिऽभूतिम्
विऽभूतिम्
अप्रऽभूती
प्रऽभूती
प्रभूती इति प्रऽभूती
अननुऽभूतीः
अभिऽभूते
प्रऽभूतौ
आऽभूत्या
मयःऽभून्
आऽभूमिः
द्यावाभूमी इति
द्यावाभूमी इति
अभिऽभूय
भूयःऽभूयः
अभिऽभूवरी
प्रऽभूषणि
प्रतिऽभूषतः
प्रऽभूषतः
आऽभूषति
परिऽभूषति
प्रतिऽभूषति
विऽभूषति
प्रतिऽभूषथ
प्रऽभूषन्
विऽभूषन्
आऽभूषन्तः

आऽभूषन्तीः
आभूषु
पुरुऽभूषु
आऽभूषेण्यम्
प्रतिऽभूषेम
औवंभृगुऽवत्
भारऽभृत्
यक्षऽभृत्
वज्रऽभृत्
श्येनऽभृत
पितुऽभृतः
आऽभृतः
प्रऽभृतः
विऽभृतः
श्येनऽआभृतः
सम्ऽभृतः
सुऽभृतः
उक्थऽभृतम्
सामऽभृतम्
अनुऽभृतम्
आऽभृतम्
उत्ऽभृतम्
निऽभृतम्
पराऽभृतम्
प्रऽभृतम्
सम्ऽभृतम्
सुऽभृतम्
सऽभृतयः
दुःऽभृतयै
प्रतिऽभृतस्य
प्रऽभृतस्य
सम्ऽभृतस्य
सुऽभृतस्य
आऽभृता
प्रऽभृता
प्रतिऽभृता
विऽभृता
सम्ऽभृता
प्रऽभृताः

उपऽआभृति
इध्मऽभृतिः
प्रऽभृतिम्
विभृते इति विऽभृते
सम्ऽभृतैः
प्रऽभृतौ
आऽभृत्य
विऽभृत्रः
विऽभृत्रम्
विऽभृत्राः
विऽभृत्वा
अवऽभृथम्
प्रऽभृथस्य
प्रऽभृथे
प्रऽभृथेषु
अनिऽभृष्टः
अनिभृष्टऽतविषिः
तिग्मऽभृष्टिः
सहस्रऽभृष्टिः
चतुःऽभृष्टिम्
पिशङ्गऽभृष्टिम्
सहस्रऽभृष्टिम्
जलाषऽभेषजः
विश्वऽभेषजः
जलाषऽभेषजम्
विश्वऽभेषजीः
प्रऽभोः
आऽभोगम्
आऽभोगयम्
आऽभोगयै
पुरुऽभोजः
मर्तऽभोजनम्
मर्तऽभोजना
अधिऽभोजना
पुरुऽभोजसः
पुरुऽभोजसम्
सुऽभोजसम्
विश्वऽभोजसम्
सुप्रऽभोजसम्

पुरुऽभोजसा
विश्वऽभोजसा
विश्वऽभोजाः
गिरिऽभ्रजः
अनवभ्रऽराधसः
विऽभ्राजते
विऽभ्राजन्
विऽभ्राजन्ते
विऽभ्राजमानः
विऽभ्राजमानान्
अग्निऽभ्राजसः
शुचिऽभ्राजाः
विऽभ्राट्
विश्वऽभ्राट्
अभ्रातरः
अभ्रातृव्यः
अभ्राताऽइव
विऽभ्राष्टिम्
विऽभ्वः
सुऽभ्वः
अभ्वः
विऽभ्वः
विऽभ्वः
विऽभ्वना
विऽभ्वने
विऽभ्वम्
सुऽभ्वम्
अभ्वम्
मातरिभ्वरीः
विऽभ्वा
विऽभ्वा
अभ्वा
अभ्वात्
विऽभ्वी
प्रऽभ्वीः
विऽभ्वीः
परिऽभ्वे
विऽभ्वे
सुऽभ्वै

परिऽमंसते
विऽमंहते
मक्षुऽमंक्षु
सुऽमख
जारयत्ऽमखः
सुऽमखम्
सत्यऽमखसम्
अदुःऽमखस्य
सुऽमखस्य
सुऽमखाः
सुऽमखाय
सुऽमखासः
प्रऽमगन्दस्य
तुविऽमघ
शतऽमघ
शतऽमघ
तुविऽमघः
शतऽमघः
तुविऽमघम्
श्रुतऽमघम्
सहस्रऽमघम्
तुविऽमघस्य
मंहिऽमघस्य
अश्वऽमघा
गोऽमघा
चित्रऽमघा
गोऽमघाः
ऋत्वाऽमघासः
तुविऽमघासः
चित्रऽमघे
सुऽमङ्गलः
सुऽमङ्गलम्
सुऽमङ्गलीः
अदुःऽमङ्गलीः
निःऽमजाम्
दुःऽमतयः
सुऽमतयः
सुऽमतये
चोदयत्ऽमति

दुःऽमतिः
सुऽमतिः
अदब्धव्रतऽप्रमतिः
अरमतिः
प्रऽमतिः
सुमतिऽभिः
दुःऽमतिम्
देवऽसुमतिम्
सुऽमतिम्
अतिऽमतिम्
अरमतिम्
प्रऽमतिम्
सुऽमती
दुःऽमतीः
सुऽमतीः
यातुऽमतीनाम्
दुःऽमतीनाम्
सुऽमतीनाम्
अनुऽमते
चोदयत्ऽमते
बृहत्ऽमते
महेऽमते
दुःऽमतौ
सुऽमतौ
सुऽमत्या
प्रऽमत्या
अनुऽमत्याः
समत्ऽसु
सुनिःऽमथा
उराऽमथिः
निःऽमथितः
वस्त्रऽमथिम्
हविःऽमथीनाम्
दुःऽमदः
सुऽमदः
विऽमदः
सुऽमदनस्य
अनुऽमदन्ति
सुऽमदम्

विऽमदस्य
गात्सऽमदाः
विऽमदाः
सुऽमदाम्
अनुऽमदाम
विऽमदाय
दुःऽमदासः
गात्सऽमदासः
उत्ऽमदिताः
मदेऽमदे
विऽमदेन
अनुऽमद्यमानः
सत्यऽमद्वा
विऽमध्यम्
अमध्यमासः
सिलिकऽमध्यमासः
विऽमध्ये
धृषत्ऽमनः
नृऽमनः
विश्वऽमनः
वृषऽमनः
सुऽमनसः
विश्वऽमनसः
सऽमनसः
अरऽमनसम्
चिकित्वित्ऽमनसम्
बोधित्ऽमनसा
सऽमनसा
महाऽमनसाम्
सुऽमनस्यमानः
सुऽमनस्यमाना
सुऽमनस्यमानाः
नृऽमनस्यसे
श्रद्धाऽमनस्या
नृऽमनाः
सुऽमनाः
ऋषिऽमनाः
गूर्तऽमनाः
बोधित्ऽमनाः

विऽमनाः
विश्वऽमनाः
वृषऽमनाः
श्रद्धाऽमनाः
विश्वऽमनुषाम्
अमन्तवः
दुःऽमन्तु
सुऽमन्तु
त्रिऽमन्तुः
अमन्तुः
सुमन्तुऽभिः
पुरुमन्तू इति पुरुऽमन्तू
सत्यऽमन्त्राः
उपऽमन्त्रिणः
निःऽमन्थतः
अधिऽमन्थनम्
अमन्दान्
प्रऽमन्दुः
पुरुऽमन्द्रा
विप्रऽमन्मनः
सुमन्मऽभिः
दुःऽमन्मा
सुऽमन्मा
यज्ञऽमन्मा
सत्यऽमन्मा
दुःऽमन्मानम्
अमन्यमानान्
सऽमन्यवः
अहिंऽमन्यवः
तुविऽमन्यवः
रघुऽमन्यवः
विऽमन्यवः
वृषऽमन्यवः
सऽमन्यवः
सुऽमन्यवः
परिऽमन्यवे
अनुत्तऽमन्युः
आपान्तऽमन्युः
व्रातऽमन्युः

सतीनऽमन्युः
उपऽमन्युम्
अनुत्तऽमन्युम्
हरिमन्युऽसायकः
अतिऽमन्यै
प्राचामन्यो इति प्राचाऽमन्यो
पुनःऽमन्यौ
प्रऽममर्ष
परिऽममृशुः
विऽममे
परिमम्नाथे इति परिऽमम्नाथे
सुऽमयम्
प्रऽमरस्य
अमरिष्णवः
आऽमरीता
एवयामरुत्
इन्द्रामरुतः
अमर्तः
अमर्त्यम्
अमर्त्यः
अमर्त्यम्
उपरिऽमर्त्यम्
अमर्त्यस्य
अमर्त्या
अमर्त्या
अमर्त्याः
अमर्त्ये
अमर्त्ये
अमर्त्येन
अमर्त्येषु
अमर्धन्तः
अमर्धन्ता
अमर्धन्तीः
परिऽमर्धिषत्
अमर्मणः
अनुऽमर्मृजानः
सऽमर्यः
सऽमर्यता
सऽमर्यम्

सऽमर्य
दुःऽमर्षम्
शिवऽअभिमर्शनः
महाऽमह
महाऽमहः
मित्रऽमहः
सुऽमहः
प्रऽमहसः
विऽमहसः
विऽमहसः
विद्युत्ऽमहसः
विश्वऽमहसः
सुऽमहसः
चित्रऽमहसम्
प्रऽमहसा
मित्रऽमहाः
वृद्धऽमहाः
सुऽमहान्
सतःऽमहान्तः
महाऽमहिव्रतम्
विऽमहीनाम्
अमहीयमानम्
प्रऽमा
प्रतिऽमा
सधऽमाः
सधऽमात्
अभिऽमातयः
उपऽमातयः
अभिऽमातये
सुऽमातरः
गोऽमातरः
पृश्निऽमातरः
पृश्निऽमातरः
सिन्धुऽमातरः
अद्रिऽमातरम्
सप्तऽमातरम्
सिन्धुऽमातरम्
सम्ऽमातरा
इहेहऽमातरा

सिन्धुऽमातरा
त्रिऽमाता
द्विऽमाता
सिन्धुऽमाता
अभिऽमाति
अभिऽमातिः
उपऽमातिः
अभिऽमातिनम्
अभिऽमातिम्
उपऽमातिम्
उपमातिऽवनिः
अभिऽमातिषु
अभिमातिऽसहः
अभिमातिऽसहः
अभिमातिऽसहम्
अभिमातिऽसहम्
अभिमातिऽहनम्
अभिमातिऽहा
अभिऽमातीः
सप्तमातृऽभिः
उपऽमाते
उपमात्ऽइव
अमात्रम्
तुविऽमात्रम्
यावत्ऽमात्रम्
परःऽमात्रम्
सधऽमादः
सोमऽमादः
देवऽमादनः
नृऽमादनः
देवऽमादनम्
नृऽमादनम्
इन्द्रऽमादनासः
उपऽमादम्
प्रऽमादम्
सधऽमादम्
सधऽमादे
सधऽमादेषु
अनुऽमाद्यः

सधऽमाद्यः
अनुऽमाद्यस्य
सधऽमाद्या
सधऽमाद्यानि
अनुऽमाद्यासः
सधऽमाद्यासः
विऽमानः
अनिऽमानः
प्रतिऽमानम्
विऽमानम्
अप्रतिऽमानम्
देवऽमानम्
देवमानाऽइव
प्रतिऽमानानि
विऽमानीम्
अमानुषः
विश्वऽमानुषः
सप्तऽमानुषः
अमानुषम्
अमानुषीषु
विऽमाने
विऽमाय
सम्ऽमाय
पुरुऽमायः
पुरुऽमायम्
दशऽमायम्
विऽमायम्
दुःऽमायवः
पुरुऽमायस्य
अहिऽमायस्य
सुऽमायाः
अहिऽमायाः
निःऽमायाः
सुऽमायाः
अहिऽमायान्
एहिऽमायासः
अजऽमायुः
गोऽमायुः
पुरुऽमाय्यम्

सुऽमारुतम्
अवऽमार्जनानि
सूर्यामासा
मासिऽमासि
दशऽमास्य
दशऽमास्यः
उपऽमित्
अमितम्
अमिता
निऽमिता
परिऽमिता
सुऽमिता
निमिताऽइव
अमिताः
अमितानि
विऽमितानि
निऽमितासः
सुऽमिती
सुमिते इति सुऽमिते
अमितैः
दुःऽमित्रः
सुऽमित्रः
हितऽमित्रः
अमित्रऽखादः
अमित्रऽदम्भनः
अमित्रऽदम्भनम्
अमित्रम्
अमित्रऽयन्तम्
अमित्रया
अमित्रऽयुधः
अमित्रस्य
पुरुऽमित्रस्य
अमित्रऽहन्
अमित्रऽहा
अमित्राः
सुऽमित्राः
अमित्रान्
द्रोघऽमित्रान्
दुःऽमित्रासः

अमित्रिणे
अमित्रियम्
अमित्रिया
सुऽमित्रेभिः
अमित्रेषु
सुऽमित्रेषु
अमित्रैः
सुऽमित्र्याः
अमिथितः
प्रऽमिनतः
प्रऽमिनती
अमिनती
अमिनती इति
अमिनते
प्रऽमिनन्ति
प्रऽमिनाति
प्रऽमिनानः
आऽमिनाना
आमिनाने इत्याऽमिनाने
प्रऽमिनाम
विऽमिन्वन्
अविश्वऽमिन्वम्
अविश्वऽमिन्वाम्
विऽमिमानः
सम्ऽमिमिक्षथुः
उपऽमिमीहि
निऽमिम्युः
प्रऽमियम्
प्रऽमिये
निऽमिश्लः
सम्ऽमिश्लः
आमिश्लऽतमः
सम्ऽमिश्लाः
निऽमिश्लाम्
सम्ऽमिश्लासः
निऽमिषः
अनिऽमिषः
निऽमिषतः
अनिमिषत्ऽभिः

अनिऽमिषन्तः
अनिऽमिषम्
अनिऽमिषम्
अनिऽमिषा
अनिऽमिषाः
निऽमिषि
अनिऽमिषेण
मन्युऽमीः
पुरुऽमीळ्ह
पुरुऽमीळ्हः
पुरुऽमीळ्हस्य
स्वःऽमीळ्हस्य
पुरुऽमीळ्हाय
भाजऽमीळ्हासः
सुऽमीळ्हे
सहस्रऽमीळ्हे
स्वःऽमीळ्हे
स्वःऽमीळ्हेषु
अमीतऽवर्णाः
प्रऽमीयसे
सम्ऽमील्य
विश्वतःऽमुख
विश्वतःऽमुखः
विऽमुचः
विऽमुचन्ति
अंहःऽमुचम्
विऽमुचम्
विऽमुच्य
प्रऽमुञ्चन्
प्रऽमुदः
आऽमुरः
अभिऽप्रमुरा
आऽमुरिम्
सहस्रऽमुष्क
सहस्रऽमुष्कम्
ऋजुऽमुष्काः
ऋजुऽमुष्कान्
आऽमुष्य
कामऽमूता

अमूर
अमूर
अमूरः
अमूरम्
अमूरा
अप्रऽमूराः
अमूराः
सहऽमूरान्
तपुःऽमूर्धा
तिग्मऽमूर्धानः
त्रिऽमूर्धानम्
सहऽमूलम्
अमृक्तः
अमृक्तम्
अमृक्ता
अमृक्ताः
अमृक्ते इति
अमृक्तेन
निऽमृग्राः
निऽमृजन्तः
सुऽमृळीकः
सुऽमृळीकाः
सुऽमृळीकान्
सुऽमृळीकाम्
सुऽमृळीकाय
प्रऽमृणः
प्रऽमृणन्
प्रऽमृणन्तम्
अमृत
अमृत
अमृतः
अमृतऽत्वम्
अमृतऽत्वस्य
अमृतऽत्वाय
अमृतऽत्वे
अमृतऽबन्धवः
अमृतम्
अमृतस्य
अमृता

अमृता
अमृताः
अमृताः
अमृताः
अमृतात्
अमृतात्ऽइव
अमृतान्
अमृतानाम्
अमृतानि
अमृताम्
अमृताय
अमृतासः
अमृतासः
अमृतासु
अमृते
अमृते इति
अमृतेन
अमृतेभिः
अमृतेषु
अमृत्यवः
अमृत्यु
विऽमृधः
अमृध्रः
अमृध्रम्
अमृध्राः
अमृध्राम्
अमृध्रे इति
विऽमृशन्तः
अभिऽमृशे
अनुऽमृश्य
प्रऽमृषे
असम्ऽमृष्टः
विऽमृष्टम्
अप्रऽमृष्यः
अप्रऽमृष्यम्
प्रऽमे
सुऽमेकः
सुऽमेकम्
सुमेके इति सुऽमेके
निऽमेघमानः
निऽमेघमानाः
उद्ऽमेघे
नृऽमेधः
पुरुऽमेधः
सुऽमेधः
प्रियऽमेधः
नृऽमेधम्
प्रियऽमेधम्
सुऽमेधसः
सुऽमेधसम्
प्रियमेधऽस्तुता
आश्वऽमेधस्य
अश्वऽमेधस्य
सुऽमेधाः
प्रियऽमेधाः
प्रियऽमेधाः
मितऽमेधाभिः
सुऽमेधाम्
अश्वऽमेधाय
गृहऽमेधासः
प्रियऽमेधासः
प्रियऽमेधासः
गृहऽमेधीयम्
आश्वऽमेधे
अश्वऽमेधे
प्रियऽमेधैः
अमेनान्
आऽमेन्यस्य
आमेन्याने इत्याऽमेन्याने
अनिऽमेषम्
प्रतिऽमै
विऽमोचन
विऽमोचनम्
विऽमोचनात्
विऽमोचने
चर्मऽम्नाः
मन्युऽम्यः
तुविऽम्रक्षः
तुविऽम्रक्षासः
ऊर्णऽम्रदाः
निऽम्रुचः
निऽम्रुचि
अनभिम्लातऽवर्णः
अपऽम्लुक्तम्
प्रयक्षऽतमम्
प्रऽयक्षन्
प्रऽयक्षे
अयक्ष्माः
अज्ञातऽयक्ष्मात्
राजऽयक्ष्मात्
अनुऽयच्छमाना
अनुऽयच्छमानाः
प्रऽयच्छसि
दिविऽयजः
पृक्षऽप्रयजः
आऽयजन्ते
सम्ऽयजन्ते
सत्यऽयजम्
सुऽयजम्
आऽयजसे
आऽयजाते
आऽयजिम्
आऽयजिष्ठः
आयजी इत्याऽयजी
सुऽयज्ञः
अयज्ञम्
यज्ञम्ऽयज्ञम्
अयज्ञऽसाचः
यज्ञस्यऽयज्ञस्य
यज्ञाऽयज्ञा
सुऽयज्ञाः
अयज्ञान्
पितृऽयज्ञाय
अयज्ञियात्
यज्ञेऽयज्ञे
देवऽयज्यया
आऽयज्यवः

अयज्यवः
प्रऽयज्यवः
प्रऽयज्यवः
प्रऽयज्यवे
देवऽयज्या
देवऽयज्याय
अयज्युम्
दीर्घऽप्रयज्युम्
अयज्यून्
प्रऽयज्यून्
प्रयज्यो इति प्रऽयज्यो
अयज्योः
प्रऽयज्योः
अयज्वनः
अस्तृतऽयज्वनः
अयज्वनाम्
पृष्ठऽयज्वने
अभ्यर्धऽयज्वा
अयज्वानः
अयज्वानम्
आऽयत्
उत्ऽयत्
सम्ऽयतः
सम्ऽयतः
आऽयतः
उत्ऽयतः
सुऽयतः
अयतन्ता
सम्ऽयतम्
अनुऽयतम्
आऽयतम्
उत्ऽयतम्
निऽयतम्
प्रऽयतम्
विऽयतम्
प्रऽयतस्य
सम्ऽयता
आऽयता
उत्ऽयता
निऽयता
प्रऽयता
प्रऽयताः
प्रऽयतान्
उत्ऽयतानि
प्रऽयतानि
आऽयताम्
स्वऽयतायै
स्वऽयतासः
प्रऽयतासु
उत्ऽयति
प्रऽयति
पराऽयतिः
आऽयतिः
प्रऽयतिः
उत्ऽयतिम्
प्रऽयतिम्
अवऽयती
आऽयती
पराऽयती
प्रऽयती
संयती इति सम्ऽयती
प्रऽयती
आऽयतीः
आऽयतीनाम्
पराऽयतीनाम्
आऽयतीम्
पराऽयतीम्
आऽयते
असम्ऽयत्तः
परिऽयत्ताय
परायत्ऽभ्यः
प्रयत्ऽभ्यः
आऽयत्याः
यत्रऽयत्र
तुर्वशायदू इति
अयथम्
यथाऽयथा
आऽयन्
उत्ऽयन्
उपऽप्रयन्
पराऽयन्
परिऽयन्
प्रऽयन्
उपऽयन्तः
उपऽप्रयन्तः
विऽयन्तः
विऽप्रयन्तः
प्रऽयन्तः
अपिऽयन्तम्
आऽयन्तम्
उत्ऽयन्तम्
उपऽयन्तम्
परिऽयन्तम्
परिऽप्रयन्तम्
प्रऽयन्तम्
प्रतिऽयन्तम्
दुःऽनियन्तवः
विऽयन्ता
निऽयन्ता
प्रऽयन्ता
उत्ऽयन्ता
आऽयन्तारम्
प्रऽयन्तारा
आऽयन्ति
उपऽयन्ति
प्रऽयन्ति
विऽयन्ति
सम्ऽयन्ति
सुयन्तुऽभिः
दशऽयन्त्रम्
दशऽयन्त्रासः
पुरवऽयन्त्रासः
श्लोकऽयन्त्रासः
अयन्त्रैः
यम्ऽयम्
सुऽयमः
सुऽयमम्

सुऽयमस्य
सुऽयमा
सुऽयमाः
सुऽयमात्
सुऽयमासः
उत्ऽयमीयसी
सुऽयमेभिः
प्रऽयम्यमानान्
आऽयय
निऽयथिनम्
आऽययुः
निऽयवम्
यवम्ऽयवम्
प्रऽयवयन्
सुऽयवसः
सुऽयवसम्
सुऽयवसाः
सुयवसिनी इति सुऽयवसिनी
सुऽयवसे
सुयवस्यू इति सुऽयवस्यू
स्वऽयशः
स्वयशःऽतरः
स्वयशःऽतरम्
स्वयशःऽभिः
स्वऽयशसः
स्वऽयशसम्
दीर्घऽयशसे
स्वऽयशसे
स्वऽयशाः
प्रऽयस्ता
अवऽयाः
ऋणऽयाः
एवऽयाः
तुरऽयाः
देवऽयाः
प्रऽयाः
अनुऽयाजः
जीवऽयाजम्
अतिऽयाजस्य

अनुऽयाजाः
प्रऽयाजाः
अनुऽयाजान्
प्रऽयाजान्
प्रऽयाजे
अतिऽआयातम्
श्वऽयातवः
अवऽयाता
अवऽयाताम्
अनुऽयाति
उपऽयाति
परिऽयाति
विऽयाति
अयातुः
शतऽयातुः
अयातुम्
उलूकऽयातुम्
कोकऽयातुम्
गृध्रऽयातुम्
शुशुलूकऽयातुम्
श्वऽयातुम्
सुपर्णऽयातुम्
परिऽप्रयाथ
अतिऽयाथः
उपऽयाथः
परिऽयाथः
प्रऽयाथन
दीर्घऽयाथे
दीर्घऽयाथैः
अवऽयानम्
देवऽयानम्
निऽयानम्
पितृऽयानम्
प्रऽयानम्
देवऽयानाः
देवऽयानात्
देवऽयानान्
देवऽयानीः
आऽयानैः

प्रऽयानैः
देवऽयानैः
अयामन्
पृथुऽयामन्
प्रवत्ऽयामना
प्रऽयामनि
यामनिऽयामनि
अखिद्रयामऽभिः
कृष्णऽयामम्
चित्रऽयामम्
पञ्चऽयामम्
रघुऽयामा
हृष्टऽयामा
उस्रऽयामा
द्युतत्ऽयामा
शुभ्रऽयामा
सहस्रऽयामा
सुऽयामाः
त्वेषऽयामाः
द्युतत्ऽयामानम्
पृक्षऽयामेषु
शतऽयाम्ना
अनुस्रऽयाम्ने
उस्रऽयाम्ने
एवऽयावः
एवऽयावः
स्वऽयावन्
एवयावऽभिः
प्रातर्यावऽभिः
सयावऽभिः
सुप्रयावऽभिः
एवऽयावरी
श्वेतऽयावरी
सऽयावरी
सऽयावरीः
अग्रऽयावा
ऋणऽयावा
देवऽयावा
पूर्वऽयावा

शुभम्ऽयावा
अक्ष्णऽयावानः
प्रातःऽयावानः
शुभम्ऽयावानः
पुरःऽयावानम्
प्रातःऽयावानम्
सऽयावानम्
प्रातःऽयावाना
रथऽयावाना
शुभ्रऽयावाना
एवऽयाम्नः
प्रातःऽयाम्नः
बुद्बुदऽयाशवः
सुयाशुऽतरा
उपऽयासि
परिऽयासि
अयास्यः
अतिऽआयाहि
प्रयियोः
ऋतऽयुक्
सऽयुक्
सुऽयुक्
अयुक्तम्
अयुक्ताः
देवऽयुक्ताः
स्वऽयुक्ताः
सुऽयुक्तान्
अयुक्तासः
प्रऽयुक्ति
प्रऽयुक्तिः
स्वयुक्तिऽभिः
ऋतऽयुक्तिम्
प्रऽयुक्तिषु
अरुणयुक्ऽभिः
ऋतयुक्ऽभिः
सुयुक्ऽभिः
स्वयुक्ऽभिः
चतुःऽयुगः
त्रिऽयुगम्

उरुऽयुगे
युगेऽयुगे
अभिऽयुग्वना
स्वयुग्वऽभिः
सुऽयुग्वा
प्रऽयुच्छतः
अप्रऽयुच्छतः
अप्रयुच्छत्ऽभिः
अप्रऽयुच्छन्
अभिऽयुजः
अश्वऽयुजः
चतुःऽयुजः
दुःऽयुजः
प्रऽयुजः
ब्रह्मऽयुजः
मनःऽयुजः
मित्रऽयुजः
रथऽयुजः
सऽयुजः
सुऽयुजः
स्वऽयुजः
अयुजः
प्रातःऽयुजम्
मनःऽयुजम्
युवाऽयुजम्
रथऽयुजम्
सऽयुजम्
सुऽयुजम्
प्रातःऽयुजा
ब्रह्मऽयुजा
मनःऽयुजा
वचःऽयुजा
सऽयुजा
साकम्ऽयुजा
सुऽयुजा
रक्षःऽयुजे
सम्ऽयुजे
प्रऽयुञ्जती
यविऽयुत्

द्वेषःऽयुतः
निऽयुतः
प्रऽयुतः
द्वेषःऽयुतम्
निऽयुतम्
प्रऽयुतम्
निऽयुता
विऽयुता
प्रऽयुताः
विऽयुताः
निऽयुताम्
अप्रऽयुताम्
प्रऽयुताम्
प्रऽयुती
वियुते इति विऽयुते
नियुत्ऽभिः
अप्रयुत्वऽभिः
अयुद्धः
अयुद्धऽसेनः
अमित्रऽयुधः
गोषुऽयुधः
प्रऽयुधः
वृषऽयुधः
गोषुऽयुधम्
पुरःऽयुधा
यविऽयुधा
अयुध्यः
अयुध्यः
अभिऽयुध्याः
अयुध्वी
आऽययुत्रे
आऽययुवे
मधुऽयुवा
निःऽयुवानः
निऽयुवाना
नियुवैते इति निऽयुवैते
शंयूहवेति शंयूऽइव
स्थूरयूपऽवत्
अश्वऽयूपाय

हरिऽयूपीयायाम्
आऽयूय
निऽयूय
विऽयूय
शुभम्ऽये
आऽयेजे
आऽयेमिरे
निऽयेमिरे
विऽयेमिरे
अवऽयै
आऽयै
उपऽयै
प्रऽयै
शम्ऽयोः
दशऽयोक्त्रेभ्यः
प्रऽयोगम्
हरिऽयोगम्
अश्वऽयोगाः
योगेऽयोगे
हारिऽयोजन
समानऽयोजनः
हारिऽयोजनम्
हरिऽयोजनाय
दशऽयोजनेभ्यः
प्रऽयोता
विऽयोतारः
पुरःऽयोधः
पुरःऽयोधा
कर्णऽयोनयः
द्विविऽयोनिः
पृषत्ऽयोनिः
सऽयोनिः
सत्यऽयोनिः
घृतऽयोनिम्
सादत्ऽयोनिम्
घृतयोनी इति घृतऽयोनी
सयोनी इति सऽयोनी
कृष्णऽयोनीः
सऽयोनीः

जनऽयोपनः
सम्ऽयोपयन्तः
आऽयोयुवानः
विऽयोषत्
वातऽरंहसः
वातऽरंहाः
अरक्षः
अभिऽरक्षति
अभिऽरक्षन्ति
अभिऽरक्षमाणाः
अरक्षसः
अरक्षसम्
अरक्षसा
अभिऽरक्षसि
पशुऽरक्षिः
पथिरक्षी इति पथिऽरक्षी
मदेऽरघुः
अरज्जुऽभिः
अरज्जौ
सुऽरणः
सुऽरणम्
सुतेऽरणम्
सुऽरणाः
सुऽरणानि
अविऽरणाय
धीऽरणासः
रणेऽरणे
निऽरण्यथः
महिऽरत्न
सुऽरत्नः
वाजऽरत्ना
सुऽरत्नाः
वाजऽरत्नाः
वाजऽरत्नाः
सुऽरत्नान्
वाजऽरत्नाम्
सुऽरत्नासः
पुरुऽरथः
सुऽरथः

अरिष्टऽरथः
चन्द्रऽरथः
ज्योतिःऽरथः
त्वेषऽरथः
नियुत्ऽरथः
पवित्रऽरथः
विद्युत्ऽरथः
वृषऽरथः
सुमत्ऽरथः
स्वनत्ऽरथः
हिरण्यऽरथः
सुऽरथम्
सुऽरथम्
नानाऽरथम्
पुरःऽरथम्
हिरण्यऽरथम्
अधिऽरथम्
चन्द्रऽरथम्
चित्रऽरथम्
ज्योतिःऽरथम्
बृहत्ऽरथम्
सुखऽरथम्
सुऽरथस्य
दशऽरथस्य
अजेऽरथस्य
सुऽरथा
सुऽरथा
बृहत्ऽरथा
सर्वऽरथा
अधिऽरथा
चन्द्रऽरथा
सुमत्ऽरथा
सुऽरथाः
अरथाः
चन्द्रऽरथाः
ज्योतिःऽरथाः
विद्युत्ऽरथाः
शुचत्ऽरथाः
हिरण्यऽरथाः

सुऽरथान्
अधिऽरथानि
श्रुतऽरथाय
सुऽरथासः
वृषऽरथासः
उद्धारथिः
अरथीः
शौचत्ऽरथे
प्रियऽरथे
श्रुतऽरथे
सुऽरथेभिः
अरध्रम्
अरध्रस्य
परिऽरपः
अरपः
अरपाः
विऽरप्शम्
विऽरप्शिन्
विऽरप्शिनः
विऽरप्शिनः
विऽरप्शिनम्
विऽरप्शिने
विऽरप्शी
सुऽसंरब्धाः
सोमरभःऽतरेभ्यः
आऽरभम्
आऽरभमाणा
गोऽरभसम्
सुरभि
आऽरभे
आऽरभ्य
सम्ऽरभ्य
अरममाणः
अवऽरम्बमाणः
आऽरम्भणम्
ऋधत्ऽरयः
मंहयत्ऽरयिः
सुमत्ऽरयिः
बृहत्ऽरयिम्

बृहत्ऽरये
सम्ऽरराणः
संरराणे इति सम्ऽरराणे
अररिऽवान्
अररुम्
अररुषः
अररुषे
तुविऽरवम्
तुविऽरवान्
वृषऽरवाय
विऽरवेण
वातऽरशनाः
यतऽरश्मयः
वृषऽरश्मयः
स्यूमऽरश्मये
अरश्मानः
स्थाःऽरश्मानः
इष्टऽरश्मिः
सऽरश्मिः
सप्तऽरश्मिः
सूर्यऽरश्मिः
सुऽरश्मिम्
पञ्चऽरश्मिम्
प्राचीनऽरश्मिम्
सप्तऽरश्मिम्
स्यूमऽरश्मौ
अरसम्
गर्भऽरसा
विऽराजः
सम्ऽराजः
स्वऽराजः
सम्ऽराज्ञः
विऽराजतः
विऽराजथ
सम्ऽराजन्तम्
ज्येष्ठऽराजम्
विऽराजम्
सम्ऽराजम्
स्वऽराजम्

अधिऽराजम्
वक्मराजऽसत्याः
प्रऽराजसि
सम्ऽराजा
सम्ऽराज्ञा
मित्राराजाना
विऽराजानि
अराजिनः
सम्ऽराजे
स्वऽराजे
सम्ऽराजोः
अप्नुऽराजौ
सम्ऽराजौ
जनऽराज्ञः
यमऽराज्ञः
सम्ऽराज्ञी
सोमऽराज्ञीः
दाशऽराज्ञे
स्वऽराज्यम्
साम्ऽराज्यस्य
साम्ऽराज्याय
विप्रऽराज्ये
समर्यऽराज्ये
स्वऽराज्ये
साम्ऽराज्येन
एकऽराट्
वनेऽराट्
विऽराट्
सम्ऽराट्
स्वऽराट्
सम्ऽराट्
सम्ऽराट्
सुऽरातयः
स्वादुऽरातयः
अरातयः
पूषऽरातयः
सऽरातयः
अरातिः
विसृष्टऽरातिः

श्रोतुऽरातिः
अरातिम्
अनर्शंऽरातिम्
मंहिष्ठऽरातिम्
विभूतऽरातिम्
अरातिऽवा
चित्ररा॑ती इति॑ चित्रऽराती
चित्रराती इति॑ चित्रऽराती
अरातीः
पिशङ्गऽराते
अरातेः
अरात्याः
अहोरात्राणि
अतिऽरात्रे
सत्यऽराधः
सत्यऽराधः
तुविऽराधसः
सुऽराधसः
अराधसः
अनवभ्रऽराधसः
अश्वऽराधसः
घृष्विऽराधसः
चित्रऽराधसः
राधसःऽराधसः
तुविऽराधसम्
सुऽराधसम्
अराधसम्
चित्रऽराधसम्
पङ्क्तिऽराधसम्
वीतिऽराधसम्
सुऽराधसा
सत्यऽराधसे
सुऽराधाः
सत्यऽराधाः
स्पार्हऽराधाः
प्रऽराध्यम्
यातऽराध्यम्
सुऽरामम्
निरामिणः

अरायासः
अरायि
अराय्यम्
अरावा
अराव्णः
अराव्णे
अभिऽराष्ट्रः
प्रऽरिक्ता
निऽरिणाति
निऽरिणानः
निऽरिणासि
पतिऽरिपः
अपिऽरिप्ताय
अरिप्रम्
अरिप्राः
आऽरिशामहे
अरिषण्यन्
अरिषण्या
अरिष्टः
अरिष्टऽगातुः
अरिष्टऽग्रामाः
अरिष्टऽतातये
अरिष्टतातिऽभिः
अरिष्टऽनेमिम्
अरिष्टम्
अरिष्टऽरथः
अरिष्टाः
अरिष्टान्
अरिष्टाभिः
अरिष्टाम्
अरिष्टिम्
अरिष्टेभिः
अरिष्टैः
अरिष्यन्तः
अरिष्यन्तम्
संरिहाणे इति सम्ऽरिहाणे
अरीळ्हम्
अकृत्तऽरुक्
विरुक्मतः

विरुक्मता
अधिऽरुक्मा
विरुक्मान्
सुरुक्मे इति सुऽरुक्मे
अरुग्णम्
अरुचः
दिवःऽरुचः
पुरुऽरुचः
वसुऽरुचः
सुऽरुचः
तनूऽरुचम्
पुरःऽरुचम्
सुऽरुचम्
तनूऽरुचा
सुऽरुचा
रुचाऽरुचा
आऽरुजः
वलम्ऽरुजः
आरुजत्नुऽभिः
आऽरुजन्तः
शफऽआरुजम्
आऽरुजम्
आऽरुजासि
आऽरुजे
अनूरुत्
अरुतऽहनुः
निऽरुद्धः
अवऽरुद्धः
निऽरुद्धाः
विऽरुद्धस्य
सोमारुद्रा
सोमारुद्रौ
अगोऽरुधाय
निऽरुध्य
आऽरुन्धानः
निऽरुन्धानः
निऽरुन्धानासः
आऽरुरुक्षतः
विऽरुरुत्सुः

उपऽआरुहः
आऽरुहम्
अरूक्षितम्
विऽरूप
पुरुऽरूपः
सुऽरूपः
अन्यऽरूपः
पिशङ्गऽरूपः
प्रतिऽरूपः
विश्वऽरूपः
विषुऽरूपः
संज्ञातऽरूपः
सुदृशीकऽरूपः
हिरण्यऽरूपः
पुरुऽरूपम्
पिशङ्गऽरूपम्
रूपम्ऽरूपम्
विऽरूपम्
विश्वऽरूपम्
विषुऽरूपम्
हिरण्यऽरूपम्
विश्वऽरूपस्य
पुरुऽरूपा
विऽरूपा
विषुऽरूपा
सऽरूपा
पुरुऽरूपाः
अग्निऽरूपाः
अनवद्यऽरूपाः
अन्यऽरूपाः
एकऽरूपाः
विऽरूपाः
विश्वऽरूपाः
सऽरूपाः
विषुऽरूपाणि
विश्वऽरूपाम्
विऽरूपासः
विरूपे इति विऽरूपे
विषुऽरूपे
विषुरूपे इति विषुऽरूपे
सऽरूपेण
विश्वऽरूपेभिः
विषुऽरूपेषु
सऽरूपैः
विश्वऽरूप्यम्
निरेकम्
निरेके
प्रऽरेके
सुऽरेक्णाः
प्रऽरेचनम्
आऽरेळिह
अरेणवः
अरेणु
बृहत्ऽरेणुः
अरेणुऽभिः
सुऽरेतः
सुऽरेतसम्
सुऽरेतसा
भूरिऽरेतसा
पर्जन्यऽरेतसे
सुऽरेताः
सहस्रऽरेताः
अरेपसः
अरेपसम्
अरेपसा
अरेपसौ
अरेपाः
विऽरोकिणः
विऽरोके
हृत्ऽरोगम्
अतिऽरोचते
विऽरोचमानः
अतिऽरोचमानम्
विऽरोचमानम्
प्रऽरोचयन्
विऽरोचयन्
स्वऽरोचिः
वसुऽरोचिषः
स्वऽरोचिषः
अवऽरोधनम्
आऽरोधनम्
आऽरोधनानि
आऽरोधने
मयूररोमऽभिः
अतिऽरोहति
अवऽरोहन्
आऽरोहन्
आऽरोहन्तम्
आऽरोहयन्ति
सऽलक्ष्मा
आऽलब्धम्
आऽलेभानात्
अनुऽआलेभिरे
जीवऽलोकम्
पतिऽलोकम्
उरुऽलोकम्
प्रतिऽलोभयन्ती
लोम्नःऽलोम्नः
नीलऽलोहितम्
अवंशात्
अवंशे
अधिऽवक्ता
अपऽवक्ता
उपऽवक्ता
उपवक्ताऽइव
अधिऽवक्तारम्
वीरऽवक्षणम्
रुक्मऽवक्षसः
रुक्मऽवक्षसः
प्रऽवक्ष्यामः
गूर्तवचःऽतमः
निऽवचनम्
निऽवचना
निऽवचनानि
विप्रऽवचसः
द्युक्षऽवचसम्
मतऽवचसा

सुऽवचस्याम्
गृतऽवचाः
मधुऽवचाः
सुऽवज्र
सुऽवज्रः
सुऽवज्रम्
सुऽवज्रा
सुऽउपवञ्चना
महाऽवटूरिणा
गिर्वणः
गिर्वणःऽतमः
गिर्वणःऽतमा
गिर्वणसम्
गिर्वणसे
सम्ऽवत्सम्
कृत्सऽवत्सम्
रुशत्ऽवत्सा
सहऽवत्सा
अवदतः
आऽवदन्
एवऽवदस्य
मिथःऽअवद्यपेभिः
अवद्यम्
अनवद्यऽरूपाः
अवद्यात्
अवद्यानि
अवद्ये
महाऽवधः
अवधम्
महाऽवधात्
तपुःऽवधेभिः
अवध्रम्
सुसऽवध्रये
सुसऽवध्रिः
सुसऽवध्रिम्
सम्ऽवननम्
सम्ऽवनना
वृश्चत्ऽवनम्
यज्ञऽवनसः
यज्ञऽवनसम्
उपमातिऽवनिः
ऋजुऽवनिः
वसुऽवनिम्
वृष्टिऽवनिम्
वनेऽवने
शातऽवनेये
प्रऽवन्तवे
देवऽवन्दैः
त्रिऽवन्धुरः
पूर्णऽवन्धुरः
सुप्रऽवन्धुरः
अष्टाऽवन्धुरम्
हिरण्यऽवन्धुरम्
त्रिऽवन्धुरे
त्रिऽवन्धुरेण
प्रऽवपन्तम्
गोऽवपुषः
अजकाऽवम्
अजावयः
वयःऽवयः
संवयन्ती इति सम्ऽवयन्ती
चतुःऽवयम्
वयम्ऽवयम्
अभिऽवयसः
सऽवयसः
सऽवयसा
आऽवयाः
त्रिऽवयाः
नीचाऽवयाः
प्रऽवयाः
वृद्धऽवयाः
अवयुनम्
आऽवरः
निऽवरः
सम्ऽवरणस्य
सम्ऽवरणात्
सम्ऽवरणानि
सम्ऽवरणेषु
साम्ऽवरणी
आऽवरत्
सुऽवरत्रम्
धारावराः
उत्ऽवरीवृजत्
मित्रावरुणः
इन्द्रावरुणयोः
मित्रावरुणयोः
इन्द्रावरुणा
मित्रावरुणा
इन्द्रावरुणा
इन्द्रावरुणा
मित्रावरुणा
मित्रावरुणा
मित्रावरुणाभ्याम्
इन्द्रावरुणौ
मित्रावरुणौ
इन्द्रावरुणौ
इन्द्रावरुणौ
मित्रावरुणौ
त्रिऽवरूथः
त्रिऽवरूथम्
त्रिऽवरूथेन
विऽवरे
सम्ऽवर्गम्
परिऽवर्गे
श्रेष्ठऽवर्चसः
सहस्रऽवर्चसम्
श्रेष्ठऽवर्चसा
समानऽवर्चसा
दस्मऽवर्चसाम्
सुऽवर्चाः
अनूनऽवर्चाः
दस्मऽवर्चाः
पावकऽवर्चाः
शुक्रऽवर्चाः
आऽवर्जते
हिरण्यऽवर्ण
अनभिम्लातऽवर्णः

मधुऽवर्णः
स्पृहयत्ऽवर्णः
हिरण्यऽवर्णः
धृषत्ऽवर्णम्
मधुऽवर्णम्
शुक्रऽवर्णम्
शुचिऽवर्णम्
हिरण्यऽवर्णम्
मधुऽवर्णा
हिरण्यऽवर्णा
सुऽवर्णीः
अमीतऽवर्णाः
चन्द्रऽवर्णाः
पावकऽवर्णाः
हिरण्यऽवर्णाः
हिरण्यऽवर्णान्
शुक्रऽवर्णाम्
सऽवर्णाम्
हिरण्यऽवर्णाम्
परिऽआवर्त्
निऽवर्त
अभिऽवर्तः
निऽवर्तत्
निऽवर्तन्
आऽवर्तनम्
निऽवर्तनम्
विऽवर्तनम्
द्विऽवर्तनिः
घृतऽवर्तनिः
रघुऽवर्तनिः
हिरण्यऽवर्तनिः
कृष्णऽवर्तनिम्
गायत्रऽवर्तनिम्
रघुऽवर्तनिम्
वृजिनऽवर्तनिम्
रुद्रवर्तनी इति रुद्रऽवर्तनी
रुद्रवर्तनी इति रुद्रऽवर्तनी
हिरण्यवर्तनी इति हिरण्यऽवर्तनी
प्रऽवर्तमानकः

परिऽवर्तमाने
प्रतिऽआवर्तय
सम्ऽवर्तयन्तः
आऽवर्तयन्ति
विऽवर्तयन्तीम्
अपऽवर्ता
त्रिऽवर्तु
दुःऽवर्तुः
सम्ऽवर्ते
अभिऽवर्तेन
अवत्रैः
उक्थऽवर्धनः
द्युम्नऽवर्धनः
नृम्णऽवर्धनः
पुष्टिऽवर्धनः
स्तोमऽवर्धनः
पुष्टिऽवर्धनम्
पशुऽवर्धनाय
उत्ऽवर्धयन्
घोरऽवर्पसः
प्रतिजूतिऽवर्पसः
भूरिऽवर्पसः
पुरुऽवर्पसम्
हरिऽवर्पसम्
भूरिऽवर्पसा
आऽवर्वृततीः
अभ्रऽवर्षाः
अकृषिऽवलाम्
शतऽवल्शः
सहस्रऽवल्शम्
सहस्रऽवल्शाः
आऽववर्तत्
आऽववर्तति
सम्ऽआववर्ति
अभिऽववृते
सम्ऽववृत्वत्
विऽववृधे
उत्ऽववृपाणः
विवव्री इति विऽवव्री

तत्ऽवशः
यथाऽवशम्
तत्ऽवशाय
वैभुऽवसः
प्रऽवसथानि
सुऽवसनस्य
सुऽवसनानि
सम्ऽवसनेषु
सम्ऽवसानम्
सम्ऽवसानाः
पुरुऽवसुः
वसुऽवसु
आभरत्ऽवसुः
उपऽवसुः
गर्तऽवसुः
धियाऽवसुः
वाजिनीऽवसुः
विदत्ऽवसुः
विभाऽवसुः
विभुऽवसुः
विश्वऽवसुः
सम्ऽवसुः
स्वऽवसुः
पुरुऽवसुम्
अक्षितऽवसुम्
उपऽवसुम्
स्वाऽवसुम्
विदत्ऽवसुम्
विभाऽवसुम्
विश्वऽवसुम्
शतत्ऽवसुम्
सहऽवसुम्
पुरुवसू इति पुरुऽवसू
कृतद्वसू इति कृतत्ऽवसू
जेन्यावसू इति
पुनर्वसू इति पुनःऽवसू
प्रतद्वसू इति प्रतत्ऽवसू
मनावसू इति
महावसू इति महाऽवसू

वाजिनीवसू इति वाजिनीऽवसू
विश्पलावसू इति
वृषण्वसू इति वृषण्ऽवसू
वृषण्वसू इति वृषण्ऽवसू
शचीवसू इति शचीऽवसू
सूर्यावसू इति
आघृणिवसो इत्याघृणिऽवसो
ऋतवसो इत्यृतऽवसो
दिवावसो इति दिवाऽवसो
धियावसो इति धियाऽवसो
पुरूवसो इति पुरुऽवसो
प्रभूवसो इति प्रभुऽवसो
रद्वसो इति रद्ऽवसो
वाजिनीवसो इति वाजिनीऽवसो
विद्द्वसो इति विदत्ऽवसो
विभावसो इति विभाऽवसो
विश्ववसो इति विश्वऽवसो
शचीवसो इति शचीऽवसो
प्रभुऽवसोः
दोषाऽवस्तः
वस्तोःऽवस्तोः
वस्यसाऽवस्यसा
अधिऽवस्त्रा
प्रऽवहन्तः
निऽवहन्ता
प्रऽवहन्ति
आऽवहन्ती
आऽवहन्तीम्
सुऽवह्ना
उपऽवाकम्
जोषऽवाकम्
सूक्तऽवाकम्
अधिऽवाकाय
नमःऽवाके
ऋतऽवाकेन
सूक्तऽवाकेन
धारऽवाकेषु
उपऽवाक्यः
अघोषऽवाचः

रण्यवाचः
सत्यवाचः
सुऽवाचः
अवाचः
दुध्रऽवाचः
भद्रऽवाचः
मृध्रऽवाचः
वध्रिऽवाचः
विऽवाचः
सूक्तऽवाचः
प्रऽवाचनम्
सुऽप्रवाचनम्
विऽवाचनी
सत्यऽवाचम्
सुऽवाचम्
अद्रोघऽवाचम्
मृध्रऽवाचम्
वाचम्ऽवाचम्
सुऽवाचसा
सत्यऽवाचा
सुऽवाचा
विऽवाचि
प्रऽवाचे
उपऽवाच्यः
प्रऽवाच्यः
प्रऽवाच्यम्
प्रऽवाच्या
भारत्ऽवाजः
भरत्ऽवाजः
शतऽवाजः
सनत्ऽवाजः
ज्याऽवाजम्
भरत्ऽवाजम्
सनत्ऽवाजम्
सहस्रऽवाजम्
शतऽवाजया
सहस्रऽवाजया
तुविऽवाजाः
भरत्ऽवाजाः

चित्रऽवाजान्
भरत्ऽवाजान्
पुरुऽवाजाभिः
भरत्ऽवाजाय
अवाजिनम्
भरत्ऽवाजे
वाजेऽवाजे
तुविऽवाजेभिः
भरत्ऽवाजेषु
दक्षिणाऽवाट्
मध्यमऽवाट्
हविःऽवाट्
हव्यऽवाट्
हव्यऽवाट्
अवातः
अवातः
देवऽवातः
इन्द्रवातऽतमाः
देववातऽतमाः
अवातम्
देवऽवातम्
देवऽवातम्
अपिऽवातयन्तः
पर्जन्यावाता
अवाता
देवऽवाता
पर्जन्यवाता
अवाताः
अवाताः
देवऽवाताः
मनःऽवाताः
अवाताम्
दैवऽवाताय
अनुऽवाति
अपऽवाति
अवाते
दैवऽवाते
प्रवातेऽजाः
सम्ऽवादार्य

भद्रऽवादी
शीर्णऽवाभम्
वामम्ऽवामम्
अन्तिऽवामा
वासःऽवायः
इन्द्रवायू इति
इन्द्रवायू इति
पुरुऽवार
विश्वऽवार
पुरुऽवारः
अशस्तऽवारः
दातिऽवारः
विश्वऽवारः
पुरुऽवारम्
दातिऽवारम्
भूरिऽवारम्
विश्वऽवारम्
पुरुऽवारस्य
विश्वऽवारस्य
विश्वऽवारा
विश्वऽवारा
दातिऽवाराः
भूरिऽवाराः
विश्वऽवाराः
विश्वऽवाराणि
विश्वऽवाराभिः
ऋधत्ऽवाराय
वीतऽवारासः
विश्वऽवारे
विश्ववारे इति विश्वऽवारे
पुरुऽवारेभिः
विश्वऽवार्यैः
अवार्यऽक्रतुम्
विश्वऽवार्यम्
अन्तःऽवावत्
हिरण्यऽवाशीः
हिरण्यऽवाशीभिः
हिरण्यवाशीमत्ऽतम
अधीवासम्
समुद्रऽवाससम्
दुःऽवाससे
सुऽवासाः
शुक्रऽवासाः
नवऽवास्त्वम्
सुऽवास्त्वाः
इन्द्रऽवाहः
वज्रऽवाहः
वीरऽवाहः
सहऽवाहः
सुष्टुऽवाहः
हव्यऽवाहः
रिप्रऽवाहः
उक्थऽवाहः
गिर्वाहः
गिर्वाहः
ब्रह्मऽवाहः
ब्रह्मवाहःऽतमम्
हव्यऽवाहन
क्रव्यऽवाहनः
देवऽवाहनः
मधुऽवाहनः
हव्यऽवाहनः
नृऽवाहनम्
मधुऽवाहनम्
रथऽवाहनम्
वसुऽवाहनम्
हव्यऽवाहनम्
हव्यऽवाहनीः
मधुऽवाहने
वीरऽवाहम्
स्वस्तिऽवाहम्
हव्यऽवाहम्
होत्रऽवाहम्
उक्थऽवाहसः
यज्ञऽवाहसः
स्तोमऽवाहसः
गिर्वाहसम्
ब्रह्मऽवाहसम्
यज्ञऽवाहसम्
सत्यऽगिर्वाहसम्
नृऽवाहसा
उक्थऽवाहसा
यज्ञऽवाहसा
विप्रऽवाहसा
सिन्धुऽवाहसा
स्तोमऽवाहसाम्
उक्थऽवाहसे
गिर्वाहसे
ब्रह्मऽवाहसे
मृक्तऽवाहसे
यज्ञऽवाहसे
इन्द्रऽवाहा
यूपऽवाहाः
स्तोमऽवाहाः
उदऽवाहासः
उदऽवाहेन
इन्द्रऽवाहौ
अविऽअनत्
अविऽउष्टाः
अधिऽविकर्तनम्
प्रऽविक्ताः
प्रऽविक्ते
अविऽक्रीतः
अविऽक्षितम्
शतऽविचक्षणाः
अविऽचाचलिः
अविऽचेतनानि
अविऽचेतसः
अविऽजानन्
सुऽविज्ञानम्
बलऽविज्ञायः
विऽविद्वन्
अश्वऽवित्
क्रतुऽवित्
क्षेत्रऽवित्
गातुऽवित्
गोऽवित्

द्रविणःऽवित्
नृमःऽवित्
प्रकुलऽवित्
रयिऽवित्
वचःऽवित्
वयुनऽवित्
वरिवःऽवित्
वसुऽवित्
विश्वऽवित्
श्रुतऽवित्
सम्ऽवित्
स्वःऽवित्
हिरण्यऽवित्
अक्षेत्रऽवित्
विश्वऽवित्
अविऽतारिणीम्
पितुऽवित्तः
अनुऽवित्तः
सनऽवित्तः
सनऽवित्तम्
क्रतुवित्ऽतमः
गातुवित्ऽतमः
वसुवित्ऽतमम्
गातुवित्ऽतमाः
क्षेत्रवित्ऽतरः
वरिवोवित्ऽतरस्य
गातुवित्ऽतरा
वरिवोवित्ऽतरा
पितुऽवित्तस्य
अविथुराः
अहःऽविदः
निऽविदः
नीथऽविदः
वचःऽविदः
वरिवःऽविदः
वसुऽविदः
स्वःऽविदः
होत्राऽविदः
सुऽविदत्रः
सुऽविदत्रम्
दुःऽविदत्रस्य
दुःऽविदत्रा
सुऽविदत्राणि
सुऽविदत्रान्
सुऽविदत्राभिः
दुःऽविदत्राम्
सुऽविदत्रियेभ्यः
सुऽविदत्रेभिः
अहःऽविदम्
क्रतुऽविदम्
क्षेत्रऽविदम्
गातुऽविदम्
गोऽविदम्
निऽविदम्
वचःऽविदम्
वरिवःऽविदम्
वसुऽविदम्
विश्वऽविदम्
सचिऽविदम्
सम्ऽविदम्
स्वःऽविदम्
होत्राऽविदम्
अविऽदस्यम्
उपऽविदा
क्रतुऽविदा
क्षेत्रऽविदा
निऽविदा
प्रऽविदा
वरिवःऽविदा
वसुऽविदा
विश्वऽविदा
स्वःऽविदा
अहःऽविदा
स्वःऽविदा
सम्ऽविदानः
सम्ऽविदानाः
सम्ऽविदानासः
संविदाने इति सम्ऽविदाने
स्वःऽविदि
अविऽदीधयुम्
आऽविदे
कुहचित्ऽविदे
स्वःऽविदे
निऽविद्धः
अवऽविद्धम्
प्रऽविद्धम्
अतिऽविद्धा
निऽविद्धा
प्रऽविद्ध
प्रतिऽविद्यम्
जातऽविद्याम्
ऋष्टिऽविद्युतः
ऋष्टिऽविद्युतः
स्वऽविद्युतः
अविद्रियाभिः
अविद्वांसः
दुःऽविद्वांसम्
सुऽविद्वांसम्
अविद्वान्
अन्तःऽविद्वान्
आऽविद्वान्
प्रऽविद्वान्
हृदयऽविधः
अविधवाः
षट्ऽविधानाः
आच्छत्ऽविधानैः
अतिऽविधे
सम्ऽविन्दते
गोऽविन्दुः
अविप्रः
सुऽविप्रः
सामऽविप्रम्
अविप्रे
अविऽरणाय
आऽविवाय
आऽविवासतः
आऽविवासताम्

आऽविवासति
आऽविवासन्
आऽविवासन्तः
आऽविवासन्ती
आऽविवाससि
आऽविवासात्
आऽविवासान्
आऽविविद्रे
निऽविविध्वान्
सुऽविवृतम्
परिऽआविवृत्सन्
अविऽवेनन्
अविऽवेनम्
आऽविवेश
प्रऽविवेश
प्रऽविवेशिथ
सम्ऽविव्यानः
विशःऽविशः
आऽविशन्
निऽविशन्ते
आऽविशम्
विशम्ऽविशम्
अनिऽविशमानाः
अनर्विशे
विशेऽविशे
अविश्वऽमिन्वम्
अविश्वऽमिन्वाम्
जरत्ऽविषम्
अविषस्य
अविषा
परिऽविषे
शिपिऽविष्ट
शिपिऽविष्टः
प्रऽविष्टः
अपरिऽविष्टम्
परिऽविष्टम्
प्रऽविष्टम्
निऽविष्टाः
प्रऽविष्टाम्
त्रिऽविष्टि
आऽविष्टितः
त्रिविष्टिऽधातु
परिऽविष्टी
इन्द्राविष्णू इति
इन्द्राविष्णु इति
अविऽह्रुतम्
अष्टाऽवी
देवऽवीः
पदऽवीः
परिऽवीतः
परिऽवीतम्
देवऽवीतमः
देवऽवीतये
अप्रऽवीता
अभिऽवीता
प्रऽवीता
अप्रऽवीताः
रथऽवीतिः
देववीतिऽभिः
देवऽवीतिम्
गोरिऽवीतेः
देवऽवीतेः
देवऽवीतौ
रथऽवीतौ
हिरण्यऽवीनाम्
पदऽवीयम्
तक्वऽवीये
क्षयत्ऽवीर
सधऽवीर
सुऽवीरः
एकऽवीरः
अभिऽवीरः
क्षयत्ऽवीरः
प्रऽवीरः
विप्रऽवीरः
सर्वऽवीरः
अवीरता
अवीरतायै
अवीरते
पुरुऽवीरम्
सुऽवीरम्
महाऽवीरम्
क्षयत्ऽवीरम्
विप्रऽवीरम्
संयत्ऽवीरम्
सर्वऽवीरम्
सहऽवीरम्
सहस्रऽवीरम्
स्पार्हऽवीरम्
सर्वऽवीरया
पुरुऽवीरस्य
ऋष्वऽवीरस्य
क्षयत्ऽवीरस्य
विप्रऽवीरस्य
सुऽवीरा
अवीराः
पुरुऽवीराः
सुऽवीराः
अरिष्टऽवीराः
विप्रऽवीराः
सतःऽवीराः
सर्वऽवीराः
स्पार्हऽवीराः
पुरुऽवीराभिः
सुऽवीराभिः
पुरुऽवीराम्
सुऽवीराम्
अवीराम्ऽइव
क्षयत्ऽवीराय
मन्दत्ऽवीराय
सुऽवीरासः
अवीरे
सुऽवीरेण
सुऽवीरैः
सुऽवीर्यम्
दुःऽवीर्यम्
सुऽवीर्यस्य

मरुत्ऽवृधः
शेऽवृधः
सदाऽवृधः
अन्नऽवृधम्
आहुतिऽवृधम्
गिराऽवृधम्
तुग्र्यऽवृधम्
नमःऽवृधम्
पयःऽवृधम्
पर्वतऽवृधम्
मधुऽवृधम्
वयःऽवृधम्
सद्यःऽवृधम्
सहःऽवृधम्
सुऽवृधम्
शेऽवृधम्
शेऽवृधम्
सदाऽवृधम्
ऋतऽवृधा
ऋदुऽवृधा
घृतऽवृधा
नमःऽवृधा
पयःऽवृधा
वयःऽवृधा
साकम्ऽवृधा
सुऽवृधा
ऋतऽवृधा
त्वाऽवृधा
सदाऽवृधा
अवृधान्
ऋतऽवृधाम्
नमःऽवृधासः
शेऽवृधासः
ऋतऽवृधे
महिऽवृधे
मरुत्ऽवृधे
त्वाऽवृधेभिः
नमःऽवृधैः
ऋतऽवृधौ
ऋतऽवृधौ
विऽवृश्चत्
विऽवृश्चन्
शृङ्गऽवृषः
प्रावृषि
प्रावृषीणम्
अभिऽवृष्टः
स्वऽवृष्टिम्
हतऽवृष्णीः
अभिऽवेगः
अनुऽवेद
प्रऽवेद
जातऽवेदः
जातऽवेदः
सुऽवेदनाम्
सुऽवेदम्
प्रतिऽवेदयन्
जातवेदसः
नवेदसः
विश्वऽवेदसः
विश्वऽवेदसः
विश्वऽवेदसम्
अनष्टऽवेदसम्
जातऽवेदसम्
जातऽवेदसा
नवेदसा
विश्वऽवेदसा
विश्वऽवेदसा
विश्वऽवेदसा
सऽवेदसा
जातऽवेदसि
जातऽवेदसे
सुऽवेदाः
केतऽवेदाः
जातऽवेदाः
नवेदाः
विश्वऽवेदाः
अविंऽवेनन्
अवेनन्तम्
अनुऽवेनन्तम्
अविंऽवेनम्
सुऽवेनीः
प्रऽवेपनी
गम्भीरऽवेपसः
पुरुऽवेपसम्
गायत्रऽवेपसम्
विश्वायुऽवेपसम्
गायत्रऽवेपसे
प्रावेपाः
गभीरऽवेपाः
विऽवेविदत्
सुऽआवेशः
निऽवेशनः
निऽवेशनम्
निऽवेशनात्
अनिऽवेशनानाम्
निऽवेशनी
निऽवेशनीम्
निऽवेशने
सम्ऽवेशने
अस्वऽवेशम्
प्रतिऽवेशम्
निऽवेशयन्
आऽवेशयन्तीम्
दासऽवेशाय
आग्निऽवेशिम्
निऽवेशे
सम्ऽवेविषः
महाऽवैलस्थे
प्रऽवोचति
उपऽवोचन्त
प्रऽवोळ्हुम्
प्रऽवोळ्हृन्
ऋतऽव्ये
पदुऽव्यः
देवव्यचःऽतमः
उरुव्यचःऽतमम्
देवव्यचःऽतमम्

उरुऽव्यचसम्
विश्वऽव्यचसम्
समुद्रऽव्यचसम्
उरुऽव्यचसा
उरुऽव्यचसे
उरुऽव्यचा
उरुऽव्यचाः
देवऽव्यचाः
उरुऽव्यञ्चम्
परिऽव्यत
अव्यथ्यै
अव्यथिः
कृष्णऽव्यथिः
अव्यथिऽभिः
अव्यथिषु
अव्यथी
अव्यथीः
अव्यथ्याय
अवऽव्ययन्
अनपऽव्ययन्तः
अव्ययम्
अतिव्रजत्ऽभिः
अभिव्रजत्ऽभिः
अभिऽव्रजन्
दर्शऽव्रजम्
अश्मऽव्रजाः
शतऽव्रजाः
अश्मऽव्रजानाम्
उदऽव्रजे
उरुऽव्रजे
दर्शऽव्रजे
महिऽव्रत
शुचिऽव्रत
शुचिऽव्रत
अव्रतः
पुरुऽव्रतः
सुऽव्रतः
अनुऽव्रतः
अन्यऽव्रतः
धृतऽव्रतः
महिऽव्रतः
वृषऽव्रतः
शुचिव्रतऽतमः
अदब्धव्रतऽप्रमतिः
अव्रतम्
सुऽव्रतम्
अन्यऽव्रतम्
धुनिऽव्रतम्
महाऽमहिव्रतम्
महिऽव्रतम्
हरिऽव्रतम्
विऽव्रतयोः
अन्यऽव्रतस्य
धृतऽव्रता
धृतऽव्रता
विऽव्रता
शुचिऽव्रता
शुचिऽव्रता
सऽव्रता
हृष्टऽव्रताः
धृतऽव्रताः
अव्रतान्
अपऽव्रतान्
प्रियऽव्रतान्
विऽव्रतानाम्
अनुऽव्रताम्
अनुऽव्रताय
धुनिऽव्रताय
धृतऽव्रताय
सुऽव्रतासः
अनुऽव्रते
धृतऽव्रते
मधुव्रते इति मधुऽव्रते
शुचिव्रते इति शुचिऽव्रते
सव्रते इति सऽव्रते
अपऽव्रतेन
विऽव्रतेन
यूपऽव्रस्काः
प्रऽव्राजे
महाऽव्रातः
भद्रऽव्रातम्
व्रातम्ऽव्रातम्
वृषऽव्रातासः
अभिऽव्लग्य
अभिऽव्लङ्गैः
उरुऽशंस
उरुऽशंस
उरुऽशंसः
दुःऽशंसः
नराशंसः
नृऽशंसः
सुऽशंसः
अघऽशंसः
गम्भीरऽशंसः
प्रऽशंसन्ति
दुःऽशंसम्
नराशंसम्
पाकऽशंसम्
अघऽशंसम्
प्रऽशंसमानः
उरुऽशंसस्य
अघऽशंसस्य
अघशंसऽहा
उरुऽशंसा
उरुऽशंसाः
सुऽशंसाः
प्रऽशंसात्
दुःऽशंसान्
उरुऽशंसाय
अघऽशंसाय
उक्थऽशंसिनः
उक्थऽशंसिनम्
जीवऽशंसे
अघऽशंसे
प्रऽशंस्यः
प्रऽशंस्यम्
सुऽशका

परिऽशक्वे
सुऽशक्तिः
तुविऽशग्म्
एकऽशतम्
चतुःऽशतम्
त्रिंशत्ऽशतम्
त्रिऽशताः
देवऽशत्रवः
अशत्रु
अशत्रुः
अजातऽशत्रुः
इन्द्रऽशत्रुः
अशत्रुऽभ्यः
अशत्रुम्
अजातऽशत्रुम्
अशत्रो इति
शत्रोःऽशत्रोः
सुऽशमि
सुऽशमी
विश्वऽशंभुवम्
विश्वऽशंभुवा
विश्वऽशंभूः
हिरण्यऽशम्यम्
प्रोष्ठेऽशयाः
वह्येऽशयाः
आऽशयानम्
परिऽशयानम्
आऽशये
पराऽशरः
सुऽशरणः
सुऽशरणाय
बृहत्ऽशरीरः
प्रऽशर्धं
शर्धम्ऽशर्धम्
अतिऽप्रशर्धयत्
विश्वऽशर्धसौ
बाहुऽशर्धी
सुऽशर्मणः
सुशर्मऽभिः
सुऽशर्मिणः
सुऽशर्मिणम्
सुऽशर्मिणा
गोऽशर्यम्
गोऽशर्ये
अपिऽशर्वरे
असामिऽशवसः
वृद्धऽशवसः
वृद्धऽशवसः
सत्यऽशवसः
अप्रतिधृष्टऽशवसम्
द्विऽशवसम्
सत्यऽशवसम्
नक्षत्रऽशवसाम्
अभिष्टिऽशवसे
शश्वत्ऽशश्वत्
अशसः
आऽशसः
उक्थऽशसः
आऽशसनम्
विऽशसनम्
उक्थऽशसम्
अभिऽशसा
आऽशसा
उक्थऽशसा
निःऽशसा
अनुऽशसे
विऽशसे
प्रऽशस्त
कविऽशस्तः
पुरुऽप्रशस्तः
प्रऽशस्तः
प्रऽशस्तः
प्रऽशस्तम्
सुऽशस्तयः
प्रऽशस्तयः
अभिऽशस्तये
प्रऽशस्तये
अशस्तऽवारः
अविऽशस्ता
पुरुऽप्रशस्ता
प्रऽशस्ता
विऽशस्ता
अनभिऽशस्ता
अप्रऽशस्ताः
कविऽशस्ताः
अनिऽशस्ताः
अप्रशस्ताःऽइव
अप्रऽशस्तान्
प्रऽशस्ताम्
सुऽशस्ति
सुऽशस्तिः
प्रऽशस्तिः
अभिशस्तिऽचातनः
अभिशस्तिऽपाः
अभिशस्तिऽपाम्
अभिशस्तिऽपावा
सुशस्तिऽभिः
प्रशस्तिऽभिः
अशस्तिम्
अभिऽशस्तिम्
प्रऽशस्तिम्
अशस्तिऽहा
अशस्तीः
अभिऽशस्तीः
अभिऽशस्तेः
प्रऽशस्यः
प्रऽशस्यते
पुरुऽशाक
पुरुशाकऽतमा
पुरुऽशाकाय
उपऽशाकेभिः
नैचाऽशाखम्
दशऽशाखाभ्याम्
सम्ऽशाय
शतऽशारदाय
शतऽशारदेन
उक्थऽशासः

प्रऽशासत्
अनुऽशासता
अनुऽशासति
अभिऽशासति
प्रऽशासनम्
अनुऽशासनस्य
प्रऽशासने
दुःऽशासुः
सर्वऽशासैः
प्रऽशास्ता
प्रऽशास्त्रम्
प्रऽशास्त्रात्
अशास्यम्
उपऽशिक्षन्
प्रतिऽशिक्षन्ति
विऽशिक्षुः
वरऽशिखस्य
अनिऽशितम्
निऽशितम्
सोमऽशितम्
अनिशितऽसर्गा
निऽशिताः
सोमऽशिताः
निऽशितानि
निऽशितिम्
निऽशिती
अशिपदाः
सुऽशिप्र
सुऽशिप्रः
सुऽशिप्रः
हिरिऽशिप्रः
हरिऽशिप्रः
विशिऽशिप्रम्
सुऽशिप्रम्
हरिऽशिप्रम्
वृषऽशिप्रस्य
अयःऽशिप्राः
सुऽशिप्राः
हिरण्यऽशिप्राः

दृशऽशिप्रे
अशिमिदाः
आऽशिरम्
आऽशिरा
सुऽशिल्पे इति सुऽशिल्पे
अशिवः
अशिवस्य
अशिवा
अशिवाः
अशिवासः
सप्तऽशिवासु
अशिवेन
सम्ऽशिशानः
निऽशिशानाः
सम्ऽशिशानाः
उपऽशिश्रियाणाः
संशिश्वरीःऽइव
सुऽशिश्विम्
अशिश्वीः
आऽशिषः
प्रऽशिषः
निऽशिषत्
आऽशिषम्
प्रऽशिषम्
आऽशिषा
अनुऽशिष्टः
वरुणऽप्रशिष्टाः
देवशिष्टे इति देवऽशिष्टे
सुऽशिष्टौ
आऽशीः
पत्सुतःऽशीः
स्योनऽशीः
मध्यमशीःऽइव
दुःऽशीमे
आऽशीतः
अशीर्षा
अयःऽशीर्षा
सहस्रऽशीर्षा
त्रिऽशीर्षाणम्

सप्तऽशीर्षाणम्
शीर्ष्णःऽशीर्ष्णः
शीर्ष्णाऽशीर्ष्णा
रुरुऽशीर्ष्णी
सप्तऽशीर्ष्णीम्
शीर्ष्णेऽशीर्ष्णे
तल्पऽशीवरीः
सुऽशुक्वानः
शुचाऽशुचा
विश्वऽशुचे
अदुच्छुनः
रथेऽशुभम्
तनूऽशुभ्रम्
आऽशुशुक्षणिः
अहिऽशुष्म
तुविऽशुष्म
सत्यऽशुष्म
तुविऽशुष्मः
सत्यऽशुष्मः
वृषऽशुष्मम्
सत्यऽशुष्मम्
वीरऽशुष्मया
तुविऽशुष्मा
अनन्तऽशुष्माः
उक्थऽशुष्माः
उक्थऽशुष्मान्
सत्यऽशुष्माय
तीक्ष्णऽशृङ्ग
चतुःऽशृङ्गः
तिग्मऽशृङ्गः
त्रिधातुऽशृङ्गः
सहस्रऽशृङ्गः
हिरण्यऽशृङ्गः
तिग्मऽशृङ्गम्
भूरिऽशृङ्गाः
आऽशृण्वती
आऽशृण्वते
आऽशृण्वन्ति
उपऽशृण्वन्ति

अभिऽश्रियः
गणऽश्रियः
सुऽश्रियः
गणऽश्रियः
अध्वरऽश्रियम्
अभिऽश्रियम्
क्षत्रऽश्रियम्
घृतऽश्रियम्
जनऽश्रियम्
यज्ञऽश्रियम्
सुऽश्रियम्
हरिऽश्रियम्
अभिऽश्रिया
घृतऽश्रिया
अभिऽश्रिषः
अभिऽश्रीः
क्षत्रऽश्रीः
घृतऽश्रीः
दर्शतऽश्रीः
मर्यऽश्रीः
अभिऽश्रीणन्
गोऽश्रीताः
गोऽश्रीते
अश्रीरःऽइव
अश्रीरम्
अश्रीरा
सुऽश्रुणम्
दीर्घऽश्रुत्
हवनऽश्रुत्
वन्दनऽश्रुत्
सनऽश्रुत
दीर्घऽश्रुतः
सुऽश्रुतः
हवनऽश्रुतः
सत्यऽश्रुतः
सनऽश्रुतः
सुऽश्रुतः
हवनऽश्रुतः
दीर्घऽश्रुतम्
देवऽश्रुतम्
हवनऽश्रुतम्
विऽश्रुतम्
सनऽश्रुतम्
सुऽश्रुता
हवनऽश्रुता
हवनऽश्रुता
विऽश्रुताय
वाजऽश्रुतासः
उपऽश्रुति
उपऽश्रुतिम्
यामऽश्रुतेभिः
दीर्घश्रुत्ऽतमः
दीर्घश्रुत्ऽतमम्
देवश्रुत्ऽतमम्
दीर्घश्रुत्ऽतमा
मन्त्रऽश्रुत्यम्
विश्वऽश्रुष्टिः
यात्ऽश्रेष्ठाभिः
उपऽश्रोता
सुऽश्रोतुः
श्वःऽश्वः
सुराश्वः
उत्ऽश्वञ्चमाना
मातरिश्वने
विऽश्वयत्
अभिऽश्वसः
अभिऽश्वसन्
मातरिश्वा
मातरिश्वानम्
उत्ऽश्वासे
सूर्यऽश्वितः
आनुषक्
अभीषाट्
ऋषिषाट्
जनाषाट्
तुराषाट्
भिल्वाट्
पुराषाट्
पृतनाषाट्
प्राशुषाट्
भूरिषाट्
रयिषाट्
वनेषाट्
विराषाट्
वृथाषाट्
सत्राषाट्
अषाळ्हः
अषाळ्हम्
अषाळ्हाय
अषाळ्हेन
आशुषाणः
आशुषाणाः
आशुषाणासः
अभिष्टयः
अभिष्टये
अभिष्टिः
परिष्टिः
अभिष्टिऽकृत्
अभिष्टिऽभिः
अभिष्टिऽमत्
दिविष्टिषु
अभिष्टौ
अभिष्टिऽपा
स्वभिष्टिऽसुम्नः
अनुष्टु
अनुष्टुया
सुऽसंरब्धाः
सुऽसंशिताः
ब्रह्मऽसंशिते
सुऽसंसत्
स्वादुऽसंसदः
सुऽसंसदम्
सुऽसंस्कृता
सुऽसंस्कृताः
अद्रिऽसंहतम्
पशुऽसः
विऽसक्ताम्

असक्राम्
प्रऽसक्षत्
प्रऽसक्षिणः
प्रऽसक्षिणा
प्रऽसक्षिणे
कुवऽसखः
यवयत्ऽसखः
द्रवयत्ऽसखम्
मन्दयत्ऽसखम्
सुऽसखा
सुऽसखा
अस्मत्ऽसखा
इन्द्रऽसखा
कण्वऽसखा
गोऽसखा
नृवत्ऽसखा
मत्ऽसखा
मरुत्ऽसखा
श्रवयत्ऽसखा
सुऽसखायः
गोऽसखायम्
सुऽसंकाशा
आऽसङ्गः
आऽसङ्गस्य
रथऽसङ्गे
असचऽद्विषः
असजात्या
अद्मऽसत्
अन्तरिक्षऽसत्
उपस्थऽसत्
ऋतऽसत्
चमूऽसत्
तुरण्यऽसत्
दुरोणऽसत्
दुवन्यऽसत्
द्रुऽसत्
नृऽसत्
प्राघर्मऽसत्
वरऽसत्
वेदिऽसत्
व्योमऽसत्
शुचिऽसत्
सम्ऽसत्
असत्
असतः
सतःऽसतः
गोसऽतमाः
असता
असति
प्रऽसत्तः
निऽसत्तः
निऽसत्तम्
निऽसत्तम्
निऽसत्ता
निऽसत्ताः
निऽसत्तिः
निऽसत्ते
घर्मसत्ऽभिः
अप्रामिऽसत्य
अनुऽसत्यम्
असत्याः
ऋतजातऽसत्याः
वक्मराजऽसत्याः
ममऽसत्येषु
सत्यऽसत्वन्
अभिऽसत्वा
सतीनऽसत्वा
आऽसत्सि
संसत्ऽसु
निऽसत्स्नुम्
अद्मऽसदः
चमूऽसदः
धूःऽसदः
नृऽसदः
परिऽसदः
पस्त्यऽसदः
पुरःऽसदः
बर्हिऽसदः
वनऽसदः
शर्मऽसदः
सदःऽसदः
सम्ऽसदः
बर्हिऽसदः
निऽसदनम्
नृऽसदनम्
नृऽसदने
होतृऽसदने
नृऽसदनेषु
परिऽसदन्तः
अप्सुऽसदम्
आऽसदम्
उपऽसदम्
गर्तऽसदम्
द्रुऽसदम्
धूःऽसदम्
पितृऽसदम्
बर्हिऽसदम्
वनऽसदम्
सम्ऽसदम्
सुऽसदम्
सुऽसंसदम्
निऽसदा
बर्हिऽसदा
सम्ऽसदा
अद्मऽसदाम्
निऽसदि
सम्ऽसदि
सुऽसंदृशः
विऽसदृशा
आऽसदे
निऽसदे
पितृऽसदे
वेदिऽसदे
सदनऽसदे
शुक्रऽसद्मनाम्
दीर्घऽप्रसद्मनि
आऽसद्य

उपऽसद्य
निऽसद्य
उपऽसद्यः
परिऽसद्यम्
अनुऽसद्याय
उपऽसद्याय
अनुऽसद्वा
नृऽसद्वा
नृऽसद्वा
परिऽसद्वानः
त्रिऽसधस्थ
त्रिऽसधस्थः
त्रिऽसधस्थः
त्रिऽसधस्थस्य
त्रिऽसधस्था
त्रिऽसधस्थे
अहम्ऽसन
गोऽसनः
सुऽसननानि
सुऽसना
पितुऽसनिः
वाजऽसनिः
हृदम्ऽसनिः
सुऽसनितः
सुऽसनितः
सुऽसनिता
गोऽसनिम्
वाजऽसनिम्
ऊर्जऽसने
प्रऽसन्ता
पुरुऽसन्तिम्
पुरुऽसन्त्योः
सुऽसंदृक्
त्वेषऽसंदृक्
रण्वऽसंदृक्
सुदृशीकऽसंदृक्
हिरण्यऽसंदृक्
सुसंदृक्ऽभिः
सुऽसंदृशः

त्वेषऽसंदृशः
भीमऽसंदृशः
हिरण्यऽसंदृशः
सुऽसंदृशम्
त्वेषऽसंदृशम्
पिशङ्गऽसंदृशम्
रण्वऽसंदृशम्
सुऽसंदृशा
असपत्नः
असपत्ना
सप्तऽसप्त
युयुजानसप्ती इति युयुजानऽसप्ती
त्रिऽसप्तैः
असमः
असमनाः
असमने
सम्ऽसम्
असमम्
असमष्टऽकाव्यः
असमा
असमाः
असमातिऽओजाः
असमातिम्
असमातिषु
असमानि
समित्ऽसमित्
सुऽसमिद्धः
सुऽसमिद्धाय
सुऽसमिधा
चतुःऽसमुद्रम्
सुऽसमुब्धम्
असम्ऽदितः
असम्ऽदिनम्
सुऽसंपिष्टम्
पुरुऽसंभृतम्
असम्ऽमृष्टः
सुऽसंमृष्टासः
पुनःऽसर
सुऽसरणम्

जीवपीतऽसर्गः
विऽसर्गम्
अनिशितऽसर्गाः
प्रऽसर्गे
प्रऽसर्गे
विऽसर्गे
विऽसर्जने
विऽसर्जनेन
प्रऽसर्तवे
सुऽसर्त्वा
प्रऽसर्पणम्
अतिऽसर्पति
प्रऽसर्पथ
विऽसर्माणम्
प्रऽसस्राणः
प्रऽसस्राणस्य
प्रऽसस्रे
प्रऽसवः
अधिऽसवन्या
अप्सवम्
प्रऽसवम्
सत्यऽसवम्
प्रऽसवस्य
सत्यऽसवस्य
वृषऽसवासः
प्रऽसविता
उत्ऽसवे
प्रऽसवे
उत्ऽसवेषु
ब्रह्मऽसवैः
सुऽसव्यः
असश्चतः
असश्चतम्
असश्चतम्
असश्चता
असश्चताऽइव
असश्चन्ती
असश्चन्ती इति
असश्चुषी

निऽससत्थ
अससन्तः
विऽससहिः
विऽससहिम्
निऽससाद
आऽसस्राणासः
परिऽसस्वजाना
सुऽसह
अभिमातिऽसहः
ऋतिऽसहः
पृतनाऽसहः
प्रऽसहः
शत्रुऽसहः
अभिमातिऽसहः
जनम्ऽसहः
सत्राऽसहः
चर्षणिऽसहः
अभिमातिऽसहम्
ऋतिऽसहम्
चर्षणिऽसहम्
द्युम्नऽसहम्
नृऽसहम्
पृतनाऽसहम्
प्रऽसहम्
यज्ञऽसहम्
विभ्वऽसहम्
विश्वऽसहम्
सत्राऽसहम्
सदाऽसहम्
अभिमातिऽसहम्
निःऽसहमानः
चतुःऽसहस्रम्
सम्ऽसहस्रम्
धन्वऽसहा
प्रऽसहा
रथऽसहा
सुऽसहा
चर्षणिऽसहा
सुऽसहाः
व्रातऽसहाः
सुऽसहान्
प्रऽसहानः
दुःऽसहासः
चर्षणिऽसहे
सत्राऽसहे
सभाऽसहेन
विऽसह्य
नृऽसह्यम्
नृऽसह्याय
पृतनाऽसह्याय
अभिमातिऽसह्यै
नृऽसह्यै
अप्साः
अश्वऽसाः
गोऽसाः
धनऽसाः
नृऽसाः
वाजऽसाः
शतऽसाः
सदाऽसाः
सहस्रऽसाः
सुऽसाः
स्वःऽसाः
अभिऽसाचः
नृऽसाचः
रयिऽसाचः
रातिसाचः
हरिऽसाचः
अयज्ञऽसाचः
नृऽसाचः
स्मद्रातिऽसाचः
अपत्यऽसाचम्
अभिऽसाचम्
द्रोणऽसाचम्
धामऽसाचम्
रातिऽसाचम्
वाजऽसातम
अश्वऽसातमः
वाजऽसातमः
सहस्रऽसातमः
वाजऽसातमम्
सदाऽसातमम्
सहस्रऽसातमम्
वाजऽसातमा
सहस्रऽसातमाम्
धनऽसातये
मेधऽसातये
वाजऽसातये
क्षेत्रऽसाता
गोऽसाता
तोकऽसाता
द्युम्नऽसाता
नृऽसाता
मेधऽसाता
शूरऽसाता
स्वःऽसाता
अभिऽसाताः
अवऽसातारम्
वाजसातिऽभिः
अर्कऽसातौ
अर्णऽसातौ
तोकऽसातौ
धनऽसातौ
मेधऽसातौ
वाजऽसातौ
शूरऽसातौ
मेधसातौऽइव
निऽसादयन्तः
दक्षऽसाधनः
प्रऽसाधनः
मन्मऽसाधनः
यज्ञऽसाधनः
गयऽसाधनम्
दक्षऽसाधनम्
प्रऽसाधनम्
पशुऽसाधनी
यज्ञऽसाधम्

सुऽसुतिम्
सोमऽसुतिम्
पृत्सुतीः
सर्पिःऽआसुते
सुतेऽसुते
पृत्सुतौ
मधुऽसुत्ऽतमः
सोमसुत्ऽभिः
पाकऽसुत्वनः
सोमऽसुत्वा
सम्ऽसुदे
आऽसुनोति
असुन्वतः
असुन्वता
असुन्वताम्
असुन्वन्तम्
असुन्वाम्
प्रऽसुपः
दम्ऽसुपत्नीः
देवऽसुमतिम्
बृहत्ऽसुम्नः
स्वभिष्टिऽसुम्नः
सुऽसुम्नम्
सुऽसुम्नस्य
सुऽसुम्ना
सुऽसुम्ना
सुसुम्ने इति सुऽसुम्ने
प्रऽसुवन्
आऽसुवन्ति
प्रऽसुवन्ती
विश्वऽसुविदः
यमऽसूः
वीरऽसूः
सुऽसूः
असूतः
नृऽसूतः
प्रऽसूतः
सुऽसूतम्
प्रऽसूता
इन्द्रऽप्रसूताः
परिऽसूताः
प्रऽसूताः
बृहस्पतिऽप्रसूताः
परिऽसूतिः
परिऽसूतेः
हव्यऽसूदः
पूर्वम्ऽसूनाम्
अश्वऽसूनृते
सुऽसूमा
असूरे
असूर्ते
नानाऽसूर्याः
बहुऽसूवरी
प्रऽसूवरीः
प्रऽसूषु
उपऽअवसृज
निःऽसृजः
अवऽसृजन्
विऽसृजन्तः
उपऽसृजन्ति
सम्ऽसृजामि
सम्ऽसृजि
वाजऽसृत्
स्वऽसृत्
विऽसृतः
स्वऽसृतः
वाळ्हुऽसृत्वा
अभिऽसृष्टः
अवऽसृष्टः
संसृष्टऽजित्
सम्ऽसृष्टम्
अवऽसृष्टा
विऽसृष्टाः
अवऽसृष्टान्
अवऽसृष्टासः
विऽसृष्टिः
पशुऽसे
सुऽसेकम्
सुऽसेचनम्
आऽसेचनानि
उपऽसेचनाय
उपऽसेचनासः
उपऽसेचनी
स्वऽसेतवः
स्वऽसेतुः
निऽसेद
निऽसेदुः
निऽसेदुषः
उपऽसेदुषे
अपऽसेधन्
अयुद्धऽसेनः
धृष्णुऽसेनः
सर्वऽसेनः
इन्द्रऽसेना
सर्वऽसेना
चित्रऽसेनाः
धृष्णुऽसेनाः
वृद्धऽसेनाः
अभिऽसेनान्
देवऽसेनानाम्
महाऽसेनासः
असेन्या
शतऽसेयाय
निऽसेवे
अनुऽसेसिधत्
अवऽसै
धनऽसैः
सुतऽसोमः
सुतऽसोमम्
सुऽसोमया
सुतसोमवत्ऽभिः
सुतऽसोमस्य
इन्द्रासोमा
अग्नीषोमा
अग्नीषोमा
इन्द्रासोमा
सुतऽसोमाः

सुतऽसोमाय
सुतऽसोमायाम्
सुतऽसोमासः
सुऽसोमे
सुतऽसोमे
सोमेऽसोमे
सुतऽसोमेषु
अग्नीषोमौ
इन्द्रासोमौ
विश्वऽसौभग
विश्वऽसौभगः
अतिऽस्कदः
अतिऽस्कदे
अधिऽस्कन्
तृणऽस्कन्दस्य
विस्कभिते इति विऽस्कभिते
प्रतिऽस्कभे
विऽस्कभे
विऽस्कभ्नन्तः
अस्कम्भने
अप्रतिऽस्कुतः
अप्रतिऽस्कुतम्
संस्कृतऽत्रम्
अस्कृधोयु
अस्कृधोयुः
अभिऽस्तने
उत्तभिता
उपऽस्तरणम्
प्रऽस्तरम्
सहस्रऽस्तरीः
विऽस्तारः
विऽस्तिरः
सम्ऽस्तिरः
उपऽस्तिरम्
उपऽस्तिरे
विसितऽस्तुका
बल्बजऽस्तुकाः
पृथुऽस्तुके
उपऽस्तुत्

पुरुऽस्तुत
पुरुऽस्तुत
सुऽस्तुत
वृषःऽस्तुतः
देवऽस्तुतः
अरिऽस्तुतः
उपऽस्तुतः
पुरुऽस्तुतः
अस्तुतः
अभिऽस्तुतः
उपऽस्तुतः
सुऽस्तुतः
उपऽस्तुतम्
पुरुऽस्तुतम्
उपऽस्तुतम्
सुऽस्तुतम्
सुऽस्तुतयः
उपऽस्तुतस्य
पुरुऽस्तुतस्य
पुरुऽस्तुता
उपऽस्तुता
ऋषिऽस्तुता
प्रियमेधऽस्तुता
सुऽस्तुता
उपऽस्तुताः
सुऽस्तुताः
ऋषिऽस्तुताभिः
पुरुऽस्तुताय
श्यावाश्वऽस्तुताय
उपऽस्तुतासः
उपऽस्तुतासः
सधऽस्तुति
दुःऽस्तुतिः
सुऽस्तुतिः
अनुऽस्तुतिः
उपऽस्तुतिः
परिऽस्तुतिः
पूर्व्यऽस्तुतिः
प्रऽस्तुतिः

सुस्तुतिऽभिः
सुऽस्तुतिम्
अनुऽस्तुतिम्
उपऽस्तुतिम्
पूर्व्यऽस्तुतिम्
प्रतिऽस्तुतिम्
सधऽस्तुतिम्
दुःऽस्तुती
सुऽस्तुती
दुःऽस्तुती
सधस्तुती इति सधऽस्तुती
सुऽस्तुतीः
सुऽस्तुतीनाम्
उपऽस्तुतीनाम्
अभिस्तुते इत्यभिऽस्तुते
उपऽस्तुते इत्युपऽस्तुते
उपऽस्तुतौ
उपऽस्तुत्यम्
उपऽस्तुत्या
सुऽस्तुत्या
सधऽस्तुत्याय
त्रिऽस्तुप्
छन्दःऽस्तुभः
त्रिऽस्तुभः
परिऽस्तुभः
वृषऽस्तुभः
सुऽस्तुभः
अनुऽस्तुभम्
ऋतऽस्तुभम्
त्रिऽस्तुभम्
आनुऽस्तुभस्य
अनुऽस्तुभा
सुऽस्तुभा
प्रऽस्तुभानः
घर्मऽस्तुभे
अरुषऽस्तूपः
हिरण्यऽस्तूपः
उपऽस्तृणन्ति
उपऽस्तृणीषणि

अस्तृतः
अनिःऽस्तृतः
अस्तृतम्
अस्तृतऽयज्वनः
वाचाऽस्तैनम्
पृथुस्तो इति पृथुऽस्तो
सुऽस्तोः
प्रऽस्तोकः
नित्यऽस्तोत्रः
प्रियऽस्तोत्रः
मरुत्ऽस्तोत्रस्य
परिऽस्तोभन्त्या
सहऽस्तोमाः
अप्नःऽस्थः
त्रिऽसधस्थः
पुरुनिःऽस्थः
कूऽस्थः
त्रिऽसधस्थः
गोऽस्थम्
त्रिऽस्थम्
उपऽस्थम्
सधऽस्थम्
उपस्थऽसत्
त्रिऽसधस्थस्य
धर्म्येऽस्था
प्रतिऽस्था
उपऽस्था
सधऽस्था
अध्वरेऽस्थाः
अनुऽस्थाः
अवऽस्थाः
गिरिऽस्थाः
निःऽस्थाः
परिऽस्थाः
पुरुनिःऽस्थाः
पृथिवीऽस्थाः
मंहनेऽस्थाः
रथेऽस्थाः
रोचनऽस्थाः
वक्षणेऽस्थाः
वन्दनेऽस्थाः
वन्धुरेऽस्थाः
विऽस्थाः
हरिऽस्थाः
हर्म्येऽस्थाः
उपऽस्थात्
सधऽस्थात्
आऽस्थाता
पुरःऽस्थाता
गोस्थात्ऽइव
भूरिऽस्थात्राम्
रयिऽस्थानः
वैलऽस्थानके
अधिऽस्थानम्
वैलऽस्थानम्
सधऽस्थानि
सुस्थाने इति सुऽस्थाने
सुऽउपस्थाभिः
कर्मनिःऽस्थाम्
गिरिऽस्थाम्
नरेऽस्थाम्
निःऽस्थाम्
पथेऽस्थाम्
परिऽस्थाम्
पर्वतेऽस्थाम्
प्रतिऽस्थाम्
बर्हिःऽस्थाम्
रथेऽस्थाम्
रोचनऽस्थाम्
हरिऽस्थाम्
सुऽस्थामा
पाकऽस्थामा
पाकऽस्थामानम्
उपऽस्थाय
रथेऽस्थाय
उपऽस्थायम्
प्रऽस्थावानः
सुऽस्थावाना
प्रतिऽस्थिः
निःऽस्थितः
विऽस्थितः
अपिऽस्थितम्
अनुऽस्थितम्
उत्थितम्
परिऽस्थितम्
प्रऽस्थितम्
विऽस्थितम्
प्रऽस्थितस्य
प्रऽस्थिता
विऽस्थिता
अभिऽस्थिताः
परिऽस्थिताः
प्रऽस्थिताः
विऽस्थिताः
प्रऽस्थितान्
प्रऽस्थिते
ऋभुऽस्थिर
जातूऽस्थिरस्य
अयःऽस्थूणम्
सहस्रऽस्थूणम्
सहस्रऽस्थूणे
अस्थूरि
गोऽस्थे
सम्ऽस्थे
उपऽस्थे
भयऽस्थे
सधऽस्थे
सधस्थे इति सधऽस्थे
रथेऽस्थेन
अस्थेयसाम्ऽइव
सधऽस्थेषु
घृतऽस्नाः
अस्नाता
अस्नातारा
प्रस्नातीःऽइव
अस्नातॄन्
प्रऽस्नापयन्ति

उत्ऽस्नाय
घृतऽस्नुः
घृतऽस्नुना
घृतऽस्नुवः
घृतऽस्नुवा
सुऽस्नुषे
वृधस्नू इति वृधऽस्नू
घृतस्नू इति घृतऽस्नू
घृतस्नू इति घृतऽस्नू
घृतऽस्नूः
वृधऽस्नैः
घृतस्नो इति घृतऽस्नो
वृधस्नो इति वृधऽस्नो
विष्पट्
अस्पन्दमानः
अवऽस्परत्
अवऽस्पर्तः
विऽस्पर्धयः
विऽस्पर्धसः
अनुऽस्पष्टः
उपऽस्पिजम्
दिविऽस्पृक्
निऽस्पृक्
पुरुऽस्पृक्
हृदिऽस्पृक्
अपऽस्पृण्वते
किल्बिषऽस्पृत्
धनऽस्पृत्
अस्पृतः
धनऽस्पृतम्
अस्पृतम्
परिऽस्पृधः
अपस्पृधेथाम्
मिथस्पृध्याऽइव
उपऽस्पिशः
ऋतऽस्पृशः
दिविऽस्पृशः
रथऽस्पृशः
सुद्नऽस्पृशः

हृदिऽस्पृशः
उपरिऽस्पृशम्
ऋतऽस्पृशम्
दिविऽस्पृशम्
हृदिऽस्पृशम्
दिविऽस्पृशा
ऋतऽस्पृशा
दिविऽस्पृशा
दिविऽस्पृशि
दिविऽस्पृशे
निऽस्पृशे
पुरुऽस्पृहः
पुरुऽस्पृहः
पुरुऽस्पृहम्
पुरुऽस्पृहा
गयऽस्फानः
अनपऽस्फुरः
प्रस्फुरन्ऽइव
विस्फुरन्ती इति विऽस्फुरन्ती
अनपऽस्फुरन्तीम्
अपऽस्फुरम्
अनपऽस्फुराम्
सम्ऽस्मयमाना
अस्मेराः
रघुऽस्यत्
रघुऽस्यदः
सऽस्यदः
रघुऽस्यदम्
द्रवन्ऽस्यदम्
अनुऽस्यदे
विऽस्यन्
अनवऽस्यन्तः
परिऽप्रस्यन्दते
नवऽस्रक्तिम्
पुष्करऽस्रजा
प्रऽस्रवणस्य
प्रऽस्रवणे
प्रऽस्रवणेषु
अस्रवन्तीम्

सम्ऽस्रवाः
सम्ऽस्रष्टा
अवऽस्रसः
विऽस्रसः
अस्रिधः
अस्रिधम्
अस्रिधा
अस्रिधानैः
यतऽस्रुक्
यतऽस्रुचः
यतऽस्रुचा
उद्यतऽस्रुचे
यतऽस्रुचे
परिऽस्रुतः
सऽस्रुतः
परिऽस्रुतम्
विऽस्रुहः
विऽस्रुहा
अस्रेधता
अस्रेधत्ऽभिः
अस्रेधन्
अस्रेधन्तः
अस्रेधन्ती
अस्रेमा
अस्रेमाणम्
प्रऽस्वः
नवस्वःऽइव
परिऽस्वजत्
परिऽस्वजे
अनुऽस्वधम्
तुविऽस्वनः
वातऽस्वनम्
तुविऽस्वनसः
वातऽस्वनसः
तुविऽस्वनसम्
तुविऽस्वनि
अहरिऽस्वनिः
तुविऽस्वनिः
प्रऽस्वनितासः

तुविऽस्वनीनाम्
मुहिऽस्वनीनाम्
जाग्रत्ऽस्वप्नः
अस्वप्नऽजः
दुःऽस्वप्न्यम्
दुःऽस्वप्न्यात्
अस्वम्
सकृत्ऽस्वम्
अभिऽस्वरन्ति
ऋषिऽस्वरम्
निऽस्वरम्
घर्मऽस्वरसः
अभिऽस्वरा
सुऽस्वरुः
अभिऽस्वरे
अभिऽस्वर्तारः
अस्वऽवेशम्
सप्तऽस्वसा
अग्निऽस्वात्ताः
प्रऽस्वादसः
अनुऽस्वापम्
घर्मऽस्वेदेभिः
सम्ऽहतः
आऽहतः
अद्रिऽसंहतम्
अर्यःऽहतम्
अहतये
त्वाऽहतस्य
निऽहतस्य
पराऽहता
उपऽहत्नुम्
विऽहत्ये
सुऽहत्यम्
मुष्टिऽहत्यया
अहिऽहत्याय
दस्युऽहत्याय
रक्षःऽहत्याय
वार्त्रऽहत्याय
वृत्रऽहत्याय
अहिऽहत्ये
दस्युऽहत्ये
वृत्रऽहत्ये
शम्बरऽहत्ये
वृत्रऽहत्येन
दस्युऽहत्येषु
वृत्रऽहत्येषु
शुष्णऽहत्येषु
वृत्रऽहथानाम्
अमित्रऽहन्
अहिऽहन्
वृत्रऽहन्
वृत्रऽहन्
अभीक्ऽहनः
पुनःऽहनः
शत्रुऽहनः
अभिमातिऽहनम्
अहिऽहनम्
तमःऽहनम्
दस्युऽहनम्
रक्षःऽहनम्
वृत्रऽहनम्
सत्राऽहनम्
अप्रऽहनम्
आऽहनसः
आऽहनसम्
तमःऽहना
दुःऽहना
रक्षःऽहना
वृत्रऽहना
सुऽहना
वृत्रऽहना
सुऽहनानि
सुऽहनाय
दुःऽहनायतः
दुःऽहनायाः
दुःऽहनायुवम्
दुःऽहनावान्
अर्यःऽहनुः
अरुतऽहनुः
दुर्हणौ इति दुःऽहनौ
वृत्रऽहनौ
वृत्रहन्ऽतम
वृत्रहन्ऽतमः
दस्युहन्ऽतमम्
वृत्रहन्ऽतमम्
वृत्रहन्ऽतमा
वृत्रहन्ऽतमा
निऽहन्तवे
अवऽहन्ता
प्रऽहन्ता
विऽहन्ता
दुःऽपरिहन्तु
सुऽहन्तु
पुरुऽहन्मन्
अश्महन्मऽभिः
अहन्यः
अहन्येभिः
वृत्रऽहभिः
वृत्रऽहम्
सत्राऽहम्
दस्युहम्ऽतमम्
वृत्रहम्ऽतमम्
अश्वऽहयः
अश्वऽहयैः
विऽहरति
उद्धरन्
प्रऽहरन्
विऽहरन्
विऽहरन्ते
वीळुऽहराः
प्रऽहराम
प्रतिऽहर्यते
प्रतिऽहर्यथ
अभिऽहर्यन्ति
उत्ऽहर्षयन्ति
वीळुऽहर्षिणः
सुऽहवः

घृतऽआहवनम्
आऽहवनानि
विऽहवन्त
सुऽहवम्
आऽहवम्
सुऽहवस्य
सुऽहवा
सुऽहवा
सुऽहवाः
इन्द्रऽहवान्
सुऽहवानि
सुऽहवाम्
सुऽहवासः
अहविः
हविःऽहविः
सुऽहविषे
शतऽहविषे
सुहवीतुऽनाम्ने
आऽहवे
विऽहवे
सुऽहवेभिः
हवेऽहवे
पृतनाऽहवेषु
आऽहवेषु
विऽहवेषु
विऽहव्यः
शतऽहव्यः
सुऽहव्यम्
वीतऽहव्यम्
वृष्टिऽहव्यस्य
शतऽहव्यस्य
शतऽहव्या
शतऽहव्या
शतऽहव्याः
सुऽहव्याम्
शतऽहव्याम्
शतऽहव्याय
वीतऽहव्याय
वीतऽहव्ये

स्वऽइदुहव्यैः
वज्रऽहस्त
वज्रऽहस्त
सुऽहस्तः
अहस्तः
उत्तानऽहस्तः
निक्तऽहस्तः
वज्रऽहस्तः
हिरण्यऽहस्तः
अहस्तम्
खादिऽहस्तम्
वज्रऽहस्तम्
हिरण्यऽहस्तम्
ऋजुऽहस्ता
सुऽहस्ता
अहस्ता
अक्रविऽहस्ता
घृतऽहस्ता
भद्रऽहस्ता
वज्रऽहस्ता
सुऽहस्ताः
उत्तानऽहस्ताः
विद्युत्ऽहस्ताः
सुऽहस्ताः
अहस्तासः
ग्रावऽहस्तासः
उभयाहस्ति
महाऽहस्ती
इषुऽहस्तेन
इषुऽहस्तैः
वज्रऽहस्तैः
सुऽहस्त्य
सुऽहस्त्यः
मधुऽहस्त्यः
सुऽहस्त्यः
सुऽहस्त्यम्
उभयाहस्त्या
उपऽहस्वानः
अघशंसऽहा

अदृष्टऽहा
अभिमातिऽहा
अमित्रऽहा
अमीवऽहा
अरुशऽहा
अशस्तिऽहा
असुरऽहा
अहिऽहा
गोऽहा
दस्युऽहा
नृऽहा
पुरःऽहा
मुष्टिऽहा
रक्षःऽहा
वृत्रऽहा
शर्यऽहा
सत्राऽहा
सपत्नऽहा
सप्तऽहा
अवीरऽहा
कृष्टिहाऽइव
मुष्टिहाऽइव
शर्यहाऽइव
निऽहाकया
प्रऽहाम्
अतिऽहाय
सम्ऽहाय
विऽहायसः
विऽहायसम्
विऽहायसे
विऽहायाः
सुऽहार्दम्
आऽहावः
आऽहावम्
दुष्कृतऽआहावम्
आऽहावाः
आऽहावान्
अहिंसन्तीः
अहिंसानस्य

अहिंस्यमानः
अभिऽहिंतः
अवऽहितः
आऽहिंतः
चनःऽहितः
दुःऽहिंतः
निऽहिंतः
पुरःऽहिंतः
प्रऽहिंतः
मनुःऽहितः
अतिऽहितम्
अपिऽहितम्
अप्रऽहितम्
अवऽहितम्
आऽहिंतम्
उद्धिंतम्
तिरःऽहिंतम्
देवऽहिंतम्
निऽहिंतम्
परिऽहितम्
पुरःऽहिंतम्
मनुःऽहितम्
सम्ऽहिंतम्
आऽहिंता
निऽहिंता
पुरःऽहिंता
सम्ऽहिंता
अपिहिताऽइव
निऽहिंताः
अपिऽहितानि
विऽहिंतानि
प्रतिऽहिताभिः
निऽहिंतासः
अस्मेऽहिंतिः
पुरःऽहिंतिः
देवऽहिंतिम्
निहिंते इति निऽहिंते
पुरोहिंते इति पुरःऽहिंते
अहिंतेन
अभिऽहिंतौ
पुरःऽहिंतौ
परिऽहिनोमि
शतऽहिंमा
शतऽहिंमाः
शतऽहिंमाय
सुऽहिरण्यः
आऽहुत
सुहुतऽअदः
सर्वऽहुतः
आऽहुतः
सुऽआहुतः
आऽहुतम्
प्रऽहुतम्
सुऽआहुतम्
सुऽहुतम्
आऽहुतस्य
आऽहुताः
प्रऽहुताः
आऽहुतानि
आऽहुतिः
आऽहुतिम्
प्रऽहुतिम्
आहुतिऽवृधम्
आऽहुती
आऽहुवः
आऽहुवध्यै
पुरुऽहूत
पुरुऽहूत
पुरुऽहूतः
आऽहूतः
पुरुऽहूतम्
देवऽहूतमः
यामऽहूतमा
देवऽहूतमान्
देवऽहूतयः
भरऽहूतये
पुरुऽहूता
अहूताः
उपऽहूताः
पुरुऽहूताय
सऽहूतिः
देवऽहूतिः
देवहूतिऽभिः
द्युम्नहूतिऽभिः
सहूतिऽभिः
इन्द्रऽहूतिम्
देवऽहूतिम्
पूर्वऽहूतिम्
सऽहूतिम्
देवऽहूतिषु
यामऽहूतिषु
सऽहूती
सहूती इति सऽहूती
पुरुहूते इति पुरुऽहूते
देवऽहूतौ
द्युम्नऽहूतौ
पूर्वऽहूतौ
भरऽहूतौ
यामऽहूतौ
देवऽहूत्या
देवऽहूत्यै
देवऽहूये
आऽहूयः
अहृणानः
दुःऽहृणायुः
दुःऽहृणायून्
अहृणीयमानः
अहृणीयमाना
बलिऽहृतः
परिऽहृतिः
सर्वऽहृदा
करुञ्जऽहे
अहेळता
अहेळन्
देवऽहेळनम्
अहेळमानः
अहेळयन्

अवयातऽहेळाः
प्रऽहेतारम्
तिग्महेती इति तिग्मऽहेती
तिग्मऽहेते
आशुहेमऽभिः
आशुऽहेमा
आशुऽहेषसा
यज्ञऽहोतः
सुऽहोता
कण्वऽहोता
नित्यऽहोता
पञ्चऽहोता
सप्तऽहोता
सुऽहोता
अग्निऽहोतारः
वीतिऽहोत्रः
सम्ऽहोत्रम्
वीतिऽहोत्रम्
वीतिऽहोत्रा

शुनऽहोत्रेषु
प्रऽहोषिणः
पज्रऽहोषिणा
प्रऽहोषे
अह्नवाय्यम्
अपऽह्नुवे
प्रऽह्वै
अह्रयः
अह्रयम्
अह्रया
अह्रयाणम्
अह्रयाणा
अह्रये
परिऽह्रुत्
अभिऽह्रुतः
अह्रुतः
अह्रुतऽप्सवः
अविऽह्रुतम्
विऽह्रुतम्

अह्रुताः
अभिऽह्रुताम्
अभिऽह्रुतेः
विऽह्वयन्ते
आऽह्वयमानान्
विऽह्वयामहे
विह्वयेते इति विऽह्वयेते
अविऽह्वरन्तम्
अनवऽह्वरम्
धरुणऽह्वरम्
उपऽह्वरे
प्रतिऽह्वरे
उपऽह्वरेषु
अपरिऽह्वृतः
परिऽह्वृता
अपरिऽह्वृता
अपरिऽह्वृताः
परिऽह्वृतिः
परिऽह्वृतिम्

खिलपदसूची

प्रास्ताविकम्

ऋग्वेदसंहितायाश्चतुर्थे भागे (८९१–१००१ पृष्ठेषु) यानि खिलसूक्तानि मुद्रितानि तेषामकारादिवर्णक्रमेण पदसूच्यत्र प्रस्तूयते। खिलमन्त्राणां पदपाठो नोपलभ्यते। यद्यप्यत्रस्थानि बहूनि खिलानि बाष्कलादिशाखासु वेदभागत्वेनान्तर्भूतानि तथापि तासां शाखानामिदानीं पठनपाठनादिप्रचाराभावात् लिखितपुस्तकाभावाच्च खिलमन्त्राणां पदपाठः प्रायोऽलभ्य एव। अतोऽर्थानुरोधेन क्वचित् वैदिकग्रन्थोपलब्धसमानमन्त्रपाठानुसारेण च पदानि पृथक्कृत्य सूच्यां प्रवेशितानि। अस्मिन्नेव पुस्तके पूर्वं मुद्रितायामृग्वेदपदसूच्यामृग्वेदपदपाठानुसारेण पदानि प्रदर्शितानि। पदपाठे पदेष्ववग्रहादिप्रदर्शनं सांहितिकदीर्घस्य ह्रस्वत्वं प्रगृह्यान्ते इतिकारोच्चारणमित्यादिकं यद्वैशिष्ट्यं तन्निबन्धनानि पदानि मुद्रितानि। अत्र तु तादृशस्य पदपाठस्यानुपलब्धेर्मन्त्रगतानि क्वचित्संधिनिविष्टानि पदान्यर्थज्ञानार्थं केवलं पृथक्कृत्य दर्शितानि। तेनात्र अवग्रहेतिकारादिपदपाठवैशिष्ट्यं सर्वथा नोपलभ्येत। सांहितिको दीर्घस्तावत् प्रायः ह्रस्वीकृत्य प्रदर्शितः। ऋग्वेदस्य स्वरोच्चारविषये क्रमागतपद्धतिमपहाय चतुर्थभागे मुद्रितेषु खिलेषु केवलमुदात्तस्वरः (स्वरितचिह्नवत्) पदेषूपरितनया रेखया प्रदर्शितः। तामेव रीतिमनुसृत्यात्रापि पदानामेक उदात्तस्वर एव उपरितनेन चिह्नेन दर्शित इत्यवश्यमवधारणीयम्। खिलेषु केषुचित् स्थलेषु (खि. ४.५.७–९; ११; १२; ४.११.९) स्वरितानुदात्तप्रदर्शिनीं स्वरपद्धतिमनुसृत्य मन्त्रांशा मुद्रिताः। तद्गतानां पदानामपि उदात्तस्वर उपरितनेन चिह्नेनैव प्रदर्शितः। खिलेषु कानिचन सूक्तानि स्वरराहित्येन मुद्रितानि। सूच्यां तावत् पदानामुदात्तस्वरप्रदर्शने यावच्छक्यं प्रयतितम्। विशेषतो निविित्सु (खि. ५.५) प्रैषेषु (५.७) च विद्यमानानां पदानामुदात्तस्वरोऽन्यत्रावलोकनेन प्रदर्शितः। अप्रमाणितखिलमन्त्रस्थानां पदानामुदात्तस्वरनिर्देश आयासो न कृतः। एकमेव पदं स्वरसहिते स्वररहिते च मन्त्रे विद्यमानं चेत् उभे अपि स्थले स्वरयुक्तपदनिबन्धनत्वेन प्रदर्शिते।

यद्यपि खिलमुद्रणावसरे खिलपाठविषये उपलब्धसाधनानुसारेण यथामति विचार्य पाठो निश्चितः तथापि सूचीविरचनावसरे बहूनां पदानां पाठविषये स्वरविषये च पुनर्विचारः कर्तव्य आसीत्। एवं येषां येषां पदानां पाठः स्वराक्षरविषये मुद्रितपाठात् भिन्नत्वेनात्र सूच्यां स्वीकृतः तेषां मुद्रितपाठः पृथक्स्वरूपेण पादटिप्पणीषु § चिह्नेन प्रदर्शितः। खिलमन्त्रैरंशतः पूर्णतो वा समानाः केचन मन्त्रा वेदेषु विशेषतोऽथर्ववेद उपलभ्यन्ते। तद्गता भिन्नाः पाठाः खिलमुद्रणसमये प्रदर्शिता एव। तेषां केचन मूलपाठत्वेन स्वीकर्तव्या इति मत्वा सूच्यां समावेशिताः। मुद्रितपाठानां नातिशुद्धतया केचन पाठा अभ्यूहनीया अप्यासन्। एतादृशेषु सर्वेषु स्थलेषु खिलग्रन्थमुद्रितपाठाः टिप्पणीषु निर्दिष्टाः। यत्र मुद्रितपुस्तकेऽविद्यमानः स्वरः सूच्यां प्रदर्शितः तादृशेषु स्थलेषु स्वररहितो मुद्रितपुस्तकपाठः पादटिप्पणीषु प्रायो दत्तः। खिलसंपादकेन शेफ्टेलोविित्झमहाशयेन स्वीकृतः क्वचन समर्थितश्च खिलपदानां पाठः सूच्यां नाङ्गीकृतश्चेत्, सोऽपि पादटिप्पणीषु प्रदर्शितः, आवश्यकतानुसारं तदनङ्गीकारे कारणमपि प्रदर्शितम्।

प्रतिपदं स्थापिताः संख्याङ्काः क्रमेण अध्यायं सूक्तं मन्त्रं च बोधयन्ति। पञ्चमेऽध्याये सप्तमं खिलं प्रैषाध्यायसंज्ञकं पञ्चसूक्तात्मकम्। तत्रैकैकस्मिन् सूक्ते अकारादिवर्णबोधिता अनेके प्रैषा विद्यन्ते। तद्गतानां पदानां स्थलबोधनसमये संख्याङ्कैः साकं तत्तत्प्रैषबोधको वर्णोऽपि

प्रदर्शितः। यथा ५.७.२ औ। एकमेव पदमेकस्मिन् सूक्ते नैकेषु प्रैषेषु स्थितं चेत् तेषां स्थलनिर्देशे सूक्तसंख्याङ्काः पुनर्न दत्ताः। यथा ५.७.२ अ, इ, ओ। अध्यायपञ्चकपरिमितेभ्यः खिलेभ्योऽधिका ये अनेके मन्त्राः पुस्तके मुद्रिताः तेषां पदान्यपि सूच्यां समावेशितानि। तानि तु सर्वथा स्वररहितानि, अतः प्रायस्तथैव मुद्रितानि। एतेषु कानिचन पदानि अध्यायपञ्चकमितेषु खिलेषु सस्वरमुपलब्धानि चेत् तैः समानस्वराणीति मत्वा तैः सह संगृहीतानि। अप्रमाणितखिलगतानां पदानां निर्देशकः संख्याङ्को मुद्रितपुस्तकपृष्ठं बोधयति, तेषां खिलानां पृथक्स्वरूपबोधनार्थं च सः कोशे स्थापितः। यथा (९७२)। एकमेव पदं प्रमाणितेष्वप्रमाणितेषु च खिलेष्वागतं चेत् प्रमाणितखिलबोधकः संख्याङ्कः पूर्वं स्थापितः।

मुद्रितपुस्तकपाठापेक्षया ये भिन्नाः पदानां पाठा अस्यां सूच्यां स्वीकृताः तेषां पाठनिर्धारणे स्वरनिर्धारणे च यैर्यैर्विद्वद्भिः साहाय्यमाचरितं तेभ्यो धन्यवादान् वितरामि। एतद्विषये अस्मद्गुरवः आचार्य-वि. प्र. लिमये-महोदयाः विशेषतो निर्देशमर्हन्ति। स्वरनिर्णयार्थं पुण्यपत्तनस्थतिलकविद्यापीठीयसंस्कृतमहाविद्यालयाध्यापकैः वा. बा. भागवतशास्त्रिमहोदयैरन्यैश्च यत्साहाय्यं कृतं तदर्थं ते धन्यवादार्हाः। नागपूर-विद्यापीठान्तर्गतवेदाध्ययनमण्डलेन डॉ. सिद्धेश्वर-वर्ममहोदयद्वारा केषांचित् पदानां पाठविषये स्वकीयं मतं प्रदर्शितम्। अतः तस्याप्युपकारं स्मरामि। पदपाठशुद्ध्यर्थं बहु प्रयतितेऽपि बहूनां लिखितपुस्तकानामभावात्, अन्येषां निर्णायकसाधनानामल्पीयस्त्वात्, मानुषसुलभदोषाच्च बहवो दोषाः पदपाठनिर्धारणविषये स्वरविषये च सत्यमवशिष्यन्ते। तेषां शोधने विद्वद्भिः साहाय्यं कृतं चेत् वेदैकदेशीयानां खिलानां सम्यगर्थज्ञानाय वेदाभ्यासकानामुपकाराय च स्यादिति संप्रार्थ्य विरमामि।

विदुषां विधेयः

चिं. ग. काशीकर

|| श्रीः ||

|| खिलपदसूची ||

अ

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §अंशु. २. §अंहसः. ३. §अक्षीभर्वः. ४. §अगमन्. ५. §अग्निः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. इदं 'घद्' धातो रूपमिति शेफ्टेलोविट्झमहाशयेनोक्तं (पृ. १५०)। परं 'घद्' इति धातुः पाणिनीयधातुपाठे नोपलभ्यते। घस्लृधातोः अघस्तम्, अघस्ताम् इत्यादीनि रूपाणि भवन्ति। तत्र सकारलोपेनेदं रूपं संपन्नं (Prakritisation) इति भाति। २. §अघ्न्या. अस्याग्रे वर्तमानस्य 'सु' इति पदस्य सकारसंबन्धेनाग्रस्थो विसर्गो लुप्त इति भाति।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

1. §अर्थ २.६.६.
2. §अद्य ३.१५.३२; ५.१.३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §अद्वयाः. २. §दधि. ३. §अधिष्ठाय. ४. §अधिरस्था. ५. 'अना' इत्यस्याग्रे अक्षरद्वयं लिखितपुस्तके नष्टम्। ६. §अनु ४.५.३८. ७. 'ज्ञातीरनुजास्वन्वा' इति मुद्रितपुस्तकपाठस्थाने 'ज्ञातीँरनुजान् पूर्वान्' इति पाठमभ्यूहामः।

पदेषूपरिस्थं चिह्नमुदात्तस्वरं बोधयति।

१. §अन्तर॑.　२. §अन्तिकाम्.　३. §अपाक्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §अपिशाचधीतः. २. §अपुरोगवासः. ३. §अभि २.८.३; ३.१५.९. ४. §अभिगूर्तया. ५. §अभिगूर्याः. ६. §अभिद्यु. ७. ऋक्सं १.५२.१०; ५३.८; २.११.२; ८ द्रष्टव्यम् ।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §अमंहत. २. §अमर्त्याः. ३. 'अमोतपुत्रका एषामु मोदका उपासते' इति मन्त्रार्धः 'अमोतं पुत्रका एषाममोतं गाइवासते' इत्याथर्वणमन्त्रानुसारेणाभ्यूहनीयः। ४. §अयान्त्स्युः. अयं पाठोऽशुद्ध इति कृत्वा 'अयांसुः' इत्यभ्यूहितः।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. ‘ सनुतरेणा नरुषो ’ इति पुस्तके मुद्रितं ‘ सनुतरेणानररुषो ’ (सनुतः + एनान् + अररुषः) इत्यभ्यूहितम्। २. §अरातीः ३.१६.३. ३. यदि नो जीवयस्व ईम् इति पाठः ‘ यदि नो जीवयस्यरीन् ’ इत्यभ्यूहितः। ४. §अस्यार्दतः (= अस्याः + अर्दतः). ५. §अलंकृताः. ६. §अलाबुकम्, अलाबुकम्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §अवं. २. §अवतः. ३. §अविचेतनानि.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §अश्विना १.२.५; ५.१.२; अश्विना १.१२.२. २. §अश्विनौ. ३. §अष्टषष्टम् ४. 'निहिता॥पि' ४.४.३ अस्य स्थाने 'निहितासि' इत्यथर्वमन्त्रानुसारेण पठनीयम्। ५. §असुरान्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. 'विश्वञ्चावस्यार्दतः' ५.२२.२ इति मुद्रितपाठः 'विष्वञ्चावस्या अर्दतः' इत्यभ्यूह्यते। २. 'अस्येश्वरया' इत्यस्य स्थाने 'अस्यै स्वधया' इति पठनीयम्। ३. §अहिंसन्तम्. ४. §अभिघ्नन्. ५. §आ ३.१५.३; ४.९.३; ५; ५.२.३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. 'नादितेयौ' इति पाठः 'नादितेयाः' इत्यभ्यूहितः। २. §आधिपत्य १.४.९. अग्रे वर्तमाने 'मे' इति पदे मकारो लुप्तः। ३. 'कुवीरं ते सुखं रुद्रं नन्दीमानं विमथ ह' इति ४.५.४० अस्य मन्त्रस्य पूर्वार्धः सर्वथापभ्रष्टः। 'कुबेर ते मुखं रौद्रं नन्दिमानन्दमावह' इति आंध्रपुस्तकपाठानुसारं तं शोधयितुमुचितम्।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §आयक्षते ५.७.२क.   २. §आविरुक्थ्य३मना ?

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. 'परेहितो' इति मुद्रितपाठः 'परेहीतो' इत्यभ्यूहनीयः । २. §इत्थ कम्. ३. §इन्द्रः ४.५.२७; २९. ४. §इन्द्रकेशम्.

ई

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. 'परेहितो' इति मुद्रितपाठः, 'परेहीतो' इति शुद्धः पाठः । २. §इहेह. ३. §ईळितः.

ईशानाम् (९३३)
ईशिषे १.१.२; ५.५
ईशे ५.४.८; (९२५)
ईश्वरः (९७३)
ईश्वरीम् २.६.९; (९३३)
ईषमाणाः ५.८.२

उ

उ[1] १.३.५; ६; ११.४; २.९.१; ३.४.१०; ४.५.१६; ३४; ६.१; ६; ९.५; ११.४; ५.४.५; ११; ११.२; ३; १३.१–६; २०.१; २; २१.३; (९४७)
उक्तम् (९७३)
उक्थशस्तः १.७.१
उक्थशासः १.१२.२
उक्था ३.४.३; (९९२)
उक्थामदानि (९९२)
उक्थिनः ३.५.६
उक्थेभिः ३.३.३; ५.६.५
उक्षणः ३.७.२
उग्रः ३.१.७; २.७; ४.५[2]
उग्रम् १.११.५; ३.१.६; २.६; १२.३; ५.१५.१६; (९४६)
उग्रस्य ५.११.१
उग्रा १.५.७; ११.७; ४.११.१२
उग्रायुधाः (९३९)
उग्रे[2] ४.५.३३
उग्रेण[3] ३.१५.३०
उच्चैः ४.६.२
उच्चैःश्रवसम्[4] ५.१४.४; ५
उच्च्यावयतात् (९९२)
उच्यते (९३९)
उत्[5] ३.१६.१; २[2]; १९.१; ४.५.१२; २९; ३२; ३४; ९.३; ५.५.११[2]; ७.१ऐ; ४च; ११.१; १५.१६; १७.१; २२.११; (९६३)
उत[6] १.४.४; २.८.२; ११.४; ३.४.८; ५.७; ६.६; ४.९.३; ११.३; ५.३.२; ९.२[2]; २०.३[2]; (९२५, ९५६, ९६५; ९६८, ९९२)
उतो ४.२.२; ५.७.४ज; २०.३
उत्खिदतात् (९९२)
उत्तमः ४.१२.२
उत्तमम्[7] १.५.३; ३.१६.७
उत्तमे ३.३.४
उत्तरतः २.२.१; ४; ४.५.२४
उत्तरेण ४.९.३
उत्ताना ४.१३.२
उत्तानायै ५.१६.४
उत्तुद ३.१६.१
उत्थात् २.११.३
उत्पत ५.१५.८
उत्पतन्ति (९४९)
उत्पन्नम् (९५८)
उत्पातितम् (९७३)
उत्सम् २.१२.१
उत्सादतः ५.७.२ऐ; (९९०)
उत्सृजे (९३२)
उदक्[8] ५.१२.३; १७.१–४
उदकम् (९४७[2])
उदके (९२६, ९३७)
उदन्तु ३.१६.२
उदरणे ५.५.७
उदरम् (९३७)
उदाराम् २.६.५
उदाहृता (९५८)
उदितम् (९७३)
उदीचीनाम् (९९२)
उद्भृतम् (९९०)
उदुम्बरः ५.२२.१०
उद्दचम् ५.७.४च

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §उं ४.९.५. २. §उग्रे. ३. 'तपसो गृणं' इति मुद्रितपुस्तकपाठः 'तपसोग्रेण' इत्यभ्यूहितः। ४. §उच्चैःश्रवसम् ५.१५.४. ५. उत् ५.१७.१. ६. मुद्रितपुस्तके 'अमोतपुत्रका' (५.९.२) इत्येकीकृतं तदशुद्धम्। ७. §उत्तमम् ३.१६.७. ८. §उदक् ५.१२.३; उदक् ५.१७.१–४.

ऊ

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §उप २.६.१६. २. §उपासते ५.३.३. ३. §ऊतिभिः १.८.३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१० §ऋषिः ५.३.५.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §एक कम्. २. §एकम् ५.३.२[२]. ३. एतेदं = एताः + इदम्. ४. 'अररुषः' अत्रस्था टिप्पणी द्रष्टव्या। ५. §एव ३.११.१; १५.२८; ४.५.२७; ३०. ६. §एषि. ७. §एषु. ८. §ओजः १.२.९.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §कः ४.५.११. २. §कक्षीवान् ३.१५.३१.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §कल्याणी ५.१३.३. २. §कांस्यस्मि तां. शेफ्टेलोवित्झमहाशयः 'कांसी अस्मि तां' इति पदानि संभावयति। कांसिन् इति पदस्य च कम्धातोरुत्पत्तिं कल्पयति। अस्मन्मत एतदनावश्यकम्। कांस्यस्मितां कंसमिव प्रकाशमानं स्मितं यस्याः ताम् इत्यर्थः। धातुवाचकः कंसशब्दोः ब्राह्मणग्रन्थेषूपलभ्यते। ३. §किम् ४.५.३४. ४. §किरणौ ५.१६.१. ५. §कुवीरं. दृश्यताम् 'आनन्दम्' अत्रस्था टिप्पणी। ६. §कुंभि.

कुह १.१५.३; ४.६.१०[१]; ८.९; (९५७[२], ९६४)
कुमः ४.३.१
कुयांत् (९६३)
कुर्वन् ५.१०.२
कुलायम् ५.१५.१६
कुले २.६.११; १२; (९६३)
कुशिकः (९५८)
कुशिकाभ्यवराणाम् ३.१५.३०
कुहम् ५.१५.६
कुहा ५.१५.७
कुहूः (९२५)
कुहूम् (९२५)
कृकवाकुम् ५.२२.८
कृणुतम्[१] १.५.९; ३.१६.७
कृणुतात् (९९२[२])
कृणुते ४.६.७[२]
कृणुथः १.५.७
कृणुष्व १.४.६; ३.१६.५; (९६३)
कृणुहि (९३८)
कृणोतु १.३.६; ५.७.२अः; (९९१)
कृण्मः ४.४.३; ५.३३
कृण्वत् ४.६.९
कृण्वन् ५.५.२
कृण्वन्ति ४.११.२
कृण्वानाः ४.४.४
कृण्वाने ५.७.१ओ
कृतपुण्यानाम् (९३२)
कृतम् १.४.४; ३.१५.१८; ३१; २०.१; ४.७.३; (९४६; ९४७)
कृत्याः ४.५.१३; २३
कृत्यानाम् ४.५.३०
कृत्याम्[२] ४.५.१; ५
कृत्ये[३] ४.५.३; ५–८; १२; १५; २१; २५; ३२
कृत्वा ३.१६.४
कृत्वी ५.७.२औ; (९९०)
कृत्न्ये ३.१.९
कृधि २.२.४; ३.५.४; ६; १२.१–३; १६.४; ४.५.७; १९; २४; ९.४[२]; (९२५, ९४८[३], ९६३)
कृपम् ३.१५.२६
कृपा ३.२२.४
कृशः १.५.१; ११
कृशम् १.५.७
कृशौ ३.६.२
कृष्टीः (९२५)
कृष्ण (९३३)
कृष्णकेशेषु ३.१५.१६
कृष्णवर्ण (९६५)
कृष्णवर्णो (९६३)
कृष्णाम् ४.२.३
कृष्णाय (९३३)
कें २.८.३; (९३९)
केतुमन्तम् १.४.१
केतुमान् १.१२.५
केन (९६६)
केवला ३.४.३; ४.९.७
केशनखे (९६३)
केशव (९३३)
केशिनी ५.१५.५
केशिनीम् (९५७)
कैलासशिखराभासाः (९७३)
कैलासशिखरे (९७३)
कोशम् १.४.८
कौषधावनीः ५.७.१ऐ
कौरवे ५.८.१
कौरव्यः ५.१०.२
कौशिकस्य (९५२)
क्रतुः ५.४.६
क्रतुना १.४.२; ३.५.६
क्रत्वा ३.१६.२[२]; ५.६.३
क्रत्वे (९२५)

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §कृणुत १.५.९. अग्रे विद्यमाने ‘मा’ इति पदे मकारो लुप्तः । २. §कृत्यां ४.५.५. ३. §कृत्ये ४.५.८.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §क्षिप्रं ४.५.६. २. §क्षुत्पिपासामला. ३. §खनेम. ४. §गृच्छ ४.५.१०. शेफ्टेलोवित्झमहाशयः 'जृ' धातोः सादृश्यात् 'नी-गर्' इति झेंदभाषीयधातोः सादृश्याच्च 'गृ' धातुं कल्पयति। परम् अथर्ववेदगतेऽस्मिन् मन्त्रे 'गच्छ' इति पदं वर्तते। 'तत्र तेऽयनम्' इत्यथर्वमन्त्रस्याग्रिमपाठेन च तत् सम्यगन्वेति। खिलमन्त्रे 'तत्र ते जनम्' इति वर्तते। अत्रस्थो जकारोऽशुद्धः प्रतिभाति।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §गर्भः २.८.३. २. §गविष्टौ १.१०.३. ३. §एषामु मोदका उपासते. अत्र 'एषाममोतना इवासते' इति पाठोऽभ्यूह्यः। ४. §गृहपतिः ४.९.१. ५. §गोअमयाणाम्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §ग्रथिता (तुर्वशासः). २. §ग्रावो. ३. §घृतश्चुता १.६.४; ५. ४. घोर. ५. §घोषाम्. ६. 'सभा समासावितुंश्चावतामुभे' (३.१५.१३) अस्य स्थाने 'सभा च मा समितिश्चावताम्' इत्याथर्वणमन्त्रानुसारेण पठनीयम्।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §चकमानौ. २. §चक्षुषी ४.११.११. ३. §चरतः ३.२२.८. ४. §चाक ३.१५.१३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §चित् ४.५.३४. २. §जगतः ४.२.३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §जयान्. २. §जरामृत्युः. ३. §जातवेदाः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §जीवयस्व. २. §ज्ञातीरनुजास्वन्वा। अत्र 'ज्ञातीरँनुजान् पूर्वान्' इति पठनीयम्। ३. 'विष्पूर्यते शिरः' अस्य स्थाने 'विष्फूर्य तच्छिरः' इति पठनीयम्। ४. §तं ४.११.८; तत् ५.१.५.

तत्परात् (९७२[२], ९७३[२])
तत्र १.११.५; ३.१२.१–३; १८.२; ४.५.१०; ५.७.२औ; (९४८[२], ९४९, ९७३, ९९०)
तत्रो ३.८.४
तथा १.२.६; ३.१५.११; ४.५.९; ३१; ३५; ११.४; ५.७.४च; १६.१–६; २२.७; (९३७[२], ९५२, ९७२)
तथाद्वैश्यम् ? (९७३)
तदर्पसः ३.१३.१
तदा[१] १.८.१
तदिव ४.११.१३
तद्धर्तुः (९५२)
तनयम् १.३.७
तनये (९९२)
तनुः ४.५.११
तनुतः ३.२२.६
तनुत्यजाः ३.१२.१
तनुभ्यः ४.४.२
तनुम् ४.५.७
तनूकृतः ५.६.६
तनूनपातम् ५.७.१आ
तनूनाम् १.८.१
तनोति १.१२.५
तन्तून् (९६३)
तन्वः ३.११.२
तन्वताम् ५.७.१अं
तन्वम् (९४९)
तन्वा १.७.३
तन्वानाः १.६.६
तपः ४.४.२; (९४७)
तपति (९६६)
तपतु ३.१६.२
तपन्ति[२] १.१२.४
तपसः २.६.६; ४.११.१३, (९४७[२])
तपसा[३] १.६.६; २.६.६; ३.१२.१; १५.३०; (९५७, ९७३)
तपुषे ४.४.३
तमः १.२.१०
तम् १.२.१०; १२; ३.२; ४.१; ७; ५.२; ९; ९.३; १०.३; ११.१; ३; २.१०.५; ७; १२.१; १३.१; ३; १५.१; ३.३.३; ५; ६; ४.४; ५.२; ८; ४.२.१; ५.३; ५; १०; १८; २५; ३६; ३७; ३९; १३.२; ५.१.४; ४.५; ६; ९; ७.२क; १५.२; ९; (९३९)
तमः ५.१०.२
तमसः ४.११.९
तमसा ३.२१.१
तमांसि ५.५.१०
तया[४] ३.११.२; १५.६; ४.५.३१; ६.४; ८.९; (९६६)
तयोः १.३.७
तरन्ता ३.२२.८
तरन्ति ४.६.७
तरसे (९५७[२])
तरुणः[५] ५.७.३आ
तरेम २.६.१९[२]; ७.५[२]; ८.५[२]
तर्पयतम् १.८.३
तर्पयन्ताम् ३.१५.२९
तर्पयन्तीम् २.६.४
तव २.६.६; १९; ७.५; ८.५ ११.५; ३.१५.४; ८; २९; (९६५)
तवसः १.४.८; ५.५.९
तवस्तमः ५.५.३
तविषम् १.४.२
तस्करत्वात् (९४६)
तस्तभुः ३.७.२
तस्थतुः १.६.२
तस्थुषः १.२.१३
तस्थौ ३.४.७
तस्मात् २.६.१८; ३.२०.१
तस्मिन् १.१२.७; (९३९)

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §तदा. २. 'सातपन्ति' अत्र 'साता तपन्ति' इति पदच्छेदः. ३. §तपसो ३.१५.३०. ४. §तया ४.८.९. ५. तरुणा.

पदेपूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. ईस्यानि ४.५.३३. २. ईस्य ४.५.३३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §ताभिः १.१२.३; ४. २. §त्यम् १.२.७. ३. §त्रिदिवम्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §त्वम् ५.४.२. २. §दधतः ३. §दधन्वी.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §दशस्यतम्. २. §दस्रौ १.३.६. ३. §दाक्षायणाः. ४. 'दासीद्विशो' इत्यस्य स्थाने 'दासीर्विशो' इति पठनीयम्। ५. §दीदास.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. ¶दुरश्रुते॰ २. दुरिष्टम् ? ३. ¶दुहितारौ॰ ४. अत्र कतिचिदक्षराणि नष्टानि॰ ५. ¶ते दृश्यते॰

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §देवौ १.२.१४. २. §देवशः. ३. §देवाः.

ध

पदेपूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §धत्तम् १.५.११.

न

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. 'धानासोमानाम् ५.७.४च. अस्य स्थाने 'धानाः सोमानाम्' इति पठनीयम्। २. §धावति. ३. §ध्रुवन्ति. ४. §ध्रुवा ३.१७.१. ५. §न ३.२२.५; ५.१५.१७. ६. §नः ३.१६.७.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §नक्तम् ३.१६.३. २. §नन्दीमानं. ३. 'अन्तर्निहितापि नासि' (४.४.३) अस्य स्थाने 'अन्तर्निहितासि नाभिः' इति अथर्वपाठानुसारेण पठनीयम्।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §नासत्या १.२.१; ३.६; नासत्या १.३.५. २. §निष्पृध्य. द्रश्यतां 'प्रपुध्य' ५.७.४क.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. 'नाभिः' अत्रस्था टिप्पणी द्रष्टव्या । २. ?

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §पतीं ५.६.२. २. §पदे ३.१५.१३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. ई परिस्रुतम् २.१३.२.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §पितृभ्या. २. §पुंसु.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §पुनते ३.५.६. २. §पुंमां ५.१५.४. ३. §पुरुश्चन्द्र.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §स्वन्वां. २. §पेर्दवे.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §प्रजा.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §प्रीणयन्ति. २. §बप्सथः. ३. 'अस्मान्नि बर्हरस्योनम्' इति पाठस्य स्थाने 'अस्मन्नि बर्हीरस्योनम्' (अस्मत् + नि + बर्हीः + अस्योनम्) इति शोधयितुमुचितम्। ४. §बहुधा ३.१५.१८; ३१. ५. §बह्वीः ४.१२.१.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. बिभ्रत् ४.९.५. २. §बृहस्पतिः ३.१५.१. ३. §बृहस्पतिम्. ४. §ब्रह्मणः ५.१३.२. ५. §ब्रह्मणा ४.५.३६. ६. §ब्राह्मण्यकृतः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. ? २. §भृज्ज. ३. §मघवत्तम. ४. §मघवन् १.२.१०. ५. §मणिना ३.१५.७.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §मधु १.११.५. २. §मनः ३.१५.१५. ३. §मन्दसानः ३.१४.१.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §महाँ ५.२२.१०. २. महिष्वणिस्था ५.१३.६.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §मही १.१०.२; ४.१३.२. २. ? ३. 'समासावितुश्च' (३.१५.१३) अस्य स्थाने 'च मा समितिश्च' इति पठनीयम्। ४. §मातरिश्वनि. ५. §मात्रा. ६. §मानयेथाम्. ७. §माम् ४.८.३. ८. §मिमाद्ब.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §मुखम्. २. §मूर्ध्नि. ३. §मेधा. ४. §मेधा १.७.३; मेधाम् ४.८.१[४]; २[३]; ६[२]; ७; ९. ५. §मेधावी ४.८.६.

य

यंसत् ५.५.८
...य[१] ३.१५.१४
यः १.४.१०; ५.८[३]; ६.३; १०.३; ४; १२.५; २.६.१६; ८.२; १०.५[२]; १३.१; २; ३.१.१; २.१; ३.३[२]; ५; ८; ४.३[२]; ५; ५.२; ७; १८.२; ४.३.१[२]; ४.१; ५.२; ५; ७; १०; ११; १४; १७[२]; १८[२]; १९[२]; २०; ३५; ३७[२]; ३८; ३९; ६.५[२]; ७; ७.२; १०.२; १३.१; ५.१.४; ४.४; ५; ९; ५.८[२]; १०.१; १२.१; २[२]; ४[२]; १३.१; २; १४.३[३]; (९२४[२], ९२५, ९३१, ९३३, ९३७, ९३८, ९३९[२], ९४७, ९४८; ९५८; ९६३[४], ९७३[४])
यका ५.१५.१०
यक्षः ४.९.२
यक्षत् ५.५.१; ७.१अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क,ख; २आ,इ,उ,ए,ऐ,औ,अः[२]; ४अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क,ख,ग,घ,ज; ५अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क,ख; (९९०[२], ९९१[२], ९९२, ९९३[२])
यक्षम् ४.११.२
यक्ष्माणाम् (९६८)
यच्छ २.९.३; ४.९.३; ५.७.४छ
यच्छतम्[२] १.१२.३; ४; ५.१.२
यच्छतु १.२.१४; ३.१५.२१
यज ४.९.५; ५.७.१अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क,ख; २आ,इ,उ,ए,ऐ,औ,अः; ३अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क; ४अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,क,ख,ग,घ,च,ज; ५अ,आ,इ,उ,ए,ऐ,ओ,औ,अं,अः,ख; (९९०[२], ९९१, ९९२, ९९३[२])
यजताम् ५.७.५क
यजते २.३.१
यजत्रा[३] १.४.२; ५
यजमानः ५.७.२क[१]; ४ङ[१]; ५ख
यजमानम् १.८.३; ५.५.२–११
यजमानस्य ३.१८.२; ५.७.४अः
यजमानाय १.६.१; ४; ५.७.३उ; ४ग,घ
यजमाने ५.७.४च; (९२५)
यजमानेन ५.७.५ख
यजमानेषु १.६.७
यजामहे (९७३)
यजूंषि ४.११.५
यज्वा ५.१२.१
यज्ञ (९७८)
यज्ञः ४.११.१
यज्ञचितेष्टकाः[४] ४.११.८
यज्ञपतये ५.१.५; ३.७
यज्ञप्रीः ५.६.१
यज्ञम् १.२.१३; ४.३; ६.६; ३.१.७; ११.१; १८.२; ४.३.१; ९.५; ६; ५.५.७; ६.१; ४.६; ७.१उ,औ; ३ओ,क; ४औ; (९२५; ९३९)
यज्ञस्य ४.११.७; ५.६.६; ७.२अ; ४च
यज्ञानाम् ५.५.१
यज्ञान्ते (९२४)
यज्ञाय ५.१.५; ३.७; ५.८
यज्ञियः ४.९.२
यज्ञियम् ५.५.६
यज्ञियासः १.११.१
यज्ञे ३.१.७; ४.११.२; ५.६.६; ७; ७.१ए,ऐ; ३इ; (९२५)
यज्ञेयज्ञे १.६.१
यज्ञेश (९३३)
यत्[५] १.२.१; २; ३.१; ४[२]; ५; ७; ४.१०; ६.१; ६; ९.३; ४[२]; ११.१; २; ५; १२.२; ५; ८[२]; २.७.२; ४; ३.१.७[३]; २.२; ३; ७[२]; ६.५; १५.४[२]; १४; १८; ३१; ३२; २०.१[३]; ४.४.३; ५.१९; ६.५; ६[३]; ८; ७.३[३]; ८.३; ४[२]; १०.२; ११.२; ३[२]; ४;

पदेपूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. अयं प्रायः कस्यचन पदस्यान्तिमो वर्णः। अस्मात् पूर्वं मन्त्रांशस्त्रुटितः। २. §यच्छताम् ५.१.२. ३. §यजत्रा १.४.५. ४. §यज्ञचित्तेष्टकाः. ५. §यत् ३.१५.४; ४.६.८.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §यत्तः. २. §यथा ५.२.३. ३. §यदि ४.९.३. ४. §यमः ४.५.२७. ५. §ययैः. ६. §यशस्विनाम्. ७. §यस्य ४.११.१०. ८. §यः १.१२.४. ९. 'मायान्तरा याश्च' (२.६.६) इति मुद्रितपुस्तकपाठः 'या आन्तरा याश्च' इति शोधनीयः। १०. §येति १.८.१. ११. §याथ. १२. §यान् ४.९.६.

र

पदेषूपरितनं चिह्नमुदात्तस्वरं बाधयति।

१. ? २. ?युवानम् १.२.७.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §रथान् १.११.५. २. §रभिष्ठ्या. ३. §राजा ४.८.२. ४. §रात्रीम् ४.२.४.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §रासभाश्वा. २. §रिशादसम्. ३. §रिषत्. ४. §रुचम् १.४.१०. ५. §रेभासः. ६. §रौत्सीत् ४.७.५. ७. §रुद्रम्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §वज्री १.५.१०. २. §वत्साः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §वरत्रयाः. २. §वरिवोभा (= वरिवः + उभा). ३. §'श्रीवर्चस्वम्' अस्य स्थाने 'श्रीवर्चसम्' (श्रीश्च वर्चश्च) इति पठितुमुचितं प्रतिभाति। ४. §वर्चसे. ५. §वर्चस्यम्. ६. §मर्माणि.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §वसुमता २. 'नन्दीमानं विमथ ह' (४.५.४०) अस्य स्थाने 'नन्दिमानन्दमा वह' इति पठनीयम्। ३. §वहतम्. ४. §वहन्तु १.२.३. ५. §वाचा ३.१५.३.

वाताःइव ३.१.८
वापीकूपतडागानाम् (९२६, ९३७[२])
वाम्[१] १.२.२–४; ३.३; ४; ६; ४.१; ४; ५; ७; ५.८; ९; ६.१[२]; ३; ४; ७.१; ३; ४; ६; ८.२; ९.२–४; १०.१[२]; २–४; ११.२; ५[२]; ८; १२.२–५; ८; ३.११.१
वामम् (९२५)
वामस्य ५.७.१अ
वामीः ५.७.४औ
वायसः १.२.११
वायसम् १.२.११; २.४.१
वायुः २.९.२; ५.६.१; २; ७.४ए; (९३२, ९६६)
वायुम् ५.७.४ए
वायो २.१०.७
वारः[२] ५.१५.५
वारय (९३९)
वारयध्वात् (९९२)
वारितीनाम् ५.७.३अः
वारेष्ठाव्याः १.७.२
वार्त्रघ्नम् ५.७.४अः
वार्या ५.७.२क; ४ङ
वार्याणि ५.७.३उ
वावदीति ५.२१.३
वावनत् (९२५)
वावाता[३] ५.१३.६
वावृधानः ३.५.२
वासन्तिकमिव[४] ५.२२.३
वासय २ ६.११; १२
वासात्यौ १.२.५
वासुदेव (९३३)
विंशतिंप्रत्यराभिः[५] १.२.१२
वि १.१.२; ३.६; ७.३; ११.६; ८; १२.५; ६; २.८.३; ४; ११.२; ३; ३.५.७; ७.१; १८.१[२]; २२.१[२]; ६; ४.२.१; ५.२; २२; ५.५.११; ७.१ए,ऐ[२]; ३इ; ४ङ[२]; १०.३; ११.१; १२.५; १७.३; ४; १९.१; २२.३; (९४९, ९७२)
विकेशी २.११.३
विक्षि ५.५.७
विख्यातम् (९५८)
विगाहथाः ५.१४.१
विचक्रमे ३.४.३
विचक्षण १.१.३; ५.६; ४.८.५
विचक्षणा ३.२२.७
विचक्षे १.११.८
विचरन्तः ३.७.४
विचर्षणे १.५.२
विजातः ३.२२.३
विड्भ्यः ५.५.८
विड्वीः ५.७.३आ
विततौ ५.१६.१
वितर्तुरम् ३.२२.९
विदत् १.२.१३
विदथे १.९.२; ६; ४.४.४
विदथेन १.११.४
विदथेषु १.२.२; ३.७; ४.११.२
विदथ्यः ५.१२.१
विदधत् ३.२२.१०
विदा ५.४.१[२]; ४
विदे ३.१.१; ५.४.५
विद्म ३.३.५; ४.४.३; ५.२२.८
विद्मः ४.५.३३
विद्मनापसम् (९२५)
विद्महे (९३२)
विद्यात् १.४.१०
विद्याम ३.२.९
विद्युतः २.५.१; (९३३)
विद्युता ४.५.१७
विद्युते ४.४.१
विद्युद्धतः ४.५.३८

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §वा १.८.२. २. §वारः. ३. §वावाता. ४. §वासन्तिकमिव. ५. §विंशति प्रत्यराभिः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §विन्दतु. २. §विन्देथे. ३. §विभुः. ४. §विविचिम्. ५. §विश्वदेव्योः.

पदेपूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §विंषितस्तुकम्. २. §विष्पूर्यते. ३. §विष्वञ्चौ.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §विषम्. २. §वृथा. ३. §वेनं तागच्छतं. ४. §वेशं प्रतिवेशिना.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §व्यक्ता. २. §शक्रा १.३.७; शक्रा १.५.८. ३. §शताधारम्.

शत्रून् ४.५.२१–२३; ५.५.१०; (९६३[२])
शत्रूयता ४.५.३५
शंतम २.१३.५; ३.५.५
शंतमाभिः २.१३.५; ३.५.५
शंताता (९३८)
शंपतः ४.५.१७
शपथ ४.५.२१
शपथः ४.५.१९[२]
शपथान् ४.५.२२; २३
शंपात् ४.५.१७[२]; १८; १९
शफः ५.१५.५
शफेन ५.१५.१२
शम् २.१३.६[५]; ५.१.५[२]; ३.७[२]; (९२५, ९३८[१४]; ९५८)
शमयन्तु (९३८)
शमितारः (९९२[२])
शमिष्ठाः ५.५.६
शमीध्वम् (९९२[३])
शमीभिः १.२.९
शम्बरहत्ये ५.५.२
शंभवे (९३३)
शंभूः ५.५.५
शंभो (९३३)
शम्यया ५.२२.८
शम्या ५.५.६
शयनात् ३.१६.१
शयवे १.१२.६
शयानम् ३.३.२
शयानाथे ५.१६.४
शये ५.१५.१४
शर् ५.१८.१
शरणम् २.४.२; ६.५; (९३३, ९५७, ९६५)
शरण्याम् (९५७)
शरण्ये (९३३)
शरदः १.१.३[२]; ५.६[२]; ३.१७.१
शरदाशानिः ४.५.१५
शरीरम्[१] २.१२.१; ४.८.५; ११.७; ८; (९३७[२], ९९२)
शर्म १.२.१४; १२.३; ४; ४.५.४०; ५.५.८
शर्मन् ५.२१.१
शर्वाय (९३३)
शला (९९२)
शलाञ्चका ५.१५.१०
शवः ३.३.१०; ८.१
शवर्तञ्चः ५.१५.१२
शविष्ठ ५.४.३; ८
शविष्ठः ५.४.४
शशमत् ५.७.१क
शशयम्[२] ३.६.८
शश्वत् १.२.१; ११
शश्वतः ५.४.८
शश्वताम् १.१२.४; ४.७.२[२]; ५.१२.४
शश्वतीः ३.१६.५
शष्पैः (९९२)
शस्यमाना १.७.५
शान्तिम् २.१३.५
शान्त्यर्थम् (९५७)
शामये ४.८.४
शायांतस्य १.७.५
शाले (९६५)
शाशदाना १.७.३
शास्स्व ५.७.२क; ४ङ
शिंशपाः ५.१५.२
शिंशवृक्षफलम् (९२४)
शिक्ष ५.४.१
शिक्षतम् १.६.४
शिक्षति ३.१.१
शिक्षथः १.६.१
शिक्षसि ३.३.६; ४.८
शिक्षो ३.४.८
शितामतः ५.७.२ऐ; (९९०)
शितिपृष्ठाः ५.७.३औ
शिथिराः ५.७.३आ

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §शरीरम् ४.११.७. २. §शशयम्.

शिनिः ३.२.२
शिप्रे ५.७.४क
शिरः १.९.३; ११.२[2]; ४; ५.१४.२; (९३७)
शिरसा[1] १.९.४; ११.३
शिव (९३३)
शिवः १.५.४; ५.६.१
शिवनामानि (९३३)
शिवम्[2] १.२.१३; ४.६; २.२.४; ४.५.२४; (९७३)
शिवरूपम् (९७३)
शिवसंकल्पम् ४.११.१–१३; (९७२[5], ९७३[14])
शिवाः ५.३.४
शिवाभिः ५.६.१
शिवाम्[3] ४.२.४
शिवालयम् (९७३)
शिवासः ४.५.१३
शिवे (९३३)
शिशवः (९९८)
शिशुः (९६५)
शिशू ३.२२.१०
शिषः ४.५.१२; ३४
शीतह्रदः (९६५)
शीर्षण्वतीम् ४.५.२
शीर्षेषु ३.५.४
शीर्ष्णी ५.२२.८
शुक्रम् ५.३.५; (९४७)
शुक्रया ५.७.४ऐ
शुक्राः ४.९.३; ५.७.४अं; (९९२)
शुक्रामन्थिनः ५.७.४अः
शुक्रासः ३.४.१०
शुक्रेण ३.८.५; ४.९.७
शुङ्ग ५.१५.८
शुचयः ३.४.१०
शुचिः ४.९.५; (९३१)
शुद्धदन्तीषु ३.१५.१७
शुनः ३.७.३
शुनम् ४.६.३
शुने ४.५.१८
शुन्धत ३.१६.६
शुभमानम् (९३२)
शुभस्पती[4] १.२.५
शुभस्पती १.६.३; ५
शुभाम् (९५७)
शुभे (९७३)
शुभ्रवस्त्रोत्तरीया (९३३)
शुभ्राः ५.५.९
शुरुधः १.१०.४
शुश्रव ५.१२.४
शुष्कम् (९६३)
शुष्णम् ३.३.८
शुष्मिणः १.२.६
शुष्यति ४.५.३८
शुष्यतु ४.५.१७; ३८
शूर ३.१.३; २.९
शूरः ३.९.१; ५.४.९
शूरसातौ १.११.८
शूराः ५.५.९
शूराणाम् ५.४.४
शूर्पंशूर्पम् ५.२२.५
शृङ्गम् ५.१५.३
शृणीहि ५.९.३
शृणुतम् १.२.५
शृणुधि ३.४.८
शृणोति (९५८)
शृणोतु ३.६.४; (९२५)
शृण्वताम् (९४७)
शृण्वन्ता १.७.६
शृण्वन्तु ३.६.३
शृण्विरे ३.५.७
शेरते (९३९)
शेवधिपाः ३.३.९
शोकमनस्तापाः (९३३)
शोचन्तः ४.९.३
शोचस्व २.१३.५

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §शिरसा १.११.३. २. §शिवम् १.२.१३. ३. §शिवाम्. ४. §शुभस्पती.

ष

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. 'श्रीवर्चस्वम्' (९३२) अस्य स्थाने 'श्रीर्वर्चसम्' इत्यूहः । २. षोळशारम्.

स

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §संयतम् ३.१५.१०   २. §शादनम्.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §सधमाध्येषु. २. §न विवेशय. ३. §सम् ३.१५.१४[२]. ४. §समश्नुते. ५. 'समासाविर्तुश्च' इत्यस्य स्थाने 'न मां समितिंश्च' इति वाचनीयम्।

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §समुद्धम्. २. §सर्वतः २.२.३.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §सवना १.३.१. २. §सहीयसा. ३. 'सातपन्ति' अत्र 'साता तपन्ति' इति पदच्छेदः । ४. §साप्तेभिः ५. §सिञ्चते.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।
१. §सु ४.५.२०, २. §सुपर्णः

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति ।

१. §सुयुजः १.२.३. २. §सुशस्तिः

पदेपूपरितनं चिह्नमुदात्तस्वरं बोधयति।
१. §सूरी. २. §स्रष्टा.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §स्थालीपाकः॰

पदेषूपरिनत चिह्नमुदात्तस्वरं बोधयति ।

१. §स्यः. २. §स्रजः ३.८.३. ३. §स्वतवसा. ४. 'अस्येश्वरया' इत्यस्य स्थाने 'अस्ये स्वधया' इति पठनीयम् । ५. §स्वप्नः. ६. §स्वाधिष्ठः. ७. §स्वानाम्. ८. §स्वांशुः.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §हतः ३.१५.१६[२]; १७ ?   २. §हयस्य.   ३. §हरितः.   ४. §हवमानासः.
५. §हविष्मती.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §हृव्यानि. २. §हस्त्यश्वादिगवे रथम्. ३. §हिं ३.३.५; ५.४.१०[10]; ११. ४. §हिं त्वा. ५. §हृदि.

पदेषूपरितनं चिह्नमुदात्तस्वरं बोधयति।

१. §होतारा ५.७.१औ. २. §होतुः ४.९.६[२]. ३. §होत्रे.

|| श्रीः ||

|| मन्त्रसूची ||

आ

आ कृष्णेन रजसा वर्तमानः १.३५.२
आकेनिपासो अहभिः ४.४५.६
आ क्रन्दय बलमोजो ६.४७.३०
आक्षित्पूर्वास्वपरा ३.५५.५
आ क्षोदो महि वृत्तं ६.१७.१२
आक्ष्णयावानो वहन्ति ८.७.३५
आगधिता परिगधिता १.१२६.६
आ गन्ता मा रिषण्यत ८.२०.१
आगन् देव ऋतुभिर्वर्धतु ४.५३.७
आगन्नृभूणामिह ४.३५.२
आगन्म वृत्रहन्तमं ८.७४.४
आ गावो अग्मन्नुत ६.२८.१
आ गोमता नासत्या रथेन ७.७२.१
आ ग्ना अग्न इहावसे १.२२.१०
आग्निं न स्ववृक्तिभिः १०.२१.१
आग्निरगामि भारतो ६.१६.१९
आग्ने गिरो दिव आ ७.३९.५
आग्ने याहि मरुत्सखा ८.१०३.१४
आग्ने वह वरुणं १०.७०.११
आग्ने वह हविरद्याय ७.११.५
आग्ने स्थूरं रयिं भर १०.१५६.३
आग्मन्नाप उशतीर्बर्हिः १०.३०.१५
आ ग्रावभिरहन्येभिः ५.४८.३
आ घ त्वावान् त्मना १.३०.१४
आ घा गमद्यदि श्रवत् १.३०.८
आ घा ता गच्छानुत्तरा १०.१०.१०
आ घा ये अग्निमिन्धते ८.४५.१
आ घा योषेव सूनरी १.४८.५
आ च त्वामेता वृषणा ३.४३.४
आ चन त्वा चिकित्सामो ७.९१.६
आ च नो बर्हिः सदता ८.५९.५
आ चर्षणिप्रा वृषभो १.१७७.१
आ च वहासि ताँ इह १.७४.६
आ चष्ट आसां पाथो ७.३४.१०
आ चिकितान सुक्रतू ५.६६.१
आच्या जानु दक्षिणतो १०.१५.६
आच्छद्विधानैर्गुपितः १०.८५.४
आ जङ्घन्ति सान्वेषां ६.७५.१३
आ जनं त्वेषसंदृशं १०.६०.१
आ जनाय द्रुह्वणे ६.२२.८
आ जागृविर्विप्र ऋता ९.९७.३७
आ जातं जातवेदसि ६.१६.४२
आ जामिरत्के अव्यत ९.१०१.१४
आजासः पूषणं रथे ६.५५.६
आजितुरं सत्पतिं ८.५३.६
आजिपते नृपते त्वमिद्धि ८.५४.६
आ जुहोता दुवस्यता ५.२८.६
आ जुहोता स्वध्वरं ३.९.८
आ जुह्वान ईड्यो वन्द्यः १०.११०.३
आ जुह्वानो न ईड्यो देवाँ १.१८८.३
आञ्जनगन्धिं सुरभिं १०.१४६.६
आ त इन्दो मदाय कं ९.६२.२०
आ त इन्द्र महिमानं ८.६५.४
आ त एता वचोयुजा ८.४५.३९
आ त एतु मनः पुनः १०.५७.४
आ तक्षत सातिमस्मभ्यं १.१११.३
आ तत्त इन्द्रायवः १०.७४.४
आ तत्ते दस्र मन्तुमः १.४२.५
आ तं भज सौश्रवेषु १०.४५.१०
आ तिष्ठतं सुवृतं यो रथः १.१८३.३
अतिष्ठन्तं परि विश्वे ३.३८.४
आ तिष्ठ रथं वृषणं १.१७७.३
आ तिष्ठ वृत्रहन् रथं १.८४.३
आ तू गहि प्र तु द्रव ८.१३.१४
आ तू न इन्दो शतदातु ९.७२.९
आ तू न इन्द्र कौशिक १.१०.११
आ तू न इन्द्र क्षुमन्तं ८.८१.१
आ तू न इन्द्र मद्र्यग् ३.४१.१
आ तू न इन्द्र वृत्रहन् ४.३२.१
आ तू भर माकिरेत ३.३६.९
आ तू षिञ्च कण्वमन्तं ८.२.२२
आ तू षिञ्च हरिमीं १०.१०१.१०
आ तू सुशिप्र दंपते ८.६९.१६
आ ते अग्न इधीमहि ५.६.४
आ ते अग्न ऋचा हविः शुक्रस्य ५.६.५
आ ते अग्न ऋचा हविः हृदा ६.१६.४७
आ ते कारो शृणवामा ३.३३.१०
आ ते दक्षं वि रोचना ८.९३.२६

इ

ई

उ

ए

एवा वामह्व ऊतये इन्द्राग्नी ८.३९.९
एवा वामह्व ऊतये नासत्या ८.४२.६
एवा सख्यं मघवाना युवं ४.२८.५
एवा हि ते विभूतय १.८.९
एवा हि ते शं सवना १.१७३.८
एवा हि त्वामृतुथा यातयन्त ५.३२.१२
एवा हि मां तवसं वर्धयन्ति १०.२८.६
एवा हि मां तवसं जज्ञुः १०.२८.७
एवा ह्यसि वीरयुः ८.९२.२८
एवा ह्यस्य काम्या १.८.१०
एवा ह्यस्य सूनृता १.८.८
एवेदिन्द्रं वृषणं ७.२३.७
एवेदिन्द्रः सुते अस्तावि ६.२३.१०
एवेदिन्द्रः सुहव ६.२९.६
एवेदिन्द्राय वृषभाय ४.१६.२०
एवेदेते प्रति मा १.१६५.१२
एवेदेष तुविकूर्मिः ८.२.३१
एवेदेषा पुरुतमा दृशे १.१२४.६
एवेद्यूने युवतयो नमन्त १०.३०.६
एवेन सद्यः पर्येति १.१२८.३
एवेन्द्राग्निभ्यामहावि ५.८६.६
एवेन्द्राग्निभ्यां पितृवन् ८.४०.१२
एवेन्द्राग्नी पपिवांसा १.१०८.१३
एवेन्नु कं सिन्धुमेभिः ७.३३.३
एवैवापागपरे १०.४४.७
एष इन्द्राय वायवे ९.२७.२
एष उ स्य पुरुव्रतो ९.३.१०
एष उ स्य वृषा रथो ९.३८.१
एष एतानि चकारेन्द्रो ८.२.३४
एष कविरभिष्टुतः ९.२७.१
एष क्षेति रथवीतिः ५.६१.१९
एष गव्युरचिक्रदत् ९.२७.४
एष ग्रावेव जरिता ५.३६.४
एष च्छागः पुरो १.१६२.३
एष तुन्नो अभिष्टुतः ९.६७.२०
एष ते देव नेता ५.५०.५
एष दिवं वि धावति ९.३.७
एष दिवं व्यासरत् ९.३.८
एष देवः शुभायते ९.२८.३
एष देवो अमर्त्यः ९.३.१
एष देवो रथर्यति ९.३.५
एष देवो विपन्युभिः ९.३.३
एष देवो विपा कृतो ९.३.२
एष द्रप्सो वृषभो ६.४१.३
एष धिया यात्यण्व्या ९.१५.१
एष नृभिर्वि नीयते ९.२७.३
एष पवित्रे अक्षरत् ९.२८.२
एष पुनानो मधुमाँ ९.११०.११
एष पुरू धियायते ९.१५.२
एष प्र कोशे मधुमाँ ९.७७.१
एष प्रत्नेन जन्मना ९.३.९
एष प्रत्नेन मन्मना ९.४२.२
एष प्रत्नेन वयसा ९.९७.४७
एष प्र पूर्वीरव १.५६.१
एष रुक्मिभिरियते ९.१५.५
एष वः स्तोमो मरुत इयं १.१६५.१५; १६६.१५; १६७.११; १६८.१०
एष वः स्तोमो मरुतो नमस्वान् १.१७१.२
एष वसूनि पिब्दना ९.१५.६
एष वां स्तोमो अश्विनावकारि १.१८४.५
एष वाजी हितो नृभिः ९.२८.१
एष वां देवावश्विना ४.१५.९
एष विप्रैरभिष्टुतो ९.३.६
एष विश्ववित् पवते ९.९७.५६
एष विश्वानि वार्या ९.३.४
एष वृषा कनिक्रदत् ९.२८.४
एष वृषा वृषव्रतः ९.६२.११
एष शुष्म्यदाभ्यः ९.२८.६
एष शुष्म्यसिष्यदत् ९.२७.६
एष शृङ्गाणि दोधुवत् ९.१५.४
एष सुवानः परि सोमः ९.८७.७
एष सूर्यमरोचयत् ९.२८.५
एष सूर्येण हासते ९.२७.५
एष सोमो अधि त्वचि ९.६६.२९
एष स्तोम इन्द्र तुभ्य १.१७३.१३
एष स्तोमो अचिक्रदद् ७.२०.९
एष स्तोमो मह उग्राय ७.२४.५
एष स्तोमो मारुतं ५.४२.१५

ऐ

ओ

औ

क

ख

ग

घ

त

त्वं तस्य द्वयाविनो १.४२.४
त्वं ताँ अग्न उभयान्वि १.१८९.७
त्वं ताँ इन्द्रोभयाँ ६.३३.३
त्वं तान् वृत्रहत्ये १०.२२.१०
त्वं तान्त्सं च प्रति २.१.१५
त्वं तू न इन्द्र तं १.१६९.४
त्वं त्यत्पणीनां विदो ९.१११.२
त्वं त्यमिटतो रथं १०.१७१.१
त्वं त्यमिन्द्र मर्त्यम् १०.१७१.३
त्वं त्यमिन्द्र सूर्यं १०.१७१.४
त्वं त्या चिदच्युताग्ने ६.२.९
त्वं त्या चिद्वातस्याश्वा १०.२२.५
त्वं त्यां न इन्द्र देव १.६३.८
त्वं त्येभिरा गहि १.३०.२२
त्वंत्वमहर्यथा १०.९६.५
त्वं दाता प्रथमो ८.९०.२
त्वं दिवो धरुणं धिष १.५६.६
त्वं दिवो बृहतः सानु १.५४.४
त्वं दूतः प्रथमो १०.१२२.५
त्वं दूतस्त्वमु नः २.९.२
त्वं दूतो अमर्त्यं आ ६.१६.६
त्वं देवि सरस्वत्यवा ६.६१.६
त्वं द्यां च महिव्रत ९.१००.९
त्वं धियं मनोयुजं ९.१००.३
त्वं धुनिरिन्द्र १.१७४.९; ६.२०.१२
त्वं धृष्णो धृषता ७.१९.३
त्वं न इन्द्र ऋतयुः ८.७०.१०
त्वं न इन्द्र त्वाभिरूती २ २०.२
त्वं न इन्द्र राया तरूषसोग्रं १.१२९.१०
त्वं न इन्द्र राया परीणसा १.१२९.९
त्वं न इन्द्र वाजयुः ७.३१.३
त्वं न इन्द्र शूर १०.२२.९
त्वं न इन्द्रा भरँ ओजो ८.९८.१०
त्वं न इन्द्रासां हस्ते ८.७०.१२
त्वं नः पश्चादधराद् ८.६१.१६
त्वं नः पाह्यंहसो जातवेदो ६.१६.३०
त्वं नः पाह्यंहसो दोषावस्तः ७.१५.१५
त्वं नः सोम विश्वतो गोपा १०.२५.७
त्वं नः सोम विश्वतो रक्षा १.९१.८
त्वं नः सोम विश्वतो वयोधाः ८.४८.१५
त्वं नः सोम सुक्रतुः १०.२५.८
त्वं नश्चित्र ऊत्या ६.४८.९
त्वं नृचक्षा असि सोम ९.८६.३८
त्वं नृचक्षा वृषभानु ३.१५.३
त्वं नृभिर्नृमणो ७.१९.४
त्वं नो अग्न आयुषु ८.३९.१०
त्वं नो अग्न एषां ५.१०.३
त्वं नो अग्ने अग्निभिः १०.१४१.६
त्वं नो अग्ने अङ्गिर स्तुतः ५.१०.७
त्वं नो अग्ने अद्भुत ५.१०.२
त्वं नो अग्ने अधराद् १०.८७.२०
त्वं नो अग्ने तव देव १.३१.१२
त्वं नो अग्ने पित्रोरुपस्थे १.३१.९
त्वं नो अग्ने महोभिः ८.७१.१
त्वं नो अग्ने वरुणस्य ४.१.४
त्वं नो अग्ने सनये १.३१.८
त्वं नो असि भारताग्ने २.७.५
त्वं नो अस्या अमतेरुत ८.६६.१४
त्वं नो अस्या इन्द्र दुर्हणायाः १.१२१.१४
त्वं नो अस्या उषसो ३.१५.२
त्वं नो गोपाः पथिकृद् २.२३.६
त्वं नो वायवेषामपूर्व्यः १.१३४.६
त्वं नो वृत्रहन्तमे १०.२५.९
त्वमग्न इन्द्रो वृषभः २.१.३
त्वमग्न ईळितो जातवेदो १०.१५.१२
त्वमग्न उरुशंसाय १.३१.१४
त्वमग्न ऋभुराके २.१.१०
त्वमग्ने अदितिर्देव २.१.११
त्वमग्ने गृहपतिः ७.१६.५
त्वमग्ने त्वष्टा २.१.५
त्वमग्ने द्युभिस्त्वमा° २.१.१
त्वमग्ने द्रविणोदा २.१.७
त्वमग्ने पुरुरूपो ५.८.५
त्वमग्ने प्रथमो अङ्गिरस्तमः १.३१.२
त्वमग्ने प्रथमो अङ्गिरा १.३१.१
त्वमग्ने प्रथमो मातरिश्वन १.३१.३
त्वमग्ने प्रमतिस्त्वं १.३१.१०
त्वमग्ने प्रयतदक्षिणं १.३१.१५

द

ध

न

प्र त्वा नमोभिरिन्दव ९.१६.५
प्र त्वा मुञ्चामि वरुणस्य १०.८५.२४
प्रथमं जातवेदसमग्निं ८.२३.२२
प्रथमभाजं यशसं ६.४९.९
प्रथमा हि सुवाचसा १.१८८.७
प्रथश्च यस्य सप्रथश्च १०.१८१.१
प्रथिष्ट यस्य वीरकर्मं १०.६१.५
प्रथिष्ट यामन्पृथिवी ५.५८.७
प्रदक्षिणिदभि गृणन्ति २.४३.१
प्र दानुदो दिव्यो दानु ९.९७.२३
प्र दीधितिर्विश्ववारा ३.४.३
प्र देवत्रा ब्रह्मणे १०.३०.१
प्र देवं देववीतये ६.१६.४१
प्र देवं देव्या धिया १०.१७६.२
प्र देवमच्छा मधुमन्त ९.६८.१
प्र दैवोदासो अग्निः ८.१०३.२
प्र द्यावा यज्ञैः पृथिवी ऋतावृधा १.१५९.१
प्र द्यावा यज्ञैः पृथिवी नमोभिः ७.५३.१
प्र द्युम्नाय प्र शवसे ८.९.२०
प्र धन्वा सोम जागृविः ९.१०६.४
प्र धारा अस्य शुष्मिणो ९.३०.१
प्र धारा मध्वो अग्रियो ९.७.२
प्र नः पूषा चरथं १०.९२.१३
प्र नव्यसा सहसः सूनुं ६.६.१
प्र निम्नेनेव सिन्धवो ९.१७.१
प्र नु यदेषां महिना १.१८६.९
प्र नु वयं सुते या ५.३०.३
प्र नु वोचा सुतेषु ६.५९.१
प्र नूनं जातवेदसं १०.१८८.१
प्र नूनं जायतामयं १०.६२.८
प्र नूनं धावता पृथक् ८.१००.७
प्र नूनं ब्रह्मणस्पतिः १.४०.५
प्र नू महित्वं वृषभस्य १.५९.६
प्र नू स मर्तः शवसा १.६४.१३
प्र नेमस्मिन् ददृशे १०.४८.१०
प्र नो यच्छत्वर्यमा १०.१४१.२
प्रपथे पथामजनिष्ट १०.१७.६
प्र पर्वतानामुशती ३.३३.१
प्र पवमान धन्वसि ९.२४.३
प्र पस्त्यामदितिं ४.५५.३
प्र पीपय वृषभ ३.१५.६
प्र पुनानस्य चेतसा ९.१६.४
प्र पुनानाय वेधसे ९.१०३.१
प्र पूतास्तिग्मशोचिषे १.७९.१०
प्र पूर्वजे पितरा ७.५३.२
प्र पूषणं वृणीमहे ८.४.१५
प्र प्यायस्व प्र स्यन्दस्व ९.६७.२८
प्रप्र क्षयाय पन्यसे ९.९.२
प्रप्र पूष्णस्तुविजातस्य १.१३८.१
प्रप्र वस्त्रिष्टुभं ८.६९.१
प्रप्रायमग्निर्भरतस्य ७.८.४
प्रप्रा वो अस्मे १.१२९.८
प्र बभ्रवे वृषभाय २.३३.८
प्र बाहवा सिसृतं ७.६२.५
प्र बुध्न्या व ईरते ७.५६.१४
प्र बोधयोषः पृणतो १.१२४.१०
प्र बोधयोषो अश्विना ८.९.१७
प्र ब्रह्माणि नभाकवद् ८.४०.५
प्र ब्रह्माणो अङ्गिरसो ७.४२.१
प्र ब्रह्मैतु सदनादृतस्य ७.३६.१
प्रभङ्गं दुर्मतीनां ८.४६.१९
प्रभङ्गी शूरो मघवा ८.६१.१८
प्रभर्ता रथं गव्यन्त ८.२.३५
प्र भूर्जयन्तं महां १०.४६.५
प्र भ्रातृत्वं सुदानवो ८.८३.८
प्र मंहिष्ठाय गायत ८.१०३.८
प्र मंहिष्ठाय बृहते १.५७.१
प्र मन्दिने पितुमदर्चता १.१०१.१
प्र मन्महे शवसानाय १.६२.१
प्र मातुः प्रतरं १०.७९.३
प्र मात्राभी रिरिचे ३.४६.३
प्र मा युयुज्रे १०.३३.१
प्र मित्रयोर्वरुणयो° ७.६६.१
प्र मित्राय प्रार्यम्णे ८.१०१.५
प्र मे नमी साप्य १०.४८.९
प्र मे पन्था देवयाना ७.७६.२
प्र मे विविक्वाँ अविदन् ३.५७.१
प्र य आरुः शितिपृष्ठस्य ३.७.१

प्र सो अग्ने तवोतिभिः ८.१९.३०
प्र सोता जीरो ७.९२.२
प्र सोम देववीतये ९.१०७.१२
प्र सोम मधुमत्तमो ९.६३.१६
प्र सोम याहि धारया ९.६६.७
प्र सोमस्य पवमानयोर्मय ९.८१.१
प्र सोमाय व्यश्ववत् ९.६५.७
प्र सोमासः स्वाध्यः ९.३१.१
प्र सोमासो अधन्विषुः ९.२४.१
प्र सोमासो मदच्युतः ९.३२.१
प्र सोमासो विपश्चितो ९.३३.१
प्र सोमो अति धारया ९.३०.४
प्र स्कम्भदेष्णा अनवभ्र° १.१६६.७
प्रस्तुतिर्वां धाम १.१५३.२
प्रस्तोक इन्नु राधसस्त ६.४७.२२
प्र स्तोषदुप गासिषत् ८.८१.५
प्र स्वानासो ९.१०.१
प्र हंसासस्तृपलं मन्युं ९.९७.८
प्र हि क्रतुं वृहथो २.३०.६
प्र हि त्वा पूषन् १.१३८.२
प्र हिन्वानास इन्दवो ९.६४.१६
प्र हिन्वानो जनिता ९.९०.१
प्र हि रिरिक्ष ओजसा ८.८८.५
प्र होता जातो महान् १०.४६.१
प्र होत्रे पूर्व्यं वचो ३.१०.५
प्र ह्यच्छा मनीषाः १०.२६.१
प्राक्तुभ्य इन्द्रः प्र १०.८९.११
प्राग्नये तवसे भरध्वं ७.५.१
प्राग्नये बृहते यज्ञियाय ५.१२.१
प्राग्नये वाचमीरय १०.१८७.१
प्राग्नये विश्वशुचे धियं ७.१३.१
प्राग्रुवो नभन्वो ४.१९.७
प्राचीनं बर्हिः प्रदिशा १०.११०.४
प्राचीनं बर्हिरोजसा १.१८८.४
प्राचीनो यज्ञः सुधितं ७.७.३
प्राचीमु देवाश्विना धियं ७.६७.५
प्राञ्चं यज्ञं चकृम ३.१.२
प्रातः सुतमपिबो ४.३५.७
प्रातरग्निः पुरुप्रियो ५.१८.१
प्रातरग्निं प्रातरिन्द्रं ७.४१.१
प्रातर्जरेथे जरणेव १०.४०.३
प्रातर्जितं भगमुग्रं ७.४१.२
प्रातर्देवीमदितिं ५.६९.३
प्रातर्यजध्वमश्विना ५.७७.२
प्रातर्यावभिरा गतं ८.३८.७
प्रातर्यावाणा प्रथमा ५.७७.१
प्रातर्यावाणा रथ्येव २.३९.२
प्रातर्याव्णः सहस्कृत १.४५.९
प्रातर्युजं नासत्याधि १०.४१.२
प्रातर्युजा वि बोधय १.२२.१
प्राता रत्नं प्रातरित्वा १.१२५.१
प्राता रथो नवो २.१८.१
प्रान्यच्चक्रमवृहः ५.२९.१०
प्राव स्तोतारं मघवन्नव ८.३६.२
प्रावीविपद्वाच ऊर्मिं ९.९६.७
प्रावेपा मा बृहतो १०.३४.१
प्रास्तौदृष्वौजा १०.१०५.६
प्रास्मा ऊर्जं घृतश्चुतं ८.८.१६
प्रास्मै गायत्रमर्चत ८.१.८
प्रास्मै हिनोत १०.३०.८
प्रास्य धारा अक्षरन् ९.२९.१
प्रास्य धारा बृहतीः ९.९६.२२
प्रियं श्रद्धे ददतः १०.१५१.२
प्रियं दुग्धं न काम्यं ५.१९.४
प्रियमेधवदत्रिवत् १.४५.३
प्रिया तष्टानि मे कपिः १०.८६.५
प्रियास इत्ते मघवन्नभिष्टौ ७.१९.८
प्रियो नो अस्तु विश्पतिः १.२६.७
प्रीणीताश्वान् हितं १०.१०१.७
प्रेतां यज्ञस्य शंभुवा २.४१.१९
प्रेता जयता नरः १०.१०३.१३
प्रेतो मुञ्चामि नामुतः १०.८५.२५
प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ ८.३७.१
प्रेद्धो अग्ने दीदिहि पुरो ७.१.३
प्रेद्वग्निर्वावृधे स्तोमेभिः ३.५.२
प्रेन्द्रस्य वोचं प्रथमा ७.९८.५
प्रेन्द्राग्निभ्यां सुवचस्यां १०.११६.९
प्रेरय सूरो अर्थं १०.२९.५

भ

म

य

यन्नियानं न्ययनं १०.१९.४
यन्निर्णिजा रेक्णसा १.१६२.२
यन्नीक्षणं मांस्पचन्या १.१६२.१३
यं नु नकिः पृतनासु ३.४९.२
यन्नूनं धीभिरश्विना ८.९.२१
यन्नूनमश्यां गतिं ५.६४.३
यन्मन्यसे वरेण्यं ५.३९.२
यन्मरुतः सरभसः ५.५४.१०
यमग्निं मेध्यातिथिः १.३६.११
यमग्ने पृत्सु मर्त्यं १.२७.७
यमग्ने मन्यसे रयिं १०.२१.४
यमग्ने वाजसातम ५.२०.१
यमत्यमिव वाजिनं ९.६.५
यमश्विना ददथुः १.११६.६
यमश्वी नित्यमुपयाति ७.१.१२
यमस्य मा यम्यं १०.१०.७
यमा चिदत्र यमसूरसूत ३.३९.३
यमादहं वैवस्वतात् १०.६०.१०
यमादित्यासो अद्रुहः ८.१९.३४
यमापो अद्रयो वना ६.४८.५
यमाय घृतवद्धविः १०.१४.१४
यमाय मधुमत्तमं १०.१४.१५
यमाय सोमं सुनुत १०.१४.१३
यमासा कृपनीळं १०.२०.३
यमिन्द्र दधिषे ८.९७.२
यमिमं त्वं वृषाकपिं १०.८६.४
यमी गर्भमृतावृधो ९.१०२.६
यमीं द्वा सवयसा १.१४४.४
यमु पूर्वमहुवे २.३७.२
यमृत्विजो बहुधा ८.५८.१
यमेइव यतमाने १०.१३.२
यमेन दत्तं त्रित १.१६३.२
यमेरिरे भृगवो १.१४३.४
यमैच्छाम मनसा सो १०.५३.१
यमो नो गातुं १०.१४.२
यं बहुतेव पिप्रती १.४१.२
यं मर्त्यः पुरुस्पृहं ५.७.६
यं मे दुरिन्द्रो मरुता ८.३.२१
यया गा आकरामहे १०.१५६.२

यया रध्रं पारयथात्यंहो २.३४.१५
ययोरधि प्र यज्ञा ८.१०.४
यवंयवं नो अन्धसा ९.५५.१
यवं वृकेणाश्विना १.११७.२१
यश्चिकेत स सुक्रतुः ५.६५.१
यश्चिदापो महिना १०.१२१.८
यश्चिद्धि त इत्था १.२४.४
यश्चिद्धि त्वा बहुभ्यः १.८४.९
यस्त इध्मं जभरत्सि ४.२.६
यस्त इन्द्र प्रियो ७.२०.८
यस्त इन्द्र महीरपः ८.६.१६
यस्त ऊरू विहरति १०.१६२.४
यस्तस्तम्भ सहसा ४.५०.१
यस्ता चकार स कुह ६.२१.४
यस्तिग्मशृङ्गो ७.१९.१
यस्तित्याज सचिविदं १०.७१.६
यस्तुभ्यमग्ने अमृताय दाशद् ४.२.९
यस्तुभ्यमग्ने अमृताय मर्त्यः १०.९१.११
यस्ते अग्ने नमसा ५.१२.६
यस्ते अग्ने सुमतिं मर्तो १०.११.७
यस्ते अद्य कृणवद्भद्रशोचे १०.४५.९
यस्ते अनु स्वधामसत् ३.५१.११
यस्ते गर्भममीवा १०.१६२.२
यस्ते चित्रश्रवस्तमो ८.९२.१७
यस्ते द्रप्सः स्कन्दति १०.१७.१२
यस्ते द्रप्सः स्कन्नो १०.१७.१३
यस्ते नूनं शतक्रतविन्द्र ८.९२.१६
यस्ते भरादन्नियते ४.२.७
यस्ते मदः पृतनाषाळ् ६.१९.७
यस्ते मदो युज्यश्चारुः ७.२२.२
यस्ते मदो वरेण्यस्तेना ९.६१.१९
यस्ते मदो वरेण्यो ८.४६.८
यस्ते मन्योऽविधद्वज्र १०.८३.१
यस्ते यज्ञेन समिधा ६.५.५
यस्ते रथो मनसा १०.११२.२
यस्ते रेवाँ अदाशुरिः ८.४५.१५
यस्ते शृङ्ग वृषो ८.१७.१३
यस्ते साधिष्ठोऽवस ५.३५.१
यस्ते साधिष्ठोऽवसे ते ८.५३.७

व

|| श्रीः ||

|| खिलमन्त्रसूची ||

[मन्त्रप्रतीकावलम्बिनः संख्याङ्काः क्रमेणाध्यायं सूक्तं मन्त्रं च बोधयन्ति। कोशे स्थापितः संख्याङ्कस्तु मुद्रितपुस्तकपृष्ठं बोधयति। अप्रमाणितमन्त्रप्रतीकदर्शनार्थं च स प्रयुक्तः। मुद्रितपाठापेक्षया मन्त्रप्रतीकेषु क्वचनाभ्यूहः कृतोऽस्ति। एतादृशेषु स्थलेष्वभ्यूहितः पाठो मूले दत्तः मुद्रितपाठश्च टिप्पणीषु प्रदर्शितः।]

[1] 'विभू वसुः' इति मुद्रितपुस्तकपाठः 'विभुर्वसुः' इत्यूह्यते।

१. 'इहेह' इति मुद्रितपुस्तके। २. 'प्रमतिनः' इति मुद्रितपुस्तकपाठोऽशुद्धः।
३. पुस्तके 'उपमैतु' इत्येकीकृत्य मुद्रितम्। ४. 'प्रजा स्रष्टा' इति मुद्रितपुस्तके।

---

१. 'कांस्यस्मि तां' इति मुद्रितपुस्तके। २. 'कुबीरं ते मुखं रुद्रं' इति मुद्रितपुस्तकपाठः। ३. 'क्षुत्पिपासामला' इति मुद्रितपुस्तके।

१. दुरिष्टं ? २. मुद्रितपुस्तके 'धानासोमानाम्' इति पाठः तत्रायमूहः। ३. 'परान्' इति मुद्रितपुस्तके। परं 'पराङ्' इति पाठमभ्यूहामः। 'पराङमित्राँ एषतु' खि. ५.२.३ 'द्रष्टव्यम्'। एवं खिलपदसूच्यामपि 'पराङ्' इति पदमभ्यूहनीयम्।

---

१. 'नो शिवासः' इति मुद्रितपुस्तकपाठस्थाने 'नोऽशिवासः' इति पठनीयम्। एवमेव खिलपदसूच्यां 'शिवासः ४.५.१३' इति निष्कास्य 'अशिवासः ४.५.१३' इति क्रमोचितस्थले स्थापनीयम्।

स

ह

१. 'स्वप्नः' इति मुद्रितपुस्तकपाठस्थाने 'स्वप्न' इति पठनीयम्।

---

१ 'ग्रावो' इत्यस्य स्थाने 'ग्राव्णो' इत्यूहितम्।

|| श्रीः ||

|| ऋषिसूची ||

अ

अंहोमुग्वामदेव्यः १०.१२६
अकृष्टा माषाः ९.८६.१–१०; ३१–४०
अक्षो मौजवान् १०.३४
अगस्त्यः १.१६५.१३–१५; १.१६६–१६९; १.१७०.२; ५; १.१७१–१७८; १.१७९.३; ४; १.१८०–१९१
अगस्त्यशिष्याः १.१७९.५; ६
अगस्त्यस्य स्वसा १०.६०.६
अग्नयो धिष्ण्या ऐश्वराः ९.१०९
अग्निः १०.१२४
अग्निः पावकः १०.१४०
अग्निः पावको बार्हस्पत्यः ८.१०२
अग्निः सौचीकः १०.५१.२; ४; ६; ८; १०.५२; १०.५३.४; ५; १०.७९; १०.८०
अग्नियुतः स्थौरः १०.११६
अग्नियूपः स्थौरः १०.११६
अग्निर्गृहपतिः सहसः सुतः ८.१०२
अग्निर्यविष्ठः सहसः सुतः ८.१०२
अग्निर्वैश्वानरः १०.७९; १०.८०
अग्निश्चाक्षुषः ९.१०६.१–३; १०–१४
अग्निस्तापसः १०.१४१
अघमर्षणो माधुच्छन्दसः १०.१९०
अङ्ग औरवः १०.१३८
अङ्गिरसः । दृश्यताम्–वसुरोचिषः
अजमीळ्हः सौहोत्रः ४.४३; ४.४४
अजाः । दृश्यताम्–पृश्नयः
अत्रिः सांख्यः १०.१४३
अत्रिर्भौमः ५.२७; ५.३७–४३; ५.७६; ५.७७; ५.८३–८६; ९.६७.१०–१२; ९.८६; ४१–४५; १०.१३७.४
अदितिः ४.१८
अदितिर्दाक्षायणी १०.७२
अनानतः पारुच्छेपिः ९.१११
अनिलो वातायनः १०.१६८
अन्धीगुः श्यावाश्विः ९.१०१.१–३
अपाला आत्रेयी ८.९१
अप्रतिरथ ऐन्द्रः १०.१०३
अप्सरसौ । दृश्यताम्–शिखण्डिन्यौ
अभितपाः सौर्यः १०.३७
अभीवर्त आङ्गिरसः १०.१७४
अमहीयुः आङ्गिरसः ९.६१
अम्बरीषो वार्षागिरः १.१००; ९.९८
अयास्यः आङ्गिरसः ९.४४–४६; १०.६७; १०.६८
अरिष्टनेमिस्तार्क्ष्यः १०.१७८
अरुणो वैतहव्यः १०.९१
अर्चनाना आत्रेयः ५.६३; ५.६४; ८.४२
अर्चन् हैरण्यस्तूपः १०.१४९
अर्बुदः काद्रवेयः १०.९४
अवत्सारः काश्यपः ५.४४; ९.५३–६०
अवस्युरात्रेयः ५.३१; ५.७५
अश्वमेधो भारतः ५.२७
अश्वसूक्ती काण्वायनः ८.१४; ८.१५
अश्व्यः । दृश्यताम्–वशः
अष्टको वैश्वामित्रः १०.१०४
अष्ट्रादंष्ट्रो वैरूपः १०.१११
असितः काश्यपः ९.५–२४
असुराः । दृश्यताम्–पणयः

आ

आगस्त्यः । दृश्यताम्–दृळहच्युतः
आग्नेयः । दृश्यन्ताम्–कुमारः; केतुः; वत्सः; श्येनः
आङ्गिः । दृश्यताम्–हविर्धानः
आङ्गिरसः । दृश्यन्ताम्–भीवर्तः; अमहीयुः; अयास्यः; उचथ्यः; ऊरुः; ऊर्ध्वसद्मा; कुत्सः; कृतयशाः; कृष्णः; गृत्समदः; घोरः; तिरश्चीः; दिव्यः; धरुणः; नृमेधः; पवित्रः; पुरुमीळ्हः; पुरुमेधः; पुरुहन्मा; पूतदक्षः;

ए

ऐ

औ

क

ग

ध

न

प

श

|| श्रीः ||

|| देवतासूची ||

अ

अक्षकृषिप्रशंसा चाक्षकितवनिन्दा च[१] १०.३४

अक्षाः १०.३४

अग्नयः पुरीष्याः[२] ३.२२

अग्नायी । दृश्यताम्–इन्द्राणी वरुणानी अग्नायी च

अग्निः[३] १.१; १.१२; १.१५.४; १२; १.२२.९; १०; १.२६; १.२७.१–१२; १.३१; १.३६.१–१२; १५–२०; १.४४.३–१४; १.४५.१–१०[३]; १.५८; १.६०; १.६५–७८; १.७९.४–१२; १.९४.१–७; ८[४]; ९–१६[१–२]; १.११२.१[२]; १.१२७–१२८; १.१३९.७; १.१४०; १.१४१; १.१४३–१५०; १.१८९; २.१; २.२; २.४–१०; ३.१; ३.५; ३.६; ३.७; ३.९–११; ३.१३–१९; ३.२०.२–४; ३.२१; ३.२३; ३.२४; ३.२५.१–३; ५; ३.२७.२–१५; ३.२८; ३.२९.१–४; ६–१६; ३.५५.२–१०; ४.१; ४.२; ४.३; ४.६–१२; ४.१५.१–६; ५.१; ५.२; ५.३.१; २; ४–१२; ५.४; ५.६–२५; ५.२६.१–८; ५.२७.१–५; ५.२८; ६.१–६; ६.१०.१६; ६.४८.१–१०; ७.१; ७.३; ७.४; ७.७–१२; ७.१४–१७; ७.५०.२; ७.१०४.१०; १४; ८.११; ८.१९.१–३३; ८.२३; ८.३९; ८.४३; ८.४४; ८.६०; ८.७१; ८.७४.१–१२; ८.७५; ८.८४; ८.१०२; ८.१०३.१–१३; ९.६६.१९–२१; ९.६७.२३; २४; १०.१–७; १०.८.१–६; १०.११; १०.१२; १०.१६; १०.२०; १०.२१; १०.४५; १०.४६; १०.५१.१; ३; ५; ७; ९; १०.५३.१–३; ६–११; १०.६९; १०.७९; १०.८०; १०.९१; १०.११५; १०.१२२; १०.१२४.१; १०.१४०; १०.१४२; १०.१५०; १०.१५६; १०.१७६.२–४; १०.१८७; १०.१९१.१

अग्निः अग्निः वैश्वानरो वा १.९८

अग्निः अग्निः शुचिर्वा[४] १.९७

अग्निः अग्निरौषस्यो[५] वा १.९५

अग्निः अग्निर्जातवेदा[६] वा १.९९

अग्निः अग्निर्द्रविणोदा[७] वा १.९६

अग्निः अग्निर्मध्यमो वा[८] १.७९.१–३

अग्निः अग्निर्वरुणश्च वा ४.१.२–५

अग्निः अग्निः सविता[९] च वा ९.६७.२६

अग्निः अश्विनौ उषाश्च १.४४.१; २

अग्निः इन्द्रश्च । दृश्यताम्–इन्द्रः अग्निश्च

अग्निः ऋतवश्च १.१५.४; १२; २.३७.६

अग्निः ऋतवो वा ३.२७.१

अग्निः ऋत्विजो वा ३.२९.५

अग्निः त्वष्टा च अथवा अग्निः इन्द्रः पर्जन्यात्मा च । दृश्यताम्–त्वष्टा अग्निश्च

अग्निः द्यावापृथिव्यौ वा २.४१.१९[३]

अग्निः पर्जन्यश्च अथवा सूर्यः १.१६४.५१

---

१. १०.३४.१; ७; ९; १२ अक्षाः, १३ कृषिः, शेषा अक्षान् निन्दन्ति–बृहद्दे.

२. धिष्ण्या अग्नयः–बृहद्दे.

३. १.२७.१० अग्निर्मध्यमः, १.५८; १.९४; १.१४०–१४१; १४३–१४४; २.२ जातवेदाः, १०.१६ अग्निः कव्यवाहनः, १०.४५.१२[३] द्यावापृथिव्यौ; १२[४] विश्वे देवाः–बृहद्दे.

४. अग्निः शुचिः–बृहद्दे.

५. अग्निरौषसः–बृहद्दे.

६. जातवेदाः–बृहद्दे.

७. अग्निर्द्रविणोदाः–बृहद्दे.

८. अग्निर्मध्यमः–बृहद्दे.

९. अग्निः सविता च–बृहद्दे.

१. १.१९ अग्निः पार्थिवः मरुतश्च, ८.१०३.१४ अग्निर्मरुद्भी रुद्रैश्च सह–बृहद्दे.
२. 'द्वृच आत्मस्तुतिर्वा' इति सर्वानुक्रमसूत्रम्.
३. विश्वे देवाः–बृहद्दे.
४. सविता–बृहद्दे.
५. ८.५६.५[१-३] अग्निः, ५[४] सूर्यः–बृहद्दे.
६. ८.१८.९[१] अग्निः, ९[२] सूर्यः, ९[३] अनिलः–बृहद्दे.
७. ८.७२ हविषां स्तुतिः पयःपश्वोषधीनां च–बृहद्दे.
८. अग्निर्वैश्वानरः–बृहद्दे.
९. १०.८७ अग्निः–बृहद्दे.
१०. ५.४०.५–९ अत्रीणां कर्म कीर्त्यते–बृहद्दे.
११. आदित्याः (वरुणोऽर्यमा मित्रश्च)–बृहद्दे.
१२. अधिषवणचर्म सोमो वा–बृहद्दे.
१३. केषांचिन्मते अप्तृणसूर्यानामियं स्तुतिः। विषघ्नमेतत्सूक्तम्–बृहद्दे.
१४. अभ्यावर्तिनः साञ्जयस्य च दानस्तुतिः–बृहद्दे.
१५. १.४६.५ अश्विनौ आदित्यश्च–बृहद्दे.

---

१. २.२७ आदित्याः = मित्रावरुणौ दक्षः अंशः तुविजातः भगः अर्यमा च, ८.१८.४; ६; ७ अदितिः, ८.१९.३४–३५ वरुणोऽर्यमा मित्रश्च, ८.४७.९ अदितिः, ८.६७.१०–१२ अदितिः–बृहद्दे.

२. १०.३०.३–४ अपां नपादिति नाम्ना अग्निर्मध्यमः–बृहद्दे.

३. १०.१९.२ इन्द्राग्नी निपातभाजौ; ६ इन्द्रः–बृहद्दे.

४. १०.१७.११–१३ सोमः–बृहद्दे.

५. ७.१०४.२३ आत्मन आशीः–बृहद्दे.

६. ८.३१.१–२ शक्रो यजतां पतिः, ३–४ यज्वा–बृहद्दे.

७. १.१३.१ इध्मः–बृहद्दे.

८. १.२८.१–४ इन्द्रोलूखलौ (इति यास्कः कात्थक्यश्च), १.८०.१६ दध्यङ् मनुरथर्वा च निपातिताः, १.१३२.६ इन्द्रापर्वतौ, १.१७०.२; ४ इन्द्रः, १; ३ अगस्त्यः, ३.३३.६ विश्वामित्रः, ३.३३.७ नद्यः, षष्ठ्यां सप्तम्यां च इन्द्रसवितारौ निपातिनौ, ४.३१.१५ सूर्यः (आश्वलायनः), ६.३७.३ वायुरिन्द्रश्च, ६.४४.२२–२४ सोमः। इन्द्र इत्येके। ७.१८–३२ मरुतो निपातभाजः, ७.३२.१० पैजवनस्य दानस्तुतिः, ७.१०४.८ इन्द्रासोमौ, ८.६.३० अग्निर्वैश्वानरः (इति शाकपूणिमुद्गलौ), ८.१७.१४[१–२] वास्तोष्पतिः, ८.३३.१९ दानवी इन्द्रमब्रवीत्, ८.४६.४–५

(अग्रिमे पृष्ठे)

१.२२; १.२३; १.५१-५७; १.६१-६३; १.८०-८४; १.१००-१०४; १.१२९.१-५; ७-११; १.१३०-१३१; १.१३२.१-५; ६^{२}; १.१३३; १.१३५.४-८; १.१३९.६; १.१४२.१३; १.१६७.१; १.१६९; १.१७०; १.१७३-१७८; २.११-२२; २.३०.१-५; ७; ८^{२}; १०; २.४१.१०-१२; ३.३०-३२; ३.३३.६-७; ३.३४-५२; ३.५३.२-१४; २१-२४; ४.१६; ४.१७; ४.१९-२२; ४.२३.१-७; ११; ४.२४; ४ २५; ४.२९; ४.३०.१-८; १२-२४; ४.३१; ४.३२.१-२२; ५.२९.१-८; ९^{२}; १०-१५; ५.३१.१-७; ८$^{१-२}$; १०-१३; ५.३२-३९; ५.४०.१-४; ६.१७-२०; ६.२१.१-८; १०; १२; ६.२२-२६; ६.२७.१-७; ६.२९-४४; ६.४५.१-३०; ६.४६; ६.४७.६-१९; २०^{४}; २१; ३१$^{३-४}$; ७.१८.१-२१; ७.१९-३२; ७.५५.२-८; ७.९७.१; ७.९८.१-६; ७.१०४.८; १६; १९-२२; २४; ८.१.१-२९; ८.२.१-४०; ८.३.१-२०; ८.४.१-१४; ८.६.१-४५; ८.१२-१७; ८.२१.१-१६; ८.२४.१-२७; ८.३२-३४; ८.३६; ८.३७; ८.४१.२-४२; ८.४६.१-२०; २९-३१; ३३; ८.४९-५३; ८.५४.१-२; ५-८; ८.६१; ८.६२; ८.६३.१-११; ८.६४-६६; ८.६८.१-१३; ८.६९.१-१०; १३-१८; ८.७०; ८.७६-७८; ८.८०.१-९; ८.८१; ८.८२; ८.८८-९२; ८.९३.१-३३; ८.९५; ८.९६.१-१३; ८.९७-९९; ८.१००.१-९; १२; १०.८.७-९; १०.२२; १०.२३; १०.२४.१-३; १०.२७; १०.२८.१; ३-५; ७; ९; ११; १०.२९; १०.३३.२; ३; १०.३८; १०.४२-४४; १०.५४; १०.५५; १०.६०.५; १०.७३; १०.७४; १०.८९.१-४; ६-१६; १०.९९; १०.१०३.१-३; ५-११; १०.१०४; १०.१०५; १०.१११-११३; १०.११६; १०.१२०; १०.१२४.९; १०.१३१.१-३; ६; ७; १०.१३३; १०.१३४; १०.१३८; १०.१४४; १०.१४७; १० १४८; १०.१५२; १०.१५३; १०.१६०; १०.१६१; १०.१६७.१; २; ४; १०.१७१; १०.१७९; १०.१८०

इन्द्रः अग्निश्च[1] १.२१; १.१०८; १.१०९; १.१३९.९; ३.१२; ३.२५.४; ५.२७.६; ५.८६; ६.५९; ६.६०; ७.९३; ७.९४; ८.३८; ८.४०; ८.४५.१

इन्द्रः अदितिर्वामदेवश्च। द्दश्यताम्—संवादः

इन्द्रः इन्द्राग्नी वृषाकपिश्च १०.८६

इन्द्रः इन्द्रासोमौ वा[2] ४.२८

इन्द्रः उशना वा[3] ५.२९.९^{३}; ५.३१.८^{४}

इन्द्रः उषाश्च[4] ४.३०.९-११

इन्द्रः ऋणञ्चयश्च ५.३०

इन्द्रः ऋतदेवो वा ४.२३.८-१०

इन्द्रः ऋतवश्च १.१५.१-५

(गतपृष्ठात्)

मित्रोऽर्यमा मरुतश्च, ८.६५.१० देवाः (इति भागुरिः), १०-१२ विश्वे देवाः (इति यास्कः), ८.१००.८ सुपर्णः, ९ वज्रः, १०.२७.१५ मरुतः, १६ वज्रः, १७$^{१-२}$ अग्निरिन्द्रश्च सोमश्च, १७$^{३-४}$ पर्जन्यावायू, १८ अग्निः, १९ सूर्यः, २०-२१ इन्द्रो वज्रश्च, २२ इन्द्रस्य धनुः, २३ पर्जन्योऽनिलो भास्करश्च, २३^{४} अनिलो भास्करश्च, २४ इन्द्रः सूर्यो वा, १०.४४.११$^{१-२}$ बृहस्पतिः, १०.५५.५ सूर्याचन्द्रमसौ, १०.६०.५ ऐक्ष्वाकोः स्तुतिः, १०.१२०.६ आप्त्या निपातभाजः, १०.१२४.९$^{१-३}$ सोमः, ९^{४} इन्द्रः, १०.१६१ इन्द्राग्नी (इति यास्कः), लिङ्गोक्तदैवतम् (इत्येके)—बृहद्दे.

१. १.१३९.९ अथवा ऋषिः ऋषीनात्मानं वा स्तौति। इन्द्राग्नी निपातभाजौ, ८.४५ इन्द्रः—बृहद्दे.

२. इन्द्रासोमौ—बृहद्दे.

३. ५.३१.८^{४} उशनाः—बृहद्दे.

४. ४.३० उषा मध्यमा च (शाकटायनः), ४.३०.२४ भगः पूषा अर्यमा च—बृहद्दे.

इन्द्रः ऋभवश्च[1] ३.६०.५–७; ८.९३.३४
इन्द्रः कपिञ्जलरूपी २.४२; २.४३
इन्द्रः कुत्सश्च ५.३१.९
इन्द्रः कुत्सो वा ५.३१.८[3]
इन्द्रः गावो वा ६.२८.२; ८[4]
इन्द्रः त्वष्टा वा २.३२.२; ३
इन्द्रः द्यावापृथिव्यौ भा १०.५९.१०[1]
इन्द्रः द्रुघणो वा[2] १०.१०२
इन्द्रः नभश्च २.३६.५
इन्द्रः पर्जन्यात्मा अग्निश्च। दृश्यताम्–त्वष्टा अग्निश्च
इन्द्रः पर्वतश्च[3] १.१३२.६[1]; ३.५३.१
इन्द्रः पूषा च ६.५७
इन्द्रः पूषा वा[4] ८.४.१५–१८
इन्द्रः बृहस्पतिश्च[5] ४.४९; ४.५०.१०; ११; ७.९७.१०; ७.९८.७; ८.९६.१५
इन्द्रः ब्रह्मणस्पतिः सोमश्च १.१८.४
इन्द्रः ब्रह्मणस्पतिश्च २.२४.१२; ७.९३.३; ९
इन्द्रः मधुश्च २.३६.१
इन्द्रः मरुतश्च १.६.५; ७
इन्द्रः मरुतो वा १०.१०३.१३
इन्द्रः लिङ्गोक्तदेवता वा १०.१६७.३
इन्द्रः वरुणश्च १.१७; ३.६२.१–३; ४.४१; ४.४२.७–१०; ६.६८; ७.८२–८५; ८.५९
इन्द्रः वामदेवो वा[6] ४.२६.१–३
इन्द्रः वायुश्च १.२.४–६; १.२३.२; ३; २.४१.३; ४.४६.२–७; ४.४७.२–४; ७.९०.५–७; ७.९१.२; ४–७; ७.९२.२
इन्द्रः विश्वे देवा वा[7] १.१२१
इन्द्रः विष्णुश्च १.१५५.१–३; ६.६९; ७.९९.४–६
इन्द्रः श्येनो वा[8] ४.२७.५
इन्द्राणी इन्द्रश्च वृषाकपिश्च १०.८६
इन्द्राणी गुङ्गुः सिनीवाली राका सरस्वती वरुणानी च २.३२.८
इन्द्राणी वरुणानी अग्नायी च[9] १.२२.१२
इन्द्राश्वौ ४.३२.२३–२४
इन्द्रासोमौ २.३०.६; ६.७२; १०.८९.५
इन्द्रासोमौ इन्द्रो वा ४.२८
इन्द्रासोमौ रक्षोहणौ ७.१०४.१–७; १५; २५
इन्द्रो मरुत्वान्[10] १.२३.७–९; १.१६५; १.१७१.३–७
इन्द्रो वैकुण्ठः १०.४७–५०
इळः १.१३.४; १.४२.४; १.१८८.३; २.३.३; ३.४.३; ५.५.३; ७.२.३; ९.५.३; १०.७०.३; १०.११०.३
इळा। दृश्यताम्–देव्यः तिस्रः
इषवः[11] ६.७५.११–१२; १५–१६
इषुधिः ६.७५.५

उ

उपनिषत्। दृश्यन्ताम्–अप्तृणसूर्याः, गर्भस्राविण्यु°, प्रस्वापिन्य°, रोगघ्न°, सपत्नीबाधनम्।
उपमश्रवा मित्रातिथिपुत्रः १०.३३.६–९
उपाध्यायस्तुतिः ३.२६.९
उर्वशी १०.९५.१; ३; ६; ८–१०; १२; १४; १७

---

१. ८.९३.३४ ऋभवः–बृहद्दे.
२. द्रुघण इन्द्रो वा (इति यास्कः), विश्वे देवाः (इति शौनकः)–बृहद्दे.
३. इन्द्रापर्वतौ–बृहद्दे.
४. ८.४.१५–१६ इन्द्रः, १७–१८ पूषा (इति गालवः)–बृहद्दे.
५. ७.९८.७ इन्द्रः, ८.९६.१३–१५ इन्द्रो मरुतो बृहस्पतिश्च। इन्द्रः (इति शौनकः), इन्द्राबृहस्पती (ऐ. ब्रा)–बृहद्दे.
६. 'आद्याभिस्तिसृभिरिन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानम्' इति सर्वानुक्रमसूत्रम्। अहमित्यात्मसंस्तावः–बृहद्दे.
७. इन्द्रः। स्वरसामसु विश्वे देवाः–बृहद्दे.
८. ४.२७.१–५ श्येनस्तुतिः–बृहद्दे.
९. देवपत्न्य इन्द्राणी वरुणानी अग्नायी च–बृहद्दे.
१०. १.१६५ मारुतैन्द्रस्तु संवादः। १; २; ४; ६; ८; १०–१५ मरुतः, ३; ५; ७; ९ इन्द्रः–बृहद्दे.
११. ६.७५.११ इषुः, १२ कवचः, १५[1] दिग्ध इषुः, १५[2] अयोमुखी, १५[3,4] वारुणमस्त्रम्, १६ धनुर्मुक्त इषुः–बृहद्दे.

१. १.११३ रात्र्युषसौ, ७.४१.७ दृष्टभ्य आशीर्वा, ७.७६.१ मध्यमः (अग्निः)–बृहद्दे.
२. उषाश्चन्द्रसूर्ययोः प्रभा वा–बृहद्दे.
३. १.१३.७ नक्तोषासा–बृहद्दे.
४. ३.६०.३–४ इन्द्रो निपाती–बृहद्दे.
५. १०.१२१ प्रजापतिः–बृहद्दे.
६. कपोतः–बृहद्दे.
७. स्रवतां गर्भाणामनुमन्त्रणम् । अग्नी रक्षोहा–बृहद्दे.
८. इन्द्रः–बृहद्दे.

---

१. १०.९४ ग्रावा–बृहद्दे.

२. १०.८५.१९[१–२] सूर्यः, १९[३–४] चन्द्रमाः–बृहद्दे.

३. ४.४२ इन्द्रावरुणौ–बृहद्दे, 'षळाद्या आत्मस्तवः' इति सर्वानुक्रमसूत्रम् ।

४. प्राजापत्या दक्षिणा दक्षिणादातार इत्येके, ८–११ भोजाः–बृहद्दे.

५. ८.३१.१० आशीः, ११–१२ पूषा, १३ मित्रार्यमवरुणाः, १४ अग्निः, १५–१८ यज्वा–बृहद्दे.

६. ८.२४.२८–३० उषाः, ८.६८.१४ ऋतवः, १५–१९ ऋक्षाश्वमेधयोर्दानस्तुतिः, ८.७४.१३–१४ ऋषेरात्मस्तुतिः श्रुतर्वणः दानस्तुतिश्च, १५ परुष्णी–बृहद्दे.

ध

न

प

---

१. १.२७.१३ विश्वे देवाः, ८.८०.१० विश्वे देवाः, १०.७२ विश्वे देवाः, २[१-२] बृहस्पतिः, १०.८५.१७ विश्वे देवाः, १०.९८.१–३ बृहस्पतिः, ४–७ देवाः, ८–१२ अग्निः–बृहद्दे.

२. १.१३.९ तिस्रो देव्यः–बृहद्दे.

३. इन्द्रः–बृहद्दे । द्यावापृथिव्यौ इन्द्रश्च–सायणभाष्यम् ।

४. हविर्धाने–बृहद्दे.

५ द्यावाभूमी पृश्निर्वा–बृहद्दे । सर्वानु (६.४८) टिप्पणी द्रष्टव्या ।

६. अन्नम्–बृहद्दे.

७. नराशंसः–बृहद्दे.

८. १०.५९.४[१-३] सोमः, ४[४] निर्ऋतिः–बृहद्दे.

९. १०.६३.१५ मरुतः–बृहद्दे.

१०. ८.१०१.१४[१-२] अग्निः, १४[३] सूर्यः, १४[४] मध्यमोऽग्निः (ऐ. आ.)–बृहद्दे.

ब

भ

---

१. १०.१८.७–९ मृत्युः, १०–१३ पृथिवी–बृहद्दे.
२. आशिषः–बृहद्दे.
३. १.२३.१३–१५ पूषा आघृणिः, ६.५५.२ रुद्र इत्येके, १०.१७.३[१-२] पूषा, ३[३] पूषा अग्निर्वा, ३[४] अग्निः–बृहद्दे.
४. ५.८४ पृथिवी मध्यमा–बृहद्दे.
५. आत्मन आशीः–बृहद्दे.
६. कशा–बृहद्दे.
७. अभ्यावर्तिनः साञ्जयस्य च दानस्तुतिः–बृहद्दे.
८. ४.५०.७–९ पुरोधातुः कर्मशंसा, १०.६७.७[३-४] ब्रह्मणस्पतिः–बृहद्दे.
९. ७.३८.६[२] भगः–बृहद्दे.

भारती । दृश्यताम्—देव्यः तिस्रः
भावयव्यः[१] १.१२६.१-५; ७
भाववृत्तम्[२] १०.१२९; १०.१३०; १०.१५४; १०.१९०
भूमिः ६.४७.२०[२]

म

मण्डूकाः ७.१०३
मधुः इन्द्रश्च । दृश्यताम्—इन्द्रः मधुश्च
मध्यमः अग्निः । दृश्यताम्—अग्निः अग्निर्मध्यमो वा
मन-आवर्तनम्[३] १०.५८
मन्युः १०.८३; १०.८४
मरुतः[४] १.६.४; ६; ८; ९; १.१५.२; १.३७-३९; १.६४; १.८५-८८; १.१३९.८; १.१६६; १.१६७.२-११; १.१६८; १.१७१.१; २; १.१७२; २.३०.११; २.३४; ३.२६.४-६; ५.५२-५९; ५.६१.१-४; ११-१६; ५.८७; ६.४८.११; १२; २०; २१; ६.६६; ७.५६-५८; ७.५९.१-११; ७.१०४.१८; ८.७; ८.२०; ८.९४; ८.९६.१४[४]; १०.७७; १०.७८
मरुतः अग्निर्मरुतश्च वा ५.६०
मरुतः अग्निश्च १.१९; ८.१०३.१४
मरुतः इन्द्रश्च[५] १.६.५; ७
मरुतः इन्द्रो वा १०.१०३.१३
मरुतः ऋतवश्च १.१५.२
मरुतः पृश्निर्द्यावाभूमी वा ६.४८.२२
मरुतः माधवश्च २.३६.२
मरुतः रुद्रो विष्णुश्च ५.३.३
मरुतः लिङ्गोक्तदेवता वा[६] ६.४८.१३-१५
मरुत्वानिन्द्रः । दृश्यताम्—इन्द्रो मरुत्वान्
माधवः मरुतश्च । दृश्यताम्—मरुतः माधवश्च
मायाभेदः[७] १०.१७७
मित्रः १.१५१.१; ३.५९
मित्रावरुणौ[८] १.२.७-९; १.१५.६; १.२३.४-६; १.४३.३; १.१३६.१-५; १.१३७; १.१३९.२; १.१५१.२-९; १.१५२; १.१५३; २.४१.४-६; ३.६२.१६-१८; ५.६२-७२; ६.६७; ७.५०.१; ७.६०.२-१२; ७.६१; ७.६२.४-६; ७.६३.५[२]; ६; ७.६४; ७.६५; ७.६६.१-३; १७-१९; ८.२५.१-९; १३-२४; ८.१०१.१-५[१-३]; १०.१३२.२-७
मित्रावरुणौ अग्निः रात्रिः सविता च १.३५.१
मित्रावरुणौ अदितिः सिन्धुः पृथिवी द्यौश्च, अथवाग्निः १.९४.१६[३-४]
मित्रावरुणौ अर्यमा च १.४१.१-३; ७-९
मित्रावरुणौ ऋतवश्च १.१५.६
मित्रावरुणौ नभस्यश्च २.३६.६
मित्रावरुणौ रुद्रश्च[९] १.४३.३
मित्रातिथिपुत्रः । दृश्यताम्—उपमश्रवाः
मुसलम् । दृश्यताम्—उलूखलमुसले
मृत्युः १०.१८.१-४
मृत्युविमोचिनी ७.५९.१२

य

यक्ष्मनाशनम् १०.८५.३१; १०.१६३

---

१. १.१२६.६; ७ जायापत्योः संप्रवादः—बृहद्दे.
२. १०.१२९ परमेष्ठी । भाववृत्तम्—बृहद्दे.
३. जीवावृत्तिः सुबन्धोर्मनसः स्तवो वा—बृहद्दे.
४. ३.२६.४-६ 'तृचौ वैश्वानरीयमारुतौ'—सर्वानु. षड्गुरुशिष्यमते द्वितीयतृचस्य मारुतोऽग्निर्देवता । ५.५६.८रोदसी,५.५७.१रुद्राः,५.८७ मरुतः । विष्णुर्निपातभाक्, ६.४८.११-१३ मरुतः, १४-१५मरुत आदित्या विश्वे देवा वा, ८.९६.१३-१५इन्द्रो मरुतः बृहस्पतिश्च । इन्द्रः (इति शौनकः), इन्द्राबृहस्पती (ऐ.ब्रा.)—बृहद्दे.
५. सप्तममन्त्रस्य तृतीयपाद इन्द्रामरुद्देवताकः—बृहद्दे.
६. ६.४८.११-१३ मरुतः, १४-१५ मरुत आदित्या विश्वे देवा वा—बृहद्दे.
७. सूर्यो मायाभेदो वा । १०.१७७.२ वाक् (इति शौनकः)—बृहद्दे.
८. १.१५२.६ अदितिरग्निर्वा । अदितिरेवाग्निरिति शौनकः, ७.६०.५ अर्यमा मित्रावरुणौ च, ८.२५.१०-२१ विश्वे देवाः, २२-२४ वरोर्दानस्तुतिः, ८.१०१.५[१-३] अर्यमा च—बृहद्दे.
९. मित्रावरुणौ रुद्रो विश्वे देवाश्च—बृहद्दे.

यजमानपत्नीहोत्राशिषः[१] १०.१८३.१
यजमानप्रशंसा इज्यास्तवश्च ८.३१.१–४
यजमानप्रशंसा दक्षिणा वा। दृश्यताम्–दक्षिणा तद्दातारो यजमाना वा
यथानिपातम्[२] १०.१२४.५–८
यमः[३] १०.१०.१; ३; ५–७; ११; १३; १०.१४.१–५; १३–१६; १०.१३५
यमी १०.१०.२; ४; ८–१०; १२; १४
यूपः १.३६.१३; १४; ३.८.१–५
यूपाः ३.८.६; ७; ९; १०
यूपाः छिन्नयूपो वा ३.८.११
यूपा विश्वे देवा वा[४] ३.८.८

र

रक्षोहणौ। दृश्यताम्–इन्द्रासोमौ रक्षोहणौ
रक्षोहा। दृश्यताम्–अग्नी रक्षोहा
रतिः १.१७९
रथः[५] ६.४७.२६–२८; ६.७५.८
रथगोपाः ६.७५.९
रथवीतिर्दाल्भ्यः ५.६१.१७–१९
रथाङ्गानि ३.५३.१७–२०
रश्मयः ६.७५.६[२]
राका २.३४.४; ५; दृश्यताम्–इन्द्राणी गुङ्गुः
राजयक्ष्मघ्नम् १०.१६१
राज्ञः स्तुतिः[६] १०.१७३; १०.१७४
रात्रिः १०.१२७; दृश्यताम्–अग्निः मित्रावरुणौ
रात्र्युषाश्च १.११३.१[३.४]
रुद्रः[७] १.४३.१; २; ४–६; १.११४; २.३३; ५.४२.११; ७.४६; ७.५९.१२
रुद्रासोमौ ६.७४
रुद्रो मरुतो विष्णुश्च[८] ५.३.३
रुद्रो मित्रावरुणौ च १.४३.३
रोगघ्न उपनिषत् १.५०.११–१३
रोदसी ३.५५.१२–१४
रोदसी द्युनिशौ वा ३.५५.१५
रोमशा[९] १.१२६.६

ल

लबः[१०] १०.११९
लिङ्गोक्तदेवताः[११] १.१३६.६; ७; २.३२.८; ६.४७.२०[१]; ६.७५.१०; १७–१९; ७.४१.१; ७.४४.१; १०.१४.६; १०.५९.७; १०.१२४.५–८; १०.१३२.१; १०.१८४
लिङ्गोक्तदेवताः अग्निर्वा ४.१३; ४.१४
लिङ्गोक्तदेवताः इन्द्रो वा १०.१६७.३
लिङ्गोक्तदेवताः पितरो वा[१२] १०.१४.७–९
लिङ्गोक्तदेवताः मरुतो वा ६.४८.१३–१५

व

वधूवासःसंस्पर्शनिन्दा १०.८५.२९; ३०
वनस्पतिः १.१३.११; १.१४२.११; १.१८८.१०; २.३.१०; ३.४.१०; ५.५.१०; ७.२.१०; ९.५.१०; १०.७०.१०; १०.११०.१०
वरुः सौषाम्णः (दानस्तुतिः) ८.२४.२८–३०
वरुणः १.२४.६–१५; १.२५; २.२८; ५.८५; ७.८६–८९; ८.४१; ८.४२.१–३; ८.६९.११[२]; १२
वरुणः अग्निश्च ४.१.२–५
वरुणः अदितिः सिन्धुः पृथिवी द्यौर्मित्रश्च, अथवाग्निः १.९४.१६[३–४]

---

१. १०.१८३.१ पुत्रकामस्याशीः; २ पुत्रकामाया आशीः; ३ ऋषेरात्मस्तवः–बृहद्दे.
२. १०.१२४.५ वरुणः, ६ सोमः, ७–८ वरुणः–बृहद्दे.
३. १०.१४.१–५ यमो मध्यमः, १०.१३५ द्युस्थानो यमः–बृहद्दे.
४. विश्वे देवाः–बृहद्दे.
५. ६.४७.२६[१] भाववृत्तम्, ६.७५.८ आयुधागारम्–बृहद्दे.
६. राज्ञेऽभिषिक्तायानुमन्त्रणे–बृहद्दे.
७. २.३३.११ ऋषिर्मृगमस्तौत्, ७.५९.१२ त्र्यम्बकः–बृहद्दे.
८. ५.३.३ मरुतो रुद्रो विष्णुश्च–औफ्रेख्ट् ऋ. २ पृ. ४७७.
९. दृश्यतां टिप्पणी ‘भावयव्यः’
१०. लब आत्मानं तुष्टाव–सर्वानु.
११. ६.७५.१० रणदेवताः, ६.७५.१७ युद्धादिः, १८ कवचस्य बध्यतः स्तुतिः, १९ युयुत्सुः, १९[४] आत्मन आशिषः–बृहद्दे.
१२. १०.१४.७–९ प्रेताशिषः–बृहद्दे.

---

१. योद्धा वर्मी–बृहद्दे.

२. ७.३३ वसिष्ठागस्त्ययोः तनयैः सह इन्द्रेण संवादः–बृहद्दे.

३. वाक्–बृहद्दे.

४. वाक्–बृहद्दे । 'वागाम्भृणी तुष्टावात्मानम्'–सर्वानु.

५. १०.८५.२० सूर्या, २१–२२ गन्धर्वो विश्वावसुः, २३ दंपती, २४–२८ वधूः–बृहद्दे.

६. 'द्वृच आत्मस्तुतिर्वा'–सर्वानु.

७. इन्द्रसूर्यौ निपातिनौ–बृहद्दे.

८. १.८९.१; २; ८; ९ देवाः, १.१३९.११ देवाः, ५.४१.१९ इळा, ५.४२.३ सविता (शौनकः), ७–९ बृहस्पतिः, १० मरुतः, १४ इळस्पतिः (शाकपूणिः), पर्जन्याग्नी (गालवः), पूषा (यास्कः), इन्द्रः (शौनकः), वैश्वानरः (भागुरिः), १५ मरुतः, १८ अश्विनौ, ५.४३.३ वायुः, ४ सोमः, ५ इन्द्रः, ६ अग्निः, ७ घर्मः, ८ अश्विनौ, ९ वायुः पूषा च, १०[१–२] अग्निः, १०[३–४] दिवौकसः, ११ वाङ्मध्यमा, १२ बृहस्पतिः, ५.४४.१ सोमो देवा इन्द्रः प्रजापतिर्वा, ४ वायुः, ८ आदित्याः, ५.५१.५ वायुः, ४; ६; ७ इन्द्रवायू, ६.५१.१–२ सूर्यः, ६.५२.१६ अग्नीपर्जन्यौ, ८.२५.१०–२१ विश्वे देवाः, ८.५४.३–४ बहुदैवतः प्रगाथः, ८.६९.११[१] इन्द्रोऽग्निर्विश्वे देवाश्च, ८.८३ देवाः, १०.३६.१२–१४ सविता (इत्येके), १४ सविता (शौनकयास्कगालवाः), १०.६२.७ अङ्गिरसां स्तुतिः, १०.६४.५ अदितिः, १०.६६.१४–१५ वाङ्मध्यमा मनुश्च, १०.९३.१४–१५ राज्ञां दानस्तुतिः, १०.११४ एकेषां मते देवाः; इन्द्रः; छन्दांसि; अग्निर्मध्यमश्च, १०.१५७ विश्वैर्देवैरादित्यैर्मरुद्भिश्च सहेन्द्रः–बृहद्दे.

४; ८.५८.२; ३; ८.६९.११[१]; ८.८३; १०.३१; १०.३२; १०.३३.१; १०.३५; १०.३६; १०.५६; १०.५७; १०.६१; १०.६२.७; १०.६३.१–१४; १७; १०.६४–६६; १०.९२; १०.९३; १०.१००; १०.१०९; १०.११४; १०.१२६; १०.१२८; १०.१३७; १०.१४१; १०.१५५.५; १०.१५७; १०.१६५; १०.१८१

विश्वे देवाः अग्निर्वा[१] ९.६७.२७

विश्वे देवाः अङ्गिरसो वा[२] १०.६२.१–६

विश्वे देवाः इन्द्रो वा १.१२१

विश्वे देवाः ऋत्विजो वा[३] ८.५८.१; १०.१०१

विश्वे देवाः यूपा वा ३.८.८

विष्णुः १.२२.१७–२१; १.१५४; १.१५५.४–६; १.१५६; ७.९९.१–३; ७; ७.१००

विष्णुः इन्द्रश्च । दृश्यताम्–इन्द्रः विष्णुश्च

विष्णुः देवा वा १.२२.१६

विष्णुः रुद्रो मरुतश्च ५.३.३

वृषाकपिरैन्द्रः इन्द्राणीन्द्रश्च[४] १०.८६

वेनः १०.१२३

वैकुण्ठः इन्द्रः । दृश्यताम्–इन्द्रो वैकुण्ठः

वैददश्विः । दृश्येताम्–पुरुमीळ्हः, तरन्तः

वैवस्वतः । दृश्येताम्–यमः, यमी

वैश्वानरः (अग्निः) १.५९; १.९८; ३.२–३; ३.२६.१–३; ४.५; ६.७–९; ७.५; ७.६; ७.१३

वैश्वानरः सूर्यश्च । दृश्यताम्–सूर्यः वैश्वानरश्च

व्रश्चनी ३.८.११

श

शकधूमः १.१६४.४३[१]

शची पौलोमी[५] (आत्मानं तुष्टाव) १०.१५९

शत्रुनाशनम् १०.१६६

शशीयसी तरन्तमहिषी ५.६१.५–८

शान्त्यर्थः पादः १०.२०.१[१]

शुक्रः त्वष्टा च । दृश्यताम्–त्वष्टा शुक्रश्च

शुचिः अग्निश्च । दृश्यताम्–अग्निः शुचिश्च

शुनः ४.५७.४

शुनासीरौ[६] ४.५७.५; ८

श्येनः ४.२६.४–७; ४.२७.१–४

श्येनः इन्द्रो वा ४.२७.५

श्रद्धा १०.१५१

श्रुतर्वा आर्क्ष्यः (दानस्तुतिः) ८.७४.१३–१५

श्वानौ १०.१४.१०–१२

स

संवत्सरसंस्थं कालचक्रवर्णनम् १.१६४.४८

संवादः इन्द्रादितिवामदेवानाम् ४.१८

संज्ञानम् १०.१९१.२–४

सदसस्पतिः १.१८.६–८

सदसस्पतिर्नराशंसो वा १.१८.९

सपत्नघ्नम् १०.१६६

सपत्नीबाधनम्[७] (उपनिषत्) १०.१४५

समित् १.१४२.१

समिद्धः १.१३.१

सरण्यूः १०.१७.१; २

सरमा १०.१०८.१; ३; ५; ७; ९

सरस्वती[८] । १.३.१०–१२; १.१६४.४९, २.३०.८[१]; २.४१.१६–१८; ६.६१; ७.९५.१; २; ४–६; ७.९६.१–३; १०.१७.७–९ दृश्येताम्–देव्यः तिस्रः; इन्द्राणी गुङ्गुः

सरस्वान् ७.९५.३; ७.९६.४–६

सरस्वान् सूर्यो वा १.१६४.५२

---

१. विश्वे देवाः–बृहद्दे.

२. १०.६२.१–७ अङ्गिरसां स्तुतिः–बृहद्दे.

३. १०.१०१ ऋत्विक्स्तुतिः–बृहद्दे.

४. वृषाकपिः–बृहद्दे.

५. पौलोमी स्वान् गुणान् सपत्नीनां च शंसति–बृहद्दे.

६. ४.५७.८[१] कृषिः, ८[२] कृषिजीवा मनुष्याः, ८[३] पर्जन्यः, ८[४] धनम् । अथवा सर्वमिदं सूक्तं कृषिदेवताकम्–बृहद्दे.

७. भाववृत्तमौपनिषदं सूक्तम् । १–५ सपत्न्यपनोदिकाः, ६ पतिसंवननी–बृहद्दे.

८. २.३०.८[१] वाङ्मध्यमा–बृहद्दे.

सविता[1] १.२२.५–८; १.२४.३; ४; १.३५.२–११; २.३८; ३.६२.१०–१२; ४.५३; ४.५४; ५.८१; ५.८२; ६.७१; ७.३८.१–६[१]; ७.४५; १०.१३९.१–३; १०.१४९

सविताग्निर्मित्रावरुणौ रात्री च १.३५.१

सविताग्निर्वा ९.६७.२५

सविताग्निश्च अथवाग्निः ९.६७.२६

सविता भगो वा[2] १.२४.५; ७.३८.६[२]

ससर्परी वाक्। दृश्यताम्–वाक् ससर्परी

साध्याः १.१६४.५०

सारथिः ६.७५.६[१]

सार्ञ्जयः। दृश्यताम्–प्रस्तोकः

सार्पराज्ञी सूर्यो वा[3] १०.१८९

सावर्णिः (दानस्तुतिः) १०.६२.८–११

साहदेव्यः सोमकः ४.१५.७–८

सिनीवाली २.३२.६; ७; दृश्यताम्–इन्द्राणी गुङ्गुः

सिन्धुः पृथिवी द्यौर्मित्रो वरुणोऽदितिश्च, अथवाग्निः १.९४.१६[३–४]

सीता ४.५७.६; ७

सुदाः पैजवनः (दानस्तुतिः) ७.१८.२२–२५

सुबन्धुजीवाह्वानम्[4] १०.६०.७–११

सुबन्धोर्लब्धसंज्ञस्य स्पर्शनम् १०.६०.१२

सूर्यः[5] १.५०; १.११५; १.१६४.४६; ४७; ४.४०.५; ५.४०.५; ७.६०.१; ७.६२.१–३; ७.६३.१–५[१]; ७.६६.१४–१६; ८.१०१.११; १२; १०.३७; १०.१३९.१–३; १०.१५८; १०.१७०

सूर्यः अग्निरनिलश्च ८.१८.९

सूर्यः अग्निर्वायुश्च १.१६४.४४; १०.१३६

सूर्यः अग्निश्च ८.५६.५

सूर्यः अप्तृणे च १.१९१

सूर्यः निर्ऋतिश्च १०.५९.४

सूर्यः पर्जन्याग्नी वा १.१६४.५१

सूर्यः वाग्निर्वा। दृश्यताम्–अग्निर्वा सूर्यो वा

सूर्यः वैश्वानरश्च[6] १०.८८

सूर्यः सरस्वान् वा १.१६४.५२

सूर्यः सार्पराज्ञी वा १०.१८९

सूर्यप्रभा उषा वा ८.१०७.१३

सूर्या[7] १०.८५.३२–४७

सूर्याविवाहः[8] १०.८५.६–१६

सोमः[9] १.४३.७–९; १.९१; १.१६४.४३[२]; ३.६२.१३–१५; ६.४७.१–५; ७.१०४.९; १२; १३; ८.४८; ८.७९; १०.२५; १०.८५.१–५

सोमः[10] (पवमानः) ९.१–४; ९.६–६५; ९.६६.१–१८; २२–३०; ९.६७.१–९; १३–२२; २८–३०; ९.६८–११४

सोमः अग्निश्च १.९३; १०.१९.१[२]

सोमः अधिषवणचर्म वा १.२८.९

सोमः अर्कश्च १०.८५.१८

सोमः आपो वा १०.१७.११–१३

---

१. ५.८२.४ दुःस्वप्ननाशिनी, ७.३८.१[३–४]; ५[२] अहिः–बृहद्दे.

२. ७.३८.६[२] भगः–बृहद्दे.

३. सार्पराज्या आत्मस्तवः। सूर्य इत्येके। वागिति मुद्गलशाकपूणिशाकटायनाः–बृहद्दे.

४. १०.६०.७ सुबन्धुजीवाह्वानम्, ८–१२ 'सूक्तशेषं जगुश्चास्य चेतसो धारणाय ते'–बृहद्दे.

५. १.५०.६ द्युभक्तिर्वरुणः, ४.४०.५ अग्निर्वायुः सूर्यश्च। सूर्य इत्यैतरेयके, ७.६६.१४–१६ तिस्रः सौर्यः आशीः, १०.३७.६ निपातिन्यो देवताः, ११–१२ विश्वे देवाः–बृहद्दे.

६. त्रयोऽग्नयः–बृहद्दे.

७. १०.८५.३२–३३ परिपन्थिनः, ३४ वधूवासः प्रतिगृह्णन्, ३५ भाववृत्तिः, ३६ धनाशिषः, ३७ संयोगाशिषः, ३८–४७ दंपतीभ्यामाशिषः–बृहद्दे.

८. १०.८५.६–१३ सूर्यायै भाववृत्तम्, १४–१५ अश्विनौ, १६ सूर्यः–बृहद्दे.

९. ६.४७.१–५ सोमः। अथवा इन्द्रः प्रधानः सोमो निपातभाक्, १०.८५.१ सत्यसूर्यर्तसोमैः सह सूर्या, २–४ सोमः, ५ चन्द्रमाः–बृहद्दे.

१०. ९.६७.२९ अग्निः, ९.७३ अग्नी रक्षोहा, ९.८३ घर्मसंस्तवः, ९.८७.३[२] ऋभुः, ९.११२ इन्द्रः–बृहद्दे.

सोमः इन्द्रश्च २.३०.६; ४.२८; ६.७२; १०.८९.५
सोमः इन्द्रश्च (रक्षोहणौ) ७.१०४.१–७; १५; २५
सोमः इन्द्रश्च अथवेन्द्रः ४.२८
सोमः इन्द्रो बृहस्पतिश्च १.१८.४
सोमः निर्ऋतिश्च १०.५९.४
सोमः पवमानः पूषा वा[1] ९.६७.१०–१२
सोमः पूषा च[2] २.४०.१–६[2]
सोमः पूषाऽदितिश्च[2] २.४०.६[2]
सोमः रुद्रश्च ६.७४
सोमः वरुणः कवचश्च ६.७५.१८
सोमः हरिश्चन्द्रः प्रजापतिर्वा १.२८.९
सोमकः साहदेव्यः ४.१५.७; ८
सौचीकः अग्निः। दृश्यताम्–अग्निः सौचीकः
स्वनयः (दानस्तुतिः) १.१२५
स्वस्त्ययनम् १०.१८५
स्वाहाकृतयः १.१३.१२; १.१४२.१२; १.१८८.११; २.३.११; ३.४.११; ५.५.११; ७.२.११; ९.५.११; १०.७०.११; १०.११०.११

ह

हरिस्तुतिः[3] १०.९६
हरिश्चन्द्रः प्रजापतिः अधिषवणचर्म वा[4] १.२८.९
हविर्धानम् १०.१३
हविर्धाने द्यावापृथिव्यौ वा २.४१.१९[1,2]; २०; २१
हविर्धाने वा द्यावापृथिव्यौ वाग्निर्वा २.४१.१९[3]
हविषां स्तुतिरग्निर्वा ८.७२
हस्तघ्नः[5] ६.७५.१४
होतारौ दैव्यौ प्रचेतसौ[6] १.१३.८; १.१४२.८; १.१८८.७; २.३.७; ३.४.७; ५.५.७; ७.२.७; ९.५.७; १०.७०.७; १०.११०.७

---

१. पूष्णा सह पवमानः–बृहद्दे.
२. २.४०.६ सोमापूषणौ अदितिश्च–बृहद्दे.
३. इन्द्रः–बृहद्दे.
४. अधिषवणचर्म सोमो वा–बृहद्दे.
५. हस्तत्राणम्–बृहद्दे.
६. दैव्यौ होतारौ–बृहद्दे.

॥ श्रीः ॥

॥ छन्दःसूची ॥

गायत्री (२४)

१.१.१–९; २.१–९; ३.१–१२; ४.१–१०; ५.१–१०; ६.१–१०; ७.१–१०; ८.१–१०; ९.१–१०; १२.१–१२; १३.१–१२; १४.१–१२; १५.१–१२; १६.१–९; १७.१–९[१]; १८.१–९; १९.१–९; २०.१–८; २१.१–६; २२.१–२१; २३.१–१८; २१[२]; २४.३–५; २५.१–२१; २६.१–१०; २७.१–१२; २८.७–९; ३०.१–१५[३]; १७–२२; ३७.१–१५; ३८.१–१५; ४१.१–९; ४२.१–१०; ४३.१–८; ४६.१–१५; ५०.१–९; ७४.१–९; ७५.१–५; ७८.१–५; ७९.७–१२; ८४.१३–१५; ८६.१–१० ९०.१–८; ९१.५–१६; ९३.९–११; ९७.१–८; १२०.१; १०–१२; १३३.५; १७२.१–३; १८७.२; ४; ८–१०; १८८.१–११ [४७२]

२.६.१–८; ७.१–६; ८.१–५; ४१.१–१५; १९–२१ [३७]

३.११.१–९; १२.१–९; २४.२–५; २७.१–१५; २८.१; २; ६; ३७.१–१०; ४०.१–९; ४१.१–९; ४२.१–९; ५१.१०–१२; ५२.१–४; ५३.१३; ५९.६–९; ६२.४–१८ [१०४]

४.८.१–८; ९.१–८; १०.१–३[४]; ४; ६; ७[५]; १५.१–१०; ३०.१–७; ९–२३; ३१.१[६]–१५; ३२.१–२४; ४६.१–७; ४९.१–६; ५२.१–७; ५५.८–१०; ५६.५–७ [११९]

५.५.१–११; १३.१–६; १४.१–६; १९.१–२; २६.१–९; २८.५–६; ५१.१–४; ५३.८; १२; ६१.१–४; ६–८; १०–१९; ६८.१–५; ७०.१–४; ७१.१–३; ८२.२–९ [७९]

६.१६.१[७]–२६; २८–४५; ४५.१–३२[८]; ४७.२४; ५२.७–१२; ५३.१–७; ९–१०; ५४.१–१०; ५५.१–६; ५६.१–५; ५७.१–६; ६०.४–१२; ६१.४–१२ [१३७]

७.१५.१–१५; ३१.१–९; ५५.१; ५९.९–११; ६६.१–९; १७–१९; ८९.१–४; ९४.१–११; ९६.४–६; १०२.१–३ [६१]

८.२.१–२७; २९–४२; ३.२२; २३; ५.१–३६; ६.१–४८; ७.१–३६; ९.२; ३; २०; २१; ११.१[९]–९; १४.१–१५; १६.१–१२; १७.१–१३; २५ २३[१०]; २६.१६–१९; २१; २५; २८.१–३; ५; ३०.१; ३१.१–८; १०[११]–१३; ३२.१–३०; ३३.१६–१८; ३४.१६–१८; ३८.१–१०; ४३.१–३३; ४४.१–३०; ४५.१–४२; ४६.१[११]; २–४; ६; १०; २३; २९; ३३; [५५.१; २; ४; ५६.१–४] ६३.२; ३; ६; ८–११; ६४.१–१२; ६५.१–१२; ६७.१–२१; ६८.२; ३; ५; ६; ८; ९; ११–१९; ६९.४–६; ७१.१–९; ७२.१–१८; ७३.१–१८; ७४.२; ३; ५; ६; ८; ९; ११; १२; ७५.१–१६; ७६.१–१२; ७७.१–९; ७८.१–९; ७९.१–८; ८०.१–९; ८१.१–९; ८२.१–९; ८३.१–९; ८४.१–९ ८५.१–९; ९२.२–३३; ९३.१–३४; ९४.१–१२; १०१.३; १०२.१–२२; १०३.१०[१२] [७३३]

---

१. ४–५ पादनिचृतौ. २. प्रतिष्ठा. ३. ११ पादनिचृत्. ४. ३ पदपङ्क्तिः. ५. ४,६,७ पदपङ्क्त्य उष्णिहो वा. ६. ३ पादनिचृत्. ७. १,६ वर्धमाने. ८. २९ अतिनिचृत्; ३१ पादनिचृत्. ९. १ प्रतिष्ठा; २ वर्धमाना. १०. उष्णिग्गर्भा. ११. पादनिचृत्. १२. ह्रसीयसी.

९.१.१-१०; २.१-१०; ३.१-१०; ४.१-१०; ५.१-७; ६.१-९; ७.१-९; ८.१-९; ९.१-९; १०.१-९; ११.१-९; १२.१-९; १३.१-९; १४.१-८; १५.१-८; १६.१-८; १७.१-८; १८.१-७; १९.१-७; २०.१-७; २१.१-७; २२.१-७; २३.१-७; २४.१-७; २५.१-६; २६.१-६; २७.१-६; २८.१-६; २९.१-६; ३०.१-६; ३१.१-६; ३२.१-६; ३३.१-६; ३४.१-६; ३५.१-६; ३६.१-६; ३७.१-६; ३८.१-६; ३९.१-६; ४०.१-६; ४१.१-६; ४२.१-६; ४३.१-६; ४४.१-६; ४५.१-६; ४६.१-६; ४७.१-५; ४८.१-५; ४९.१-५; ५०.१-५; ५१.१-५; ५२.१-५; ५३.१-४; ५४.१-४; ५५.१-४; ५६.१-४; ५७.१-४; ५८.१-४; ५९.१-४; ६०.१; २; ४; ६१.१-३०; ६२.१-३०; ६३.१-३०; ६४.१-३० ६५.१-३०; ६६.१-१७; १९-३०; ६७.१-१५; १९-२६; २८; २९; १०१.२-३; १०८.१३[१]; [६००]

१०.९.१-७[२]; १९.६; २०.३-८; ३३.४-९; ५७.१-६; ६०.१-५; ६२.१०; १०१.४; ६; १०५.१[३]; ११८.१-९; ११९.१-१३; १२७.१-८; १४४.१; ३; ४; १५३.१-५; १५६.१-५; १५८.१-५; १७१.१-४; १७५.१-४; १७६.२; १८५.१-३; १८६.१-३; १८७.१-५; १८८.१-३; १८९.१-३ [१०८]

उष्णिह् (२८)

१.२३.१९[४]; ७९.४-६; ८४.७-९; ९१.१७; ९२.१३-१८; १२०.२[५]; ५[६]; ६[७]; १५०.१-३; १८७.१[८] [२१]

३.१०.१-९; २८.१ [१०]

४.१०.८; ५७.५[९] [२]

५.४०.१-३; ५१.५-१०; ५३.१; १०; ११[१०]; १५[११]; ७२.१-३; ७८.१-३ [१९]

६.४३.१-४; ४८.१३; १८[१२]; ५१.१३-१५ [९]

७.६६.१६[१३] [१]

८.४.२१; ९.५[१४]; १२.१-३३; १३.१-३३; १५.१-१३; १८.१-२२; १९.३४; ३६[१४]; २२.११[१४]; २३.१-३०; २४.१-२९; २५.१-२२; २४; २६.१-१५; २२-२४; २८.४[१५]; ३०.२; ४६.५[१६]; १५[१७]; ३१; ६९.२; ७०.१३; १५[१५]; ९८.१-१२[१८]; १०३.८; १२[१६] [२२८]

९.६०.३[१५]; ६७.३०[१५]; १०२.१-८; १०३.१-६; १०४.१-६; १०५.१-६; १०६.१-१४ [४२]

१०.२६.१; ४; १०५.२-१०[१९]; १३२.१ [१२]

अनुष्टुभ् (३२)

१.१०.१-१२; ११.१-८; २३.२०; २२-२४; २८.१-६; ४३.९; ४५.१-१०; ४९.१-४; ५०.१०-१३; ८४.१-६; ९०.९; ९३.१-३; १२०.३[२०]; ४[२१]; ८[२२]; ९[२३]; १२६.६; ७; १३३.२-४; १४२.१-१३; १४९.१-५[२४]; १५८.६; १६४.५१; १७०.२-४; १७५.२-५; १७६.१-५; १८७.३; ५-७; ११[२५]; १९१.१-९; १४-१६ [११७]

२.५.१-८; ८.६; ३२.६-८; ४१.१६; १७ [१४]

३.८.३; ७; १३.१-७; २१.२; ३; २२.४; २४.१; २५.१-५[२६]; २९.१; ४; १०; १२; ३३.१३; ३७.११; ५३.१२; २०; २२ [२७]

---

१. यवमध्या. २. ५ वर्धमाना; ७ प्रतिष्ठा. ३. उष्णिग्वा. ४. पुरउष्णिक्. ५. ककुप्. ६. तनुशिरा. ७. अक्षरैः ८. अनुष्टुब्गर्भा. ९. पुरउष्णिक्. १०. १,१०,११ ककुभः. ११. १३,१८ पुरउष्णिहौ. १२. पुरउष्णिक्. १३. पुरउष्णिक्. १४. ककुप्. १५. पुरउष्णिक्. १६. ककुप्. १७. न्यङ्कुशिरा. १८. ७,१०,११ ककुभः; ९,१२ पुरउष्णिहौ. १९. २,७ पिपीलिकमध्ये. २०. काविराट्. २१. नष्टरूपी. २२. कृतिः २३. विराट्. २४. विराट्. २५. बृहती वा. २६. विराट्.

४.७.२–६; १०.५[१]; २४.१०; ३०.८; २४; ३७.५–८; ३९.६; ४७.१–४; ४८.१–५; ५७.१; ४; ६; ७ [२७]

५.७.१–९; ९.१–४; ६; १०.१–३; ५; ६; १६.१–४; १७.१–४; १८.१–४; १९.३; ४; २०.१–३; २१.१–३; २२.१–३; २३.१–३; २५.१–९; २७.४–६; २८.४; ३५.१–७; ३८.१–५; ३९.१–४; ४०.५; ९; ५०.१–४; ५१.१४; १५; ५२.१–५; ७–१५; ५३.३; ६१.५; ६४.१–६; ६५.१–५; ६६.१–६; ६७.१–५; ७३.१–१०; ७४.१–१०; ७८.५–९; ८२.१; ८३.९ ८४.१–३; ८६.१–५ [१५५]

६.२.१–१०; १४.१–५; १५.१७; १६.२७; ४७; ४८; २८.८; ४२.१–३; ४४.१–६; ४५.३३; ४७.२३; ४८.२२; ५१.१६; ५३.८; ५६.६; ५९;७–१०; ६०.१५; ७५.१२; १३; १५; १६; १९ [४५]

७.१.१–१८[२]; २२.१–८[२]; ३१.१०–१२; ५५.५–८; ५९.१२; ६७.१–७[२]; ९४.१२; १०३.१; १०४.२५ [४४]

८.२.२८; ३.२१; ५.३९; ८.१–२३; ९.७–९; ११[३]; १३; १६–१९; १०.३; २२.८; २४.३०; २६.२०; ३०.४; ३१.९; १४; ३३.१९; ३४.१–१५; ४२.४–६; ४६.८; १६[३]; [५५. ३; ५;] ६३.१; ४; ५; ७; ६६.१५; ६८.१; ४; ७; १०; ६९.१; ३; ७–१०; १२–१५; ७०.१४; ७४.१; ४; ७; १०; १३–१५; ७९.९; ८९.५; ६; ९१.३–७; ९२.१; ९५.१–९; १००.७–९; १०३.१४ [११२]

९.५.८–११; ६६.१८; ६७.२७; ३१; ३२; ९८.१–१०; १२; ९९.२–८; १००.१–९; १०१.१; ४–१६; ११०.१–३[४]; १०–१२[५] [५५]

१०.९.८; ९; १४.१३; १४; १६; १६.११–१४; १७.१४; १८.१४; १९.१–५; ७; ८; २०.२; ९[५]; २२.५; ७; ९; २४.४–६; २६.२; ३; ५–९; ५८.१–१२; ६०.६; ७; १०–१२; ६२.५; ८; ९; ७२.१–९; ८५.१–१३; १५–१७; २२.२५; २८–३३; ३५; ३८–४२; ४५–४७; ८७.२२–२५; ९०.१–१५; ९३.२; ३; १३; ९७.१–२३; १०३.१३; १०९.६; ७; १३१.४; १३५.१–७; १३६.१–७; १३७.१–७; १४१.१–६; १४२.७; ८; १४३.१–६; १४५.१–५; १४६.१–६; १५१.१–५; १५२.१–५; १५४.१–५; १५५.१–५; १५९.१–६; १६१.५; १६२.१–६; १६३.१–६; १६४.१; २; ४; १६६.१–४; १७३.१–६; १७४.१–५; १७६.१; ३; ४; १७९.१; १८४.१–३; १९०.१–३; १९१.१; २; ४ [२६०]

बृहती (३६)

१.१२०.७[६]; १३९.५; १७०.१; १७५.१[७]; १७९.५ [५]

२.४१.१८ [१]

३.९.१–८; ४४.१–५; ४५.१–५; ५३ १८ [१९]

५.५३.२; ५६.१; ४; ५; ८; ९ [६]

६.१५.१८; ४२.४; ४७.१९; ४८.५; १४; १९; २०; ५९.१–६; ६०.१४ [१४]

७.१४.१; ५५.२–४[८] [४]

८.१.५–३२; ३.२४; ५.३७; ३८; ९.१; ४; ६.१४; १५; १०.१; २२.७; ३०.३; ३३.१–१५; ४६.७; ११; १४[४]; १८[८]; १९; २०[९]; ६२.७–९; ६९.१७; १८; ७०.७–१२; ७८.१०; ८९.७; ९७.१–९; ११; १२[८]; १०१.१३; १०२.१–४ [८९]

९.९८.११; ९९.१; १०७.८; ९; ११०.४–९ [१०]

१०.१४.१५; १७.१३[१०]; २२.१–४; ६; ८; १०–१४[११]; ८५.३४[१२]; ९३.११[१३]; १५[१४];

---

१. महापदपङ्क्तिः. २. विराट्. ३. विराट्. ४. पिपीलिकमध्या. ५. विराट्. ६. विष्टारबृहती. ७. स्कन्धोग्रीवी. ८. उपरिष्टाद्बृहती. ९. विषमपदा. १०. अनुष्टुब्वा. ११. १–४,६,८,१०–१४ पुरस्ताद्बृहत्यः. १२. उरोबृहती. १३. न्यङ्कुसारिणी. १४. पुरस्ताद्बृहती.

१०१.५; १०२.१; ३; १२; १२६.१–७[१];
१३२.१[२]; १४४.१; १५०.१–३ [३२]

पङ्क्तिः (४०)

१.२९.१–७; ८०.१–१६; ८१.१–९; ८२.१–५;
८४.१०–१२; ८८.१; ६[३]; १०५.१–७;
९–१८; १६४.४२[४]; १६९.२[५] [६१]
२.२१.५[६]; २३.३[७] [२]
५.६.१–१०; ७.१०; ९.५; ७; १०.४; ७;
१६.५; १७.५; १८.५; २०.४; २१.४;
२२.४; २३.४; ३५.८; ३९.५; ५०.५;
५२.६; १६; १७; ५३.७; ९; १३; १४[८];
६१.९[७]; ६४.७; ६५.६; ७५.१–९;
७९.१–१० [५४]
६.२०.७[९]; ४४.७–९[९]; ७५.१७ [५]
७.९६.३[१०] [१]
८.१०.४[११]; १९.३५[१२]; ३७; ३१.१५–१८;
३५.२२; २४; ४६.९[१२]; १२[१३]; २१; २२;
२४; ३२; [५६.५] ६२.१–६; १०–१२;
६९.११; १६; ९१.१; २; ९६.४[९]; १०१.४[१२];
१०३.७; ९; ११; १३[१४] [३३]
९.१०८.१४[१२]; ११२.१–४; ११३.१–११;
११४.१–४ [२०]
१०.१८.११[१०]; २१.१–८[११]; २४.१–३[११];
२५.१–११[११]; ५९.८; ६०.८; ९; ८६.१–२३;
९३.१; ४–८; १०; १२; १४[१४]; ९[१६];
१३२.२; ६[१०]; १३४.७; १४०.१–२[१७];
३–५[१२]; १४४.५[१२]; ६[१७]; १४५.६; १६४.५;
१७०.४[११] [७२]

त्रिष्टुभ् (४४)

१.२४.१; २; ६–१५; २७.१३; ३०.१६;
३१.८; १६; १८; ३२.१–१५; ३३.१–१५;
३४.९; १२; ३५.२–८; १०; ११; ५१.१४;
१५; ५२.१३; १५; ५३.१०; ११; ५४.६;
८; ९; ११; ५८.६–९; ५९.१–७;
६०.१–५; ६१.१–१६; ६२.१–१३;
६३.१–९; ६४.१५; ७१.१–१०;
७२.१–१०; ७३.१–१०; ७६.१–५;
७७.१–५; ७९.१–३; ८४.१६–१८; ८५.५;
१२; ८८.२–५[१८]; ८९.६[१९]; ८–१०;
९१.१–४; १८–२३; ९२.५–१२;
९३.४–७; ८[२०]; १२; ९४.१५; १६;
९५.१–११; ९६.१–९ ९८.१–३; ९९.१;
१००.१–१९; १०१.८–११; १०२.११;
१०३.१–८; १०४.१–९; १०५.८[२१]; १९;
१०६.७; १०७.१–३; १०८.१–१३;
१०९.१–८; ११०.५; ९; १११.५; ११२.२४;
२५; ११३.१–२०; ११४.१०; ११;
११५.१–६; ११६.१–२५; ११७.१–२५;
११८.१–११; १२१.१–१५; १२२.१–१५[२२];
१२३.१–१३; १२४.१–१३; १२५.१–३;
६; ७; १२६.१–५; १३०.१०; १३३.१;
१३६.७; १३९.११; १४०.१०[२०]; १२; १३;
१४१.१२; १३; १४३.८; १४५.५;
१४६.१–५; १४७.१–५; १४८.१–५;
१५२.१–७; १५३.१–४; १५४.१–६;
१५७.५–६; १५८.१–५; १६१.१४;
१६२.१; २; ४; ५; ७–२२; १६३.१–१३;
१६४.१–११; १३; १४; १६–२२; २४–२८;
३०–३५; ३७–४०; ४३–५०; ५२;
१६५.१–१५; १६६.१४; १५; १६७.१–११;
१६८.८–१०; १६९.१; ३–८; १७०.५;
१७१.१–६; १७३.१–१३; १७४.१–१०;
१७५.६; १७६.६; १७७.१–५; १७८.१–५;
१७९.१–४; ६; १८०.१–१०; १८१.१–९;

---

१. उपरिष्टाद्बृहती. २. न्यङ्कुसारिणी ३. १,६ प्रस्तारपङ्क्ती. ४. प्रस्तारपङ्क्तिः. ५. चतुष्पदा विराट्. ६. विराड्रूपा सतोबृहती च। दृश्यतां षड्गुरुशिष्यभाष्यम्. ७. सतोबृहती. ८. ७,९,१३,१४ सतोबृहत्यः. ९. विराट्. १०. प्रस्तारपङ्क्तिः. ११. आस्तारपङ्क्तिः. १२. सतोबृहती. १३. विपरीता. १४. ७,९,११,१३ सतोबृहत्यः. १५. १,४–८,१०, १२,१४ प्रस्तारपङ्क्तयः. १६. अक्षरैः. १७. विष्टारपङ्क्तिः. १८. ५ विराड्रूपा. १९. विराट्स्थाना. २०. जगती वा. २१. यवमध्या महाबृहती. २२. ५,६ विराड्रूपे.

१८२.६; ८; १८३.१-६; १८४.१-६; १८५.१-११; १८६.१.-११; १८९.१-८; १९०.१-८; १९१.१३[१] [७४२]

२.३.१-६; ८-११; ४.१-९; ९.१-६; १०.१-६; ११.१-२१[२]; १२.१-१५; १३.१३; १४.१-१२; १५.१-१०; १६.९; १७.८; ९; १८.१-९; १९.१-९; २०.१-९[३]; २१.६; २३.१५; १९; २४.१२; १६; २७.१-१७; २८.१-११; २९.१-७; ३०.१-१०; ३१.७; ३३.१-१५; ३४.१५; ३५.१-१५; ३८.१-११; ३९.१-८; ४०.१-६; ४२.१-३ [२३०]

३.१.१-२३; ४.१-११; ५.१-११; ६.१-११; ७.१-११; ८.१; २; ४-६; ८-११; ९.९; १४.१-७; १५.१-७; १७.१-५; १८.१-५; १९.१-५; २०.१-५; २१.१; ४; २२.१-३; ५; २३.१; २; ४; ५; २६.७-९; २८.४; २९.२; ३; ५; ७-९; १३; १६; ३०.१-२२; ३१.१-२२; ३२.१-१७; ३३.१-१२; ३४.१-११; ३५.१-११; ३६.१-११; ३८.१-१०; ३९.१-९; ४३.१-८; ४६.१-५; ४७.१-५; ४८.१-५; ४९.१-५; ५०.१-५; ५१.४-९; ५२.५; ७; ८; ५३.१-९; ११; १४; १५; १७; १९; २१; २३; २४; ५४.१-२२; ५५.१-२२; ५६.१-८; ५७.१-६; ५८.१-९; ५९.१-५; ६१.१-७; ६२.१-३ [३९९]

४.१.४-२०; २.१-२०; ३.१-१६; ४.१-१५; ५.१-१५; ६.१-११; ७.७-११; ११.१-६; १२.१-६; १३.१-५; १४.१-५; १६.१-२१ १७.१-१४; १६-२१; १८.१-१३; १९.१-११; २०.१-११; २१.१-११; २२.१-११; २३.१-११; २४.१-९; ११; २५.१-८; २६.१-७; २७.१-४; २८.१-५; २९.१-५; ३३.१-११; ३४.१-११; ३५.१-९; ३६.९; ३७.१-४; ३८.१-१०; ३९.१-५; ४०.१; ४१.१-११; ४२.१-१०; ४३.१-७. ४४.१-७; ४५.७; ५०.१-९; ११; ५१.१-११; ५४.६; ५५.१-७; ५६.१-४; ५७.२-३; ८; ५८.१-१० [४०३]

५.१.१-१२; २.१-११; ३.१-१२; ४.१-११; १२.१-६; १५.१-५; १९.५[४]; २७.१-३; २८.१; ३; २९.१-१५; ३०.१-१५; ३१.१-१३; ३२.१-१२; ३३.१-१०; ३४.९; ३६.१; २; ४-६; ३७.१-५; ४०.४; ६-८; ४१.१-१५; १८; १९; ४२.१-१६; १८; ४३.१-१५; १७; ४४.१४; १५; ४५.१-११; ४६.२; ८; ४७.१-७; ४९.१-५; ५४.१४; ५५ १०; ५७.७; ८; ५८.१-८; ५९.८; ६०.१-६; ६२.१-९; ६९.१-४; ७६.१-५; ७७.१-५; ७८ ४; ८०.१-६; ८३.१; ५-८; १०; ८५.१-८; ८६.६[५] [२८४]

६.१.१-१३; ३.१-८; ४.१-८; ५.१-७; ६.१-७; ७.१-५; ८.७; ९.१-७; १०.१-६; ११.१-६; १२.१-६; १३.१-६; १५.१०-१४; १६; १९; १६.४६; १७.१-१४; १८.१-१५; १९.१-१३; २०.१-६; ८-१३; २१.१-१२; २२.१-११; २३.१-१०; २४.१-१०; २५.१-९; २६.१-८; २७.१-८; २८.१; ५-७; २९.१-६; ३०.१-५; ३१.१-३; ५; ३२.१-५; ३३.१-५; ३४.१-५; ३५.१-५; ३६.१-५; ३७.१-५; ३८.१-५; ३९.१-५; ४०.१-५; ४१.१-५; ४४.९-२४; ४७.१-१८; २०-२२; २६; २८-३१; ४८.२१[६]; ४९.१-१४; ५०.१-१५; ५१.१-१३; ५२.१-६; १३; १५-१७; ५८.१; ३; ४; ६०.१-३; १३; ६१.१४; ६२.१-११; ६३.१-१०; ६४.१-६; ६५.१-६; ६६.१-११; ६७.१-११; ६८.१-८; १०; ६९.१-८; ७१.४-६;

---

१. महाबृहती. २. १-२० विराट्स्थानाः. ३. ३ विराड्रूपा. ४. विराड्रूपा. ५ विराट्पूर्वा. ६. यवमध्या महाबृहती.

---

१. मध्येज्योतिः. २. उपरिष्टाज्ज्योतिः. ३. महाबृहती. ४. विराड्रूपा. ५. अभिसारिणी. ६. ३,४ अभिसारिण्यौ. ७. पङ्क्त्युत्तरा. ८. १५ जगती वा.

जगती (४८)

---

१. ३ विराड्रूपा। २. उपरिष्टाज्ज्योतिः। ३. उपरिष्टाज्ज्योती; ४ जगती वा।
४. षड्गुरुशिष्यमते त्रिष्टुप्। ५. महापङ्क्तयः। ६. त्रिष्टुभो वा। ७. महापङ्क्तिः।
८. महापङ्क्तयः।

९; ७१.९; ७५.१–९; ७६.१–८; ७७.५; ७८.२; ५–७; ८३.१; ४–७; ८४.४–७; ८५.१८; २७; ४३; ९१.१–१४; ९२.१–१५; ९४.१–४; ६; ८–१३; ९६.१–११; १००.१–११; १०१.९–११२; १०७.४; ११३.१–९; ११४.४; ११५.१–७; ११७.१–२; १२२.२–४; ६–८; १२४.७; १२५.२; १२८.९; १३०.१; १३२.७[१]; १३३.४–६[२]; १३४.१–६[२]; १३८.१–६; १४२.१; २; १४७.१–४; १६६.५[३]; १६७.१–४; १७०.१–३; १७७.१; [३५१]

अतिजगती (५२)

४.१.२ [१]
५.४१.१६; १७; ८७.१–९ [११]
६.४८.१५ [१]
८.३७.१; ९७.१०; १३ [६]

शक्करी (५६)

४.२७.५ [१]
५.२.१२ [१]
६.२.११; १४.६; १५.३; १५; ३१.४; ४९.१५ [६]
७.५०.४[४] [१]
८.३६.१–६; ४०.२ [७]
९.११५.९; १३३.१–३ [४]

अतिशक्करी (६०)

१.१२९.८; ९; १३७.१–३ [५]
२.२२.२; ३; ४[५]; ४३.२[५] [४]
६.१५.६ [१]

अष्टिः (६४)

१.१२९.११; १३४.६; १३५.७; ८ [४]
२.२२.१ [१]
४.१.१ [१]

अत्यष्टिः (६८)

१.१२७.१–५; ७–११; १२८.१–८; १२९.१–७; १०; १३०.१–९; १३१.१–७; १३२.१–६; १३३.७; १३४.१–५; १३५.१–६; ९; १३६.१–६; १३८.१–४; १३९.१–४; ६–१० [८०]
९.१११.१–३ [३]

धृतिः (७२)

१.१३३.६ [१]
४.१.३ [१]

अतिधृतिः (७६)

१.१२७.६ [१]

द्विपदा (२०)

१.६५.१–५; ६६.१–५; ६७.१–५; ६८.१–५; ६९.१–५; ७०.१–६ [३१]
५.२४.१–४ [४]
६.१०.७; १७.१५[६]; ४७.२५ [३]
७.१७.१–७[७]; ३२.३; ३४.१–२१; ५६.१–११ [४०]
८.१९.२७; २९.१–१०; ४६.१३[८]; ३० [१३]
९.६७.१६–१८[९]; १०७.३; १६; १०९.१–२२ [२७]
१०.१५७.१–५[१०]; १७२.१–४ [९]

एकपदा (१०)

४.१७.१५ [१]
५.४१.२०; ४२.१७; ४३.१६ [३]
६.६३.११[११] [१]
१०.२०.१ [१]

प्रगाथः

(अ) बार्हतः प्रगाथः (३६; ४०)

१.३६.१–२०; ३९.१–१०; ४०.१–८; ४४.१–१४; ४७.१–१०; ४८.१–१६; ८४.१९; २० [८०]
३.१६.१–६ [६]
५.५६.२–३; ६–७[१२] [४]
६.४६.१–१४; ४८.१–४; ९–१० [२०]

---

१. महासतोबृहती. २. महापङ्क्तयः ३. महापङ्क्तिः. ४. अतिजगती वा. ५. अष्टिर्वा. ६. त्रिष्टुप्. ७. द्विपदास्त्रिष्टुभः. ८. चतुर्विंशिका. ९. द्विपदा गायत्र्यः. १०. त्रिष्टुभः ११. एकपदा त्रिष्टुप्. १२. सर्वानुक्रमसूत्रे एतयोः प्रगाथत्वं न निर्दिष्टम्।

७.१६.१–१२; २२.१–२; ४–२७; ५९.१–६; ६६.१०–१५; ७४.१–६; ८१.१–६; ९६.१–२ [६४]

८.१.१–४; ३.१–२०; ४.१–२०; १०.५–६; १७.१४–१५; २२.१–६; २७.१–२२; ४६.२५–२८; [४९.१–१०; ५०.१–१०; ५१.१–१०; ५२.१–१०; ५३.१–८; ५४.१–८]; ६०.१–२०; ६१.१–१८; ६६.१–१४; ७०.१–६; ७१.१०–१५; ७७.१०–११; ८७.१–६; ८८.१–६; ८९.१–४; ९०.१–६; ९९.१–८; १०१.१–२; ५–१२; १०३.६–७ [१८८]

९.१०७.१–२; ४–७; १०–१५; १७–२६ [२२]

१०.२३.२–३; ६२.६–७ [४]

(आ) काकुभः प्रगाथः (२८; ४०)

५.५३.५–६; १५–१६[१] [४]

६.४८.११–१२; १६–१७ [४]

८.१९.१–२६; २८–३३; २०.१–२६; २१.१–१८; २२.९–१०; १३–१८ [८४]

९.१०८.१–१२; १५–१६ [१४]

(इ) महाबार्हतः प्रगाथः (४४;४८)

६.४८.७–८ [२]

---

१. सर्वानुक्रमसूत्रे एतयोः प्रगाथत्वं न निर्दिष्टम्।

|| श्रीः ||

|| सर्वानुक्रमः ||

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठसंख्या
१	१.१.१	१.१.१	अग्निम्	९	मधुच्छन्दा वैश्वामित्रः	अग्निः	गायत्री	३३
२	१.१.२	१.१.३	वायो	९	,, ,,	१–३ वायुः ४–६ इन्द्रवायू ७–९ मित्रावरुणौ	,,	३९
३	१.१.३	१.१.५	अश्विना	१२	,, ,,	१–३ अश्विनौ ४–६ इन्द्रः ७–९ विश्वे देवाः १०–१२ सरस्वती	,,	४८
४	१.२.१	१.१.७	सुरूपकृत्नुम्	१०	,, ,,	इन्द्रः	,,	५७
५	१.२.२	१.१.९	आ तु	१०	,, ,,	,,	,,	६३
६	१.२.३	१.१.११	युञ्जन्ति	१०	,, ,,	१–३; १० इन्द्रः ४;६;८;९ मरुतः ५;७ मरुत इन्द्रश्च	,,	६९
७	१.२.४	१.१.१३	इन्द्रमित्	१०	,, ,,	इन्द्रः	,,	७७
८	१.३.१	१.१.१५	एन्द्र सानसिं	१०	,, ,,	,,	,,	८४
९	१.३.२	१.१.१७	इन्द्रेहि	१०	,, ,,	,,	,,	९१
१०	१.३.३	१.१.१९	गायन्ति	१२	,, ,,	,,	अनुष्टुप्	९६
११	१.३.४	१.१.२१	इन्द्रम्	८	जेता माधुच्छन्दसः	,,	,,	१०६

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
१२	१.४.१	१.१.२२	अग्निं	१२	मेधातिथिः काण्वः	अग्निः ६[१] अग्निर्निर्मथ्योऽग्निराहवनीयश्च	गायत्री	११२
१३	१.४.२	१.१.२४	सुसमिद्धः	१२	,, ,,	१ इध्मः समिद्धो वाग्निः २ तनूनपात्; ३ नराशंसः; ४ इळः; ५ बर्हिः; ६ देवीर्द्वारः; ७ उषासानक्ता; ८ दैव्यौ होतारौ प्रचेतसौ; ९ तिस्रो देव्यः सरस्वतीळाभारत्यः; १० त्वष्टा; ११ वनस्पतिः; १२ स्वाहाकृतयः (आप्रीसूक्तम्)	,,	११८
१४	१.४.३	१.१.२६	ऐभिः	१२	,, ,,	विश्वे देवाः	,,	१२५
१५	१.४.४	१.१.२८	इन्द्र सोमं	१२	,, ,,	ऋतवः १इन्द्रः; २मरुतः; ३त्वष्टा; ४ अग्निः; ५ इन्द्रः; ६ मित्रावरुणौ; ७–१० द्रविणोदाः; ११ अश्विनौ; १२ अग्निः	,,	१३१
१६	१.४.५	१.१.३०	आ त्वा	९	,, ,,	इन्द्रः	,,	१३७
१७	१.४.६	१.१.३२	इन्द्रावरुणयोः	९	,, ,,	इन्द्रावरुणौ	१–३; ६–९ गायत्री ४; ५ पादनिचृत्	१४१

१८	१.५.१	१.१.३४	सोमानं	९	मेधातिथिः	काण्वः	१–३ ब्रह्मणस्पतिः ४ ब्रह्मणस्पतिरिन्द्रः सोमश्च । ५ ब्रह्मणस्पतिर्दक्षिणा च । ६–८ सदसस्पतिः । ९ सदसस्पतिर्नराशंसो वा	गायत्री	१४६
१९	१.५.२	१.१.३६	प्रति त्यं	९	,,	,,	अग्निर्मरुतश्च	,,	१५१
२०	१.५.३	१.२.१	अयं	८	,,	,,	ऋभवः	,,	१५६
२१	१.५.४	१.२.३	इह	६	,,	,,	इन्द्राग्नी	,,	१६०
२२	१.५.५	१.२.४	प्रातर्युजा	२१	,,	,,	१–४ अश्विनौ; ५–८ सविता; ९–१० अग्निः; ११ देव्यः; १२ इन्द्राणी-वरुणान्यग्नाय्यः; १३–१४ द्यावापृथिव्यौ; १५पृथिवी; १६ विष्णुर्देवा वा; १७–२१ विष्णुः	,,	१६२
२३	१.५.६	१.२.८	तीव्राः	२४	,,	,,	१ वायुः; २–३ इन्द्रवायू; ४–६ मित्रावरुणौ; ७–९ इन्द्रो मरुत्वान्; १०–१२ विश्वे देवाः; १३–१५पूषा; १६–२३[१–२] आपः; २३[३–४]–२४ अग्निः	१–१८ गायत्री; १९पुर-उष्णिक्; २० अनुष्टुप् २१ प्रतिष्ठा; २२–२४ अनुष्टुप्	१७१
२४	१.६.१	१.२.१३	कस्य	१५	शुनःशेप आजीगर्तिः (कृत्रिमो वैश्वामित्रः देवरातः)		१ कः; २ अग्निः; ३–४ सविता; ५ सविता भगो वा; ६–१५ वरुणः	१; २; ६–१५ त्रिष्टुप् ३–५ गायत्री	१८२
२५	१.६.२	१.२.१६	यच्चिद्धि	२१	,,	,,	वरुणः	गायत्री	१९१
२६	१.६.३	१.२.२०	वसिष्वा	१०	,,	,,	अग्निः	,,	१९८

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
२७	१.६.४	१.२.२२	अश्वं	१३	शुनःशेप आजीगर्तिः (कृत्रिमो वैश्वामित्रः देवरातः)	१–१२ अग्निः; १३ देवाः	१–१२गायत्री; १३त्रिष्टुप्	२०२
२८	१.६.५	१.२.२५	यत्र ग्रावा	९	” ”	१–४ इन्द्रः; ५–६ उलूखलम्; ७–८ उलूखलमुसले; ९ प्रजापतिर्हरिश्चन्द्रोऽधिषवणचर्म वा	१–६अनुष्टुप्; ७–९जगती	२०६
२९	१.६.६	१.२.२७	यच्चित्	७	शुनःशेप आजीगर्तिः	इन्द्रः	पङ्क्तिः	२१०
३०	१.६.७	१.२.२८	आ वः	२२	” ”	१–१६ इन्द्रः; १७–१९ अश्विनौ; २०–२२ उषाः	१–१०; १२–१५; १७–२२गायत्री; ११पादनिचृद्गायत्री; १६ त्रिष्टुप्	२१४
३१	१.७.१	१.२.३२	त्वमग्ने	१८	हिरण्यस्तूप आङ्गिरसः	अग्निः	१–७; ९–१५;१७ जगती; ८; १६; १८ त्रिष्टुप्	२२२
३२	१.७.२	१.२.३६	इन्द्रस्य नु	१५	” ”	इन्द्रः	त्रिष्टुप्	२३३
३३	१.७.३	१.३.१	एत	१५	” ”	”	”	२४३
३४	१.७.४	१.३.४	त्रिश्चित्	१२	” ”	अश्विनौ	१–८; १०; ११ जगती; ९; १२ त्रिष्टुप्	२५३
३५	१.७.५	१.३.५	ह्वयामि	११	” ”	१ अग्निर्मित्रावरुणौ रात्री सविता; २–११ सविता	१; ९ जगती; २–८;१०; ११ त्रिष्टुप्	२६०
३६	१.८.१	१.३.८	प्र वः	२०	कण्वो घौरः	१–१२; १५–२० अग्निः; १३; १४ यूपः	प्रागाथं बार्हतम्	२६७
३७	१.८.२	१.३.१२	क्रीळं	१५	” ”	मरुतः	गायत्री	२७८
३८	१.८.३	१.३.१५	कद्ध	१५	” ”	”	”	२८३
३९	१.८.४	१.३.१८	प्र यत्	१०	” ”	”	प्रागाथं बार्हतम्	२८९

४०	१.८.५	१.३.२०	उत्तिष्ठ	८	,, ,,	ब्रह्मणस्पतिः	प्रगाथं बार्हतम्	२९४
४१	१.८.६	१.३.२२	यं रक्षन्ति	९	,, ,,	१–३; ७–९ वरुणमित्रा-र्यमणः; ४–६ आदित्याः	गायत्री	२९९
४२	१.८.७	१.३.२४	सं पूषन्	१०	,, ,,	पूषा	,,	३०२
४३	१.८.८	१.३.२६	कद्रुद्राय	९	,, ,,	१; २; ४–६ रुद्रः; ३ मित्रावरुणौ रुद्रश्च; ७–९ सोमः	१–८ गायत्री ९ अनुष्टुप्	३०६
४४	१.९.१	१.३.२८	अग्ने	१४	प्रस्कण्वः काण्वः	१; २ अग्निरश्विनावुषाश्च ३–१४ अग्निः	प्रगाथं बार्हतम्	३१०
४५	१.९.२	१.३.३१	त्वमग्ने	१०	,, ,,	१–१०[1]अग्निः; १०[2]देवाः	अनुष्टुप्	३१७
४६	१.९.३	१.३.३३	एषो	१५	,, ,,	अश्विनौ	गायत्री	३२१
४७	१.९.४	१.४.१	अयं	१०	,, ,,	,,	प्रागाथं बार्हतम्	३२८
४८	१.९.५	१.४.३	सह	१६	,, ,,	उषाः	,, ,,	३३३
४९	१.९.६	१.४.६	उषः	४	,, ,,	,,	अनुष्टुप्	३४२
५०	१.९.७	१.४.७	उदु त्यं	१३	,, ,,	सूर्यः	१–९ गायत्री १०–१३ अनुष्टुप्	३४५
५१	१.१०.१	१.४.९	अभि त्यं	१५	सव्य आङ्गिरसः	इन्द्रः	१–१३ जगती १४–१५ त्रिष्टुप्	३५२
५२	१.१०.२	१.४.१२	त्यं सु	१५	,, ,,	,,	१–१२; १४ जगती १३; १५ त्रिष्टुप्	३६३
५३	१.१०.३	१.४.१५	न्यू३षु	११	,, ,,	,,	१–९ जगती १०–११ त्रिष्टुप्	३७३
५४	१.१०.४	१.४.१७	मा नो	११	,, ,,	,,	१–५; ७; १० जगती ६; ८; ९; ११ त्रिष्टुप्	३७९
५५	१.१०.५	१.४.१९	दिवश्चित्	८	,, ,,	,,	जगती	३८६
५६	१.१०.६	१.४.२१	एष प्र	६	,, ,,	,,	,,	३९१
५७	१.१०.७	१.४.२२	प्र मंहिष्ठाय	६	,, ,,	,,	,,	३९५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
५८	१.११.१	१.४.२३	नू चित्	९	नोधा गौतमः	अग्निः	१–५ जगती ६–९ त्रिष्टुप्	३९९
५९	१.११.२	१.४.२५	वया इत्	७	,, ,,	अग्निर्वैश्वानरः	त्रिष्टुप्	४०४
६०	१.११.३	१.४.२६	वह्निः	५	,, ,,	अग्निः	,,	४०८
६१	१.११.४	१.४.२७	अस्मा इदु	१६	,, ,,	इन्द्रः	,,	४११
६२	१.११.५	१.५.१	प्र मन्महे	१३	,, ,,	,,	,,	४२२
६३	१.११.६	१.५.४	त्वं महाँ	९	,, ,,	,,	,,	४३१
६४	१.११.७	१.५.६	वृष्णे शर्धाय	१५	,, ,,	मरुतः	१–१४ जगती १५ त्रिष्टुप्	४३६
६५	१.१२.१	१.५.९	पश्वा	१०(५)	पराशरः शाक्त्यः	अग्निः	द्विपदा विराट्	४४५
६६	१.१२.२	१.५.१०	रयिं	१०(५)	,, ,,	,,	,, ,,	४४९
६७	१.१२.३	१.५.११	वनेषु	१०(५)	,, ,,	,,	,, ,,	४५२
६८	१.१२.४	१.५.१२	श्रीणन्	१०(५)	,, ,,	,,	,, ,,	४५५
६९	१.१२.५	१.५.१३	शुक्रः	१०(५)	,, ,,	,,	,, ,,	४५७
७०	१.१२.६	१.५.१४	वनेम	११(६)	,, ,,	,,	,, ,,	४६०
७१	१.१२.७	१.५.१५	उप प्र	१०	,, ,,	,,	त्रिष्टुप्	४६३
७२	१.१२.८	१.५.१७	नि काव्या	१०	,, ,,	,,	,,	४६९
७३	१.१२.९	१.५.१९	रयिर्न	१०	,, ,,	,,	,,	४७५
७४	१.१३.१	१.५.२१	उपप्रयन्तः	९	गोतमो राहूगणः	,,	गायत्री	४८१
७५	१.१३.२	१.५.२३	जुषस्व	५	,, ,,	,,	,,	४८४
७६	१.१३.३	१.५.२४	का ते	५	,, ,,	,,	त्रिष्टुप्	४८५
७७	१.१३.४	१.५.२५	कथा	५	,, ,,	,,	,,	४८८
७८	१.१३.५	१.५.२६	अभि त्वा	५	,, ,,	,,	गायत्री	४९१

७९	१.१३.६	१.५.२७	हिरण्यकेशः	१२	,,	,,	१–३ अग्निरग्निर्मध्यमो वा ४–१२ अग्निः	१–३ त्रिष्टुप्; ४–६ उष्णिक्; ७–१२ गायत्री	४९२
८०	१.१३.७	१.५.२९	इत्था	१६	,,	,,	इन्द्रः	पङ्क्तिः	४९७
८१	१.१३.८	१.६.१	इन्द्रो मदाय	९	,,	,,	,,	,,	५०५
८२	१.१३.९	१.६.३	उपो षु	६	,,	,,	,,	१–५ पङ्क्तिः; ६ जगती	५१०
८३	१.१३.१०	१.६.४	अश्वावति	६	,,	,,	,,	जगती	५१३
८४	१.१३.११	१.६.५	असावि	२०	,,	,,	,,	१–६ अनुष्टुप्; ७–९ उष्णिक्; १०–१२ पङ्क्तिः; १३–१५ गायत्री; १६–१८ त्रिष्टुप्; १९ बृहती; २० सतोबृहती	५१७
८५	१.१४.१	१.६.९	प्र ये	१२	,,	,,	मरुतः	१–४; ६–११ जगती; ५; १२ त्रिष्टुप्	५२८
८६	१.१४.२	१.६.११	मरुतो यस्य	१०	,,	,,	,,	गायत्री	५३४
८७	१.१४.३	१.६.१३	प्रत्वक्षसः	६	,,	,,	,,	जगती	५३८
८८	१.१४.४	१.६.१४	आ विद्युन्मद्भिः	६	,,	,,	,,	१;६ प्रस्तारपङ्क्तिः २–४ त्रिष्टुप्; ५ विराड्रूपा	५४२
८९	१.१४.५	१.६.१५	आ नो भद्राः	१०	,,	,,	विश्वे देवाः	१–५; ७जगती; ६विराट्स्थाना; ८–१० त्रिष्टुप्	५४६
९०	१.१४.६	१.६.१७	ऋजुनीती	९	,,	,,	,, ,,	१–८ गायत्री; ९ अनुष्टुप्	५५२
९१	१.१४.७	१.६.१९	त्वं सोम	२३	,,	,,	सोमः	१–४; १८–२३ त्रिष्टुप्; ५–१६ गायत्री; १७ उष्णिक्	५५५
९२	१.१४.८	१.६.२४	एता उ त्याः	१८	,,	,,	१–१५ उषाः; १६–१८ अश्विनौ	१–४ जगती; ५–१२ त्रिष्टुप्; १३–१८ उष्णिक्	५६७
९३	१.१४.९	१.६.२८	अग्नीषोमौ	१२	,,	,,	अग्नीषोमौ	१–३ अनुष्टुप्; ४–७; १२ त्रिष्टुप्; ८ जगती त्रिष्टुब्वा; ९–११ गायत्री	५७६

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
९४	१.१५.१	१.६.३०	इमं	१६	कुत्स आङ्गिरसः	१–७; ८४; ९–१६१-२ अग्निः; ८१-२ देवाः १६३-४ मित्रो वरुणोऽदितिः सिन्धुः पृथिवी द्यौश्च अथवाग्निः	१–१४ जगती; १५; १६ त्रिष्टुप्	५८२
९५	१.१५.२	१.७.१	द्वे विरूपे	११	,, ,,	अग्निरग्निरौषसो वा	त्रिष्टुप्	५९२
९६	१.१५.३	१.७.३	स प्रत्नथा	९	,, ,,	अग्निरग्निर्द्रविणोदा वा	,,	५९९
९७	१.१५.४	१.७.५	अप नः	८	,, ,,	अग्निरग्निः शुचिर्वा	गायत्री	६०४
९८	१.१५.५	१.७.६	वैश्वानरस्य	३	,, ,,	अग्निरग्निर्वैश्वानरो वा	त्रिष्टुप्	६०७
९९	१.१५.६	१.७.७	जातवेदसे	१	कश्यपो मारीचः	अग्निरग्निर्जातवेदा वा	,,	६०८
१००	१.१५.७	१.७.८	स यो वृषा	१९	ऋज्राश्वाम्बरीषसहदेवभयमानसुराधसो वार्षागिराः	इन्द्रः	,,	६०९
१०१	१.१५.८	१.७.१२	प्र मन्दिने	११	कुत्स आङ्गिरसः	,,	१–७ जगती; ८–११ त्रिष्टुप्	६१९
१०२	१.१५.९	१.७.१४	इमां ते	११	,, ,,	,,	१–१० जगती; ११त्रिष्टुप्	६२४
१०३	१.१५.१०	१.७.१६	तत्ते	८	,, ,,	,,	त्रिष्टुप्	६३०
१०४	१.१५.११	१.७.१८	योनिः	९	,, ,,	,,	,,	६३४
१०५	१.१५.१२	१.७.२०	चन्द्रमाः	१९	,, ,, आप्त्यस्त्रितो वा	विश्वे देवाः	१–७; ९–१८ पङ्क्तिः; ८ महाबृहती यवमध्या; १९ त्रिष्टुप्	६३९
१०६	१.१६.१	१.७.२४	इन्द्रं मित्रं	७	कुत्स आङ्गिरसः	,, ,,	१–६ जगती; ७ त्रिष्टुप्	६५०
१०७	१.१६.२	१.७.२५	यज्ञो देवानां	३	,, ,,	,, ,,	त्रिष्टुप्	६५३
१०८	१.१६.३	१.७.२६	य इन्द्राग्नी	१३	,, ,,	इन्द्राग्नी	,,	६५५

१०९	१.१६.४	१.७.२८	वि हि	८	,,	,,	,,	त्रिष्टुप्	६६०
११०	१.१६.५	१.७.३०	ततं मे	९	,,	,,	ऋभवः	१–४; ६–८ जगती; ५; ९ त्रिष्टुप्	६६५
१११	१.१६.६	१.७.३२	तक्षन्	५	,,	,,	,,	१–४ जगती; ५ त्रिष्टुप्	६७१
११२	१.१६.७	१.७.३३	ईळे	२५	,,	,,	$१^{१}$ द्यावापृथिव्यौ; $१^{२}$ अग्निः; $१^{३-४}$–२५ अश्विनौ	१–२३ जगती; २४; २५ त्रिष्टुप्	६७४
११३	१.१६.८	१.८.१	इदं	२०	,,	,,	$१^{१-२}$; २–२० उषाः; $१^{३-४}$ उषा रात्री च	त्रिष्टुप्	६८९
११४	१.१६.९	१.८.५	इमा रुद्राय	११	,,	,,	रुद्रः	१–९ जगती; १०; ११ त्रिष्टुप्	७०१
११५	१.१६.१०	१.८.७	चित्रं	६	,,	,,	सूर्यः	त्रिष्टुप्	७०८
११६	१.१७.१	१.८.८	नासत्याभ्यां	२५	कक्षीवान् औशिजः	दैर्घतमस	अश्विनौ	,,	७१२
११७	१.१७.२	१.८.१३	मध्वः	२५	,,	,,	,,	,,	७२७
११८	१.१७.३	१.८.१७	आ वां रथः	११	,,	,,	,,	,,	७४०
११९	१.१७.४	१.८.२०	आ वां रथं	१०	,,	,,	,,	जगती	७४६
१२०	१.१७.५	१.८.२२	का राधत्	१२	,,	,,	१–११ अश्विनौ; १२ दुःस्वप्ननाशनम्	१ गायत्री २ ककुप्; ३काविराट्; ४ नष्टरूपी; ५ तनुशिरा; ६ (अक्षरैः) उष्णिक्; ७ विष्टारबृहती; ८ कृतिः; ९ विराट्; १०–१२गायत्री	७५१
१२१	१.१८.१	१.८.२४	कदित्था	१५	,,	,,	इन्द्रो विश्वे देवा वा	त्रिष्टुप्	७५७
१२२	१.१८.२	२.१.१	प्र वः पान्तं	१५	,,	,,	विश्वे देवाः	,,	७६९
१२३	१.१८.३	२.१.४	पृथू रथः	१३	,,	,,	उषाः	,,	७७७
१२४	१.१८.४	२.१.७	उषा उच्छन्ती	१३	,,	,,	,,	,,	७८५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
१२५	१.१८.५	२.१.१०	प्राता रत्नं	७	कक्षीवान् दैर्घतमस औशिजः	स्वनयस्य दानस्तुतिः	१–३; ६; ७त्रिष्टुप्; ४–५ जगती	७९३
१२६	१.१८.६	२.१.११	अमन्दान्	७	१–५ कक्षीवान् दैर्घतमस औशिजः; ६ भावयव्यः; ७ रोमशा	१–५; ७ भावयव्यः; ६ रोमशा	१–५ त्रिष्टुप्; ६; ७ अनुष्टुप्	७९७
१२७	१.१९.१	२.१.१२	अग्निं होतारं	११	परुच्छेपो दैवोदासिः	अग्निः	१–५; ७–११ अत्यष्टिः; ६ अतिधृतिः	८०१
१२८	१.१९.२	२.१.१४	अयं जायत	८	,, ,,	,,	अत्यष्टिः	८१०
१२९	१.१९.३	२.१.१६	यं त्वं	११	,, ,,	१–५; ७–११ इन्द्रः; ६ इन्दुः	१–७; १० अत्यष्टिः; ८; ९ अतिशक्करी; ११ अष्टिः	८१५
१३०	१.१९.४	२.१.१८	एन्द्र याहि	१०	,, ,,	इन्द्रः	१–९ अत्यष्टिः; १० त्रिष्टुप्	८२३
१३१	१.१९.५	२.१.२०	इन्द्राय	७	,, ,,	,,	अत्यष्टिः	८३१
१३२	१.१९.६	२.१.२१	त्वया	६	,, ,,	१–५; ६² इन्द्रः; ६¹ इन्द्रापर्वतौ	अत्यष्टिः	८३६
१३३	१.१९.७	२.१.२२	उभे पुनामि	७	,, ,,	इन्द्रः	१ त्रिष्टुप्; २–४ अनुष्टुप् ५ गायत्री; ६ धृतिः; ७ अत्यष्टिः	८४१
१३४	१.२०.१	२.१.२३	आ त्वा	६	,, ,,	वायुः	१–५ अत्यष्टिः; ६ अष्टिः	८४६
१३५	१.२०.२	२.१.२४	स्तीर्णं	९	,, ,,	१–३; ९ वायुः; ४–८ इन्द्रवायू	१–६; ९ अत्यष्टिः; ७; ८ अष्टिः	८५०
१३६	१.२०.३	२.१.२६	प्र सु ज्येष्ठं	७	,, ,,	१–५ मित्रावरुणौ; ६; ७ लिङ्गोक्तदेवताः	१–६ अत्यष्टिः; ७ त्रिष्टुप्	८५६

१३७	१.२०.४	२.२.१	सुषुमा यातं	३	„ „	मित्रावरुणौ	अतिशक्करी	८६२
१३८	१.२०.५	२.२.२	प्र प्र पूष्णः	४	„ „	पूषा	अत्यष्टिः	८६४
१३९	१.२०.६	२.२.३	अस्तु श्रौषट्	११	„ „	१ विश्वे देवाः; २ मित्रावरुणौ; ३–५ अश्विनौ; ६ इन्द्रः; ७ अग्निः; ८मरुतः; ९ इन्द्राग्नी; १० बृहस्पतिः; ११ विश्वे देवाः	१–४; ६–१० अत्यष्टिः; ५ बृहती; ११ त्रिष्टुप्	८६७
१४०	१.२१.१	२.२.५	वेदिषदे	१३	दीर्घतमा औचथ्यः	अग्निः	१–९; ११ जगती; १० त्रिष्टुप् जगती वा; १२; १३ त्रिष्टुप्	८७५
१४१	१.२१.२	२.२.८	बळित्था	१३	„ „	„	१–११ जगती; १२; १३ त्रिष्टुप्	८८२
१४२	१.२१.३	२.२.१०	समिद्धो अग्न आ	१३	„ „	आप्रीसूक्तम् १ समित्; २ तनूनपात्; ३ नराशंसः; ४ इळः; ५ बर्हिः; ६ देवीर्द्वारः; ७ उषासानक्ता; ८ दैव्यौ होतारौ प्रचेतसौ; ९ तिस्रो देव्यः सरस्वतीळाभारत्यः; १० त्वष्टा; ११ वनस्पतिः; १२ स्वाहाकृतयः; १३ इन्द्रः	अनुष्टुप्	८८९
१४३	१.२१.४	२.२.१२	प्र तव्यसीं	८	„ „	अग्निः	१–७ जगती; ८ त्रिष्टुप्	८९५
१४४	१.२१.५	२.२.१३	एति प्र	७	„ „	„	जगती	८९९
१४५	१.२१.६	२.२.१४	तं पृच्छता	५	„ „	„	१–४ जगती; ५ त्रिष्टुप्	९०३
१४६	१.२१.७	२.२.१५	त्रिमूर्धानं	५	„ „	„	त्रिष्टुप्	९०५
१४७	१.२१.८	२.२.१६	कथा ते	५	„ „	„	„	९०८

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठसंख्या
१४८	१.२१.९	२.२.१७	मथीद्यत्	५	दीर्घतमा औचथ्यः	अग्निः	त्रिष्टुप्	९११
१४९	१.२१.१०	२.२.१८	महः सः	५	,, ,,	,,	विराट्	९१४
१५०	१.२१.११	२.२.१९	पुरु त्वा	३	,, ,,	,,	उष्णिक्	९१६
१५१	१.२१.१२	२.२.२०	मित्रं न यं	९	,, ,,	१ मित्रः; २–९ मित्रावरुणौ	जगती	९१८
१५२	१.२१.१३	२.२.२२	युवं वस्त्राणि	७	,, ,,	मित्रावरुणौ	त्रिष्टुप्	९२३
१५३	१.२१.१४	२.२.२३	यजामहे वां	४	,, ,,	,,	,,	९२७
१५४	१.२१.१५	२.२.२४	विष्णोर्नु कं	६	,, ,,	विष्णुः	,,	९२९
१५५	१.२१.१६	२.२.२५	प्र वः पान्तम्	६	,, ,,	१–३ विष्णुरिन्द्रश्च; ४–६ विष्णुः	जगती	९३३
१५६	१.२१.१७	२.२.२६	भवा मित्रः	५	,, ,,	विष्णुः	,,	९३६
१५७	१.२२.१	२.२.२७	अबोध्यग्निः	६	,, ,,	अश्विनौ	१–४ जगती; ५; ६ त्रिष्टुप्	९३९
१५८	१.२२.२	२.३.१	वसू रुद्रा	६	,, ,,	,,	१–५ त्रिष्टुप्; ६ अनुष्टुप्	९४३
१५९	१.२२.३	२.३.२	प्र द्यावा	५	,, ,,	द्यावापृथिवी	जगती	९४६
१६०	१.२२.४	२.३.३	ते हि	५	,, ,,	,,	,,	९४९
१६१	१.२२.५	२.३.४	किमु श्रेष्ठः	१४	,, ,,	ऋभवः	१–१३ जगती; १४ त्रिष्टुप्	९५२
१६२	१.२२.६	२.३.७	मा नो मित्रः	२२	,, ,,	अश्वस्तुतिः	१; २; ४; ५; ७–२२ त्रिष्टुप्; ३; ६ जगती	९६०
१६३	१.२२.७	२.३.११	यदक्रन्दः	१३	,, ,,	,,	त्रिष्टुप्	९७०
१६४	१.२२.८	२.३.१४	अस्य वामस्य	५२	,, ,,	१–४१ विश्वे देवाः; ४२^{1} वाक्; ४२^{2} आपः; ४३^{1}	१–११ त्रिष्टुप्; १२ जगती; १३; १४ त्रिष्टुप्;	९७७

						शकधूमः; ४३² सोमः; ४४ अग्निसूर्यवायवः; ४५ वाक्; ४६; ४७ सूर्यः ४८ संवत्सरसंस्थं कालचक्रवर्णनम्; ४९ सरस्वती; ५० साध्याः; ५१ सूर्यः पर्जन्याग्नी वा; ५२ सरस्वान् सूर्यो वा	१५ जगती; १६–२२ त्रिष्टुप्; २३ जगती; २४–२८ त्रिष्टुप्; २९ जगती; ३०–३५ त्रिष्टुप्; ३६ जगती; ३७–४० त्रिष्टुप्; ४१ जगती; ४२ प्रस्तारपङ्क्तिः; ४३–५० त्रिष्टुप्; ५१ अनुष्टुप्; ५२ त्रिष्टुप्	
१६५	१.२३.१	२.३.२४	कया शुभा	१५	१; २ इन्द्रः; ३ मरुतः; ४ इन्द्रः; ५ मरुतः; ६ इन्द्रः; ७ मरुतः; ८इन्द्रः; ९ मरुतः; १०–१२ इन्द्रः; १३–१५ अगस्त्यः	मरुत्वानिन्द्रः	त्रिष्टुप्	१०१५
१६६	१.२३.२	२.४.१	तन्नु	१५	अगस्त्यः	मरुतः	१–१३ जगती; १४; १५ त्रिष्टुप्	१०२२
१६७	१.२३.३	२.४.४	सहस्रं ते	११	,,	१ इन्द्रः; २–११ मरुतः	त्रिष्टुप्	१०२८
१६८	१.२३.४	२.४.६	यज्ञायज्ञा	१०	,,	मरुतः	१–७ जगती; ८–१० त्रिष्टुप्	१०३२
१६९	१.२३.५	२.४.८	महश्चित्त्वं	८	,,	इन्द्रः	१; ३–८ त्रिष्टुप्; २ चतुष्पदा विराट्	१०३७
१७०	१.२३.६	२.४.१०	न नूनमस्ति	५	१; ३; ४ इन्द्रः; २; ५ अगस्त्यः	,,	१ बृहती; २–४ अनुष्टुप् ५ त्रिष्टुप्	१०४०
१७१	१.२३.७	२.४.११	प्रति वः	६	अगस्त्यः	१; २ मरुतः; ३–६ मरुत्वानिन्द्रः	त्रिष्टुप्	१०४२
१७२	१.२३.८	२.४.१२	चित्रो वः	३	,,	मरुतः	गायत्री	१०४५
१७३	१.२३.९	२.४.१३	गायत्साम	१३	,,	इन्द्रः	त्रिष्टुप्	१०४६

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	प्रथमभागे पृष्ठ-संख्या
१७४	१.२३.१०	२.४.१६	त्वं राजा	१०	अगस्त्यः	इन्द्रः	त्रिष्टुप्	१०५१
१७५	१.२३.११	२.४.१८	मत्स्यपायि	६	,,	,,	१ स्कन्धोग्रीवी बृहती; २–५ अनुष्टुप्; ६ त्रिष्टुप्	१०५६
१७६	१.२३.१२	२.४.१९	मत्सि नः	६	,,	,,	१–५ अनुष्टुप्; ६ त्रिष्टुप्	१०५८
१७७	१.२३.१३	२.४.२०	आ चर्षणिप्राः	५	,,	,,	त्रिष्टुप्	१०६१
१७८	१.२३.१४	२.४.२१	यद्ध स्या	५	,,	,,	,,	१०६३
१७९	१.२३.१५	२.४.२२	पूर्वीरहं	६	१; २ लोपामुद्रा; ३; ४ अगस्त्यः; ५; ६ अन्तेवासी ब्रह्मचारी	रतिः	१–४; ६ त्रिष्टुप्; ५ बृहती	१०६५
१८०	१.२४.१	२.४.२३	युवो रजांसि	१०	अगस्त्यः	अश्विनौ	त्रिष्टुप्	१०६८
१८१	१.२४.२	२.४.२५	कदु प्रेष्ठौ	९	,,	,,	,,	१०७२
१८२	१.२४.३	२.४.२७	अभूदिदं	८	,,	,,	१–५; ७ जगती; ६; ८ त्रिष्टुप्	१०७६
१८३	१.२४.४	२.४.२९	तं युञ्जाथां	६	,,	,,	त्रिष्टुप्	१०७९
१८४	१.२४.५	२.५.१	ता वामद्य	६	,,	,,	,,	१०८३
१८५	१.२४.६	२.५.२	कतरा पूर्वा	११	,,	द्यावापृथिवी	,,	१०८५
१८६	१.२४.७	२.५.४	आ नः	११	,,	विश्वे देवाः	,,	१०९०
१८७	१.२४.८	२.५.६	पितुं नु	११	,,	अन्नस्तुतिः	१ अनुष्टुब्गर्भोष्णिक्; २; ४; ८–१० गायत्री; ३; ५–७ अनुष्टुप्; ११ अनुष्टुब्बृहती वा	१०९५
१८८	१.२४.९	२.५.८	समिद्धो अद्य	११	,,	आप्रियः	गायत्री	१०९८
१८९	१.२४.१०	२.५.१०	अग्ने नय	८	,,	अग्निः	त्रिष्टुप्	११०१

१९०	१.२४.११	२.५.१२	अनर्वाणं वृषभं	८	,,	बृहस्पतिः	,,	११०५
१९१	१.२४.१२	२.५.१४	कङ्कतो न	१६	विषशङ्कावानगस्त्यः	अप्तृणसूर्याः	१-९; १४-१६ अनुष्टुप्; १०-१२ महापङ्क्तिः; १३ महाबृहती	११०९ द्वि०-भागे
१(१९२)	२.१.१	२.५.१७	त्वमग्ने द्युभिः	१६	गृत्समद आङ्गिरसः शौन-होत्रः पश्चाद्भार्गवः शौनकः	अग्निः	जगती	१
२(१९३)	२.१.२	२.५.२०	यज्ञेन वर्धत	१६ (३)	गृत्समदः	,,	,,	८
३(१९४)	२.१.३	२.५.२२	समिद्धो अग्निः	११	,,	आप्रियः	१-६; ८-११ त्रिष्टुप्; ७ जगती	१४
४(१९५)	२.१.४	२.५.२४	हुवे वः	९	सोमाहुतिर्भार्गवः	अग्निः	त्रिष्टुप्	१८
५(१९६)	२.१.५	२.५.२६	होताजनिष्ट	८	,,	,,	अनुष्टुप्	२२
६(१९७)	२.१.६	२.५.२७	इमां मे	८	,,	,,	गायत्री	२५
७(१९८)	२.१.७	२.५.२८	श्रेष्ठं यविष्ठ	६	,,	,,	,,	२७
८(१९९)	२.१.८	२.५.२९	वाजयन्निव	६	गृत्समदः	,,	१-५ गायत्री; ६ अनुष्टुप्	२९
९(२००)	२.१.९	२.६.१	नि होता	६	,,	,,	त्रिष्टुप्	३१
१०(२०१)	२.१.१०	२.६.२	जोहूत्रो अग्निः	६	,,	,,	,,	३३
११(२०२)	२.१.११	२.६.३	श्रुधी हवं	२१	,,	इन्द्रः	१-२० विराट्स्थाना त्रिष्टुप्; २१ त्रिष्टुप्	३६
१२(२०३)	२.२.१	२.६.७	यो जात एव	१५	,,	,,	त्रिष्टुप्	४५
१३(२०४)	२.२.२	२.६.१०	ऋतुर्जनित्री	१३	,,	,,	१-१२ जगती; १३ त्रिष्टुप्	५१
१४(२०५)	२.२.३	२.६.१३	अध्वर्यवो भरतेन्द्राय	१२	,,	,,	त्रिष्टुप्	५७
१५(२०६)	२.२.४	२.६.१५	प्र घा न्वस्य	१०	,,	,,	,,	६१
१६(२०७)	२.२.५	२.६.१७	प्र वः सतां	९	,,	,,	१-८ जगती; ९ त्रिष्टुप्	६५
१७(२०८)	२.२.६	२.६.१९	तदस्मै	९	,,	,,	१-७ जगती; ८; ९ त्रिष्टुप्	६९
१८(२०९)	२.२.७	२.६.२१	प्राता रथः	९	,,	,,	,,	७३

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	द्वि॰ भागे पृष्ठसंख्या
१९(२१०)	२.२.८	२.६.२३	अपाय्यस्य	९	गृत्समदः	इन्द्रः	त्रिष्टुप्	७६
२०(२११)	२.२.९	२.६.२५	वयं ते वयः	९	,,	,,	,,	८०
२१(२१२)	२.२.१०	२.६.२७	विश्वजिते	६	,,	,,	१–५ जगती; ६ त्रिष्टुप्	८३
२२(२१३)	२.२.११	२.६.२८	त्रिकद्रुकेषु	४	,,	,,	१ अष्टिः; २; ३ अतिशक्वरी; ४ अतिशक्वरी अष्टिर्वा	८६
२३(२१४)	२.३.१	२.६.२९	गणानां	१९	,,	१ ब्रह्मणस्पतिः; २–४ बृहस्पतिः; ५ ब्रह्मणस्पतिः; ६–८ बृहस्पतिः; ९ ब्रह्मणस्पतिः; १० बृहस्पतिः; ११ ब्रह्मणस्पतिः; १२–१६ बृहस्पतिः; १७ ब्रह्मणस्पतिः; १८ बृहस्पतिः; १९ ब्रह्मणस्पतिः	१–१४;१६–१८ जगती; १५; १९ त्रिष्टुप्	८८
२४(२१५)	२.३.२	२.७.१	सेमाम्	१६	,,	१–११ ब्रह्मणस्पतिः; १२ ब्रह्मणस्पतिरिन्द्रश्च; १३–१६ ब्रह्मणस्पतिः	१–११; १३–१५ जगती; १२; १६ त्रिष्टुप्	९७
२५(२१६)	२.३.३	२.७.४	इन्धानो	५	,,	ब्रह्मणस्पतिः	जगती	१०४
२६(२१७)	२.३.४	२.७.५	ऋजुः	४	,,	,,	,,	१०६
२७(२१८)	२.३.५	२.७.६	इमा गिरः	१७	कूर्मो गार्त्समदः गृत्समदो वा	आदित्याः	त्रिष्टुप्	१०८
२८(२१९)	२.३.६	२.७.९	इदं कवेः	११	,, ,,	वरुणः	,,	११५
२९(२२०)	२.३.७	२.७.११	धृतव्रताः	७	,, ,,	विश्वे देवाः	,,	१२०

३०(२२१)	२.३.८	२.७.१२	ऋतं देवाय	११	गृत्समदः	१–५ इन्द्रः; ६ इन्द्रासोमौ; ७ इन्द्रः; ८[१] सरस्वती; ८[२] इन्द्रः; ९ बृहस्पतिः; १० इन्द्रः; ११ मरुतः	१–१० त्रिष्टुप्; ११ जगती	१२३
३१(२२२)	२.३.९	२.७.१४	अस्माकं	७	”	विश्वे देवाः	१–६ जगती; ७ त्रिष्टुप्	१२७
३२(२२३)	२.३.१०	२.७.१५	अस्य मे	८	”	१ द्यावापृथिवी; २; ३ इन्द्रस्त्वष्टा वा; ४; ५ राका; ६; ७ सिनीवाली; ८ गुङ्गुः सिनीवाली राका सरस्वती इन्द्राणी वरुणानी च	१–५ जगती; ६–८ अनुष्टुप्	१३०
३३(२२४)	२.४.१	२.७.१६	आ ते पितः	१५	”	रुद्रः	त्रिष्टुप्	१३४
३४(२२५)	२.४.२	२.७.१९	धारावराः	१५	”	मरुतः	१–१४जगती; १५त्रिष्टुप्	१४०
३५(२२६)	२.४.३	२.७.२२	उपेमसृक्षि	१५	”	अपां नपात्	त्रिष्टुप्	१४७
३६(२२७)	२.४.४	२.७.२५	तुभ्यं हिन्वानः	६	”	ऋतवः १ इन्द्रो मधुश्च; २ मरुतो माधवश्च; ३ त्वष्टा शुक्रश्च; ४ अग्निः शुचिश्च; ५ इन्द्रो नभश्च; ६ मित्रावरुणौ नभस्यश्च	जगती	१५३
३७(२२८)	२.४.५	२.८.१	मन्दस्व	६	”	ऋतवः १–४ द्रविणोदाः; ५ अश्विनौ; ६ अग्निः	”	१५६
३८(२२९)	२.४.६	२.८.२	उदु ष्यः	११	”	सविता	त्रिष्टुप्	१५८
३९(२३०)	२.४.७	२.८.४	ग्रावाणेव	८	”	अश्विनौ	”	१६२
४०(२३१)	२.४.८	२.८.६	सोमापूषणा	६	”	१–६[१] सोमापूषणौ; ६[२] सोमापूषणौ अदितिश्च;	”	१६५
४१(२३२)	२.४.९	२.८.७	वायो ये ते	२१	”	१; २ वायुः; ३ इन्द्र-	१–१५ गायत्री; १६; १७	१६८

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि॰-भागे पृष्ठ-संख्या
						वायू ; ४–६ मित्रावरुणौ; ७–९ अश्विनौ; १०–१२; इन्द्रः; १३–१५ विश्वे देवाः; १६–१८सरस्वती; १९¹⁻² द्यावापृथिवी हविर्धाने वा; १९³ द्यावापृथिवी हविर्धाने वाग्निर्वा; २०; २१ द्यावापृथिवी वा हविर्धाने वा	अनुष्टुप्; १८ बृहती; १९–२१ गायत्री	
४२(२३३)	२.४.१०	२.८.११	कनिक्रदत्	३	गृत्समदः	इन्द्रः कपिञ्जलरूपी	त्रिष्टुप्	१७३
४३(२३४)	२.४.११	२.८.१२	प्रदक्षिणित्	३	,,	,, ,,	१ जगती; २ अतिशक्वर्यष्टिर्वा; ३ जगती	१७४
१(२३५)	३.१.१	२.८.१३	सोमस्य मा	२३	विश्वामित्रो गाथिनः	अग्निः	त्रिष्टुप्	१७७
२(२३६)	३.१.२	२.८.१७	वैश्वानराय	१५	,, ,,	अग्निर्वैश्वानरः	जगती	१८५
३(२३७)	३.१.३	२.८.१८	,,	११	,, ,,	,,	,,	१९०
४(२३८)	३.१.४	२.८.२२	समित्समित्	११	,, ,,	आप्रियः	त्रिष्टुप्	१९४
५(२३९)	३.१.५	२.८.२४	प्रत्यग्निरुषसः	११	,, ,,	अग्निः	,,	१९८
६(२४०)	३.१.६	२.८.२६	प्र कारवः	११	,, ,,	,,	,,	२०२
७(२४१)	३.१.७	३.१.१	प्र य आरुः	११	,, ,,	,,	,,	२०७
८(२४२)	३.१.८	३.१.३	अञ्जन्ति	११	,, ,,	यूपस्तुतिः १–५ यूपः; ६–७ यूपाः; ८ विश्वे देवा यूपा वा; ९; १०	१;२ त्रिष्टुप्; ३ अनुष्टुप्; ४–६ त्रिष्टुप्; ७ अनुष्टुप्; ८–११ त्रिष्टुप्	२१५

						यूपाः; ११ छिन्नयूपस्य मूलभूतः स्थाणुः		
९(२४३)	३.१.९	३.१.५	सखायस्त्वा	९	,, ,,	अग्निः	१–८ बृहती; ९ त्रिष्टुप्	२२३
१०(२४४)	३.१.१०	३.१.७	त्वामग्ने	९	,, ,,	,,	उष्णिक्	२२८
११(२४५)	३.१.११	३.१.९	अग्निर्होता	९	,, ,,	,,	गायत्री	२३२
१२(२४६)	३.१.१२	३.१.११	इन्द्राग्नी	९	,, ,,	इन्द्राग्नी	,,	२३६
१३(२४७)	३.२.१	३.१.१३	प्र वो देवाय	७	ऋषभो वैश्वामित्रः	अग्निः	अनुष्टुप्	२४०
१४(२४८)	३.२.२	३.१.१४	आ होता	७	,, ,,	,,	त्रिष्टुप्	२४३
१५(२४९)	३.२.३	३.१.१५	वि पाजसा	७	उत्कीलः कात्यः	,,	,,	२४७
१६(२५०)	३.२.४	३.१.१६	अयमग्निः	६	,, ,,	,,	१;३;५ बृहती; २;४;६ सतोबृहती	२५२
१७(२५१)	३.२.५	३.१.१७	समिध्यमानः	५	कतो वैश्वामित्रः	,,	त्रिष्टुप्	२५६
१८(२५२)	३.२.६	३.१.१८	भवा नो अग्ने	५	,, ,,	,,	,,	२५९
१९(२५३)	३.२.७	३.१.१९	अग्निं होतारं	५	गाथी कौशिकः	,,	,,	२६०
२०(२५४)	३.२.८	३.१.२०	अग्निमुषसं	५	,, ,,	१ विश्वे देवाः; २–४ अग्निः; ५ विश्वे देवाः	,,	२६६
२१(२५५)	३.२.९	३.१.२१	इमं नः	५	,, ,,	अग्निः	१ त्रिष्टुप्; २;३ अनुष्टुप्; ४ त्रिष्टुप्; ५ विराड्रूपा सतोबृहती	२६९
२२(२५६)	३.२.१०	३.१.२२	अयं सः	५	,, ,,	पुरीष्या अग्नयः	१–३ त्रिष्टुप्; ४अनुष्टुप्; ५ त्रिष्टुप्	२७२
२३(२५७)	३.२.११	३.१.२३	निर्मथितः सुधितः	५	देवश्रवा देववातश्च भारतौ	अग्निः	१; २ त्रिष्टुप्; ३ सतोबृहती; ४; ५ त्रिष्टुप्	२७६
२४(२५८)	३.२.१२	३.१.२४	अग्ने सहस्व	५	विश्वामित्रः	,,	१ अनुष्टुप्; २–५गायत्री	२७९
२५(२५९)	३.२.१३	३.१.२५	अग्ने दिवः	५	,,	१–३ अग्निः; ४ अग्नीन्द्रौ; ५ अग्निः	विराट्	२८१
२६(२६०)	३.२.१४	३.१.२६	वैश्वानरं मनसा	९	१–६ विश्वामित्रः; ७	१–३ अग्निर्वैश्वानरः;	१–६जगती; ७–९त्रिष्टुप्	२८३

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि॰ भागे पृष्ठ-संख्या
					विश्वामित्रः	४–६ मरुतः; ७; ८ अग्निर्विश्वामित्रो वा; ९ विश्वामित्रोपाध्यायः		
२७(२६१)	३.२.१५	३.१.२८	प्र वो वाजाः	१५	„	१ अग्निर्ऋतवो वा; २–१५ अग्निः	गायत्री	२९०
२८(२६२)	३.२.१६	३.१.३१	अग्ने जुषस्व	६	„	अग्निः	१;२ गायत्री; ३उष्णिक्; ४ त्रिष्टुप्; ५ जगती; ६ गायत्री	२९६
२९(२६३)	३.२.१७	३.१.३२	अस्तीदं	१६	„	१–४ अग्निः; ५ अग्निर्ऋत्विजो वा; ६–१६ अग्निः	१; ४; १०; १२अनुष्टुप्; २; ३; ५; ७–९; १३; १६ त्रिष्टुप्; ६; ११; १४; १५ जगती	२९९
३०(२६४)	३.३.१	३.२.१	इच्छन्ति त्वा	२२	„	इन्द्रः	त्रिष्टुप्	३१०
३१(२६५)	३.३.२	३.२.५	शासद्वह्निः	२२	कुशिक ऐषीरथिः विश्वामित्रो वा	„	„	३२३
३२(२६६)	३.३.३	३.२.९	इन्द्र सोमं	१७	विश्वामित्रः	„	„	३३६
३३(२६७)	३.३.४	३.२.१२	प्र पर्वतानां	१३	१–३ विश्वामित्रः; ४ नद्यः; ५ विश्वामित्रः; ६ नद्यः; ७ विश्वामित्रः; ८ नद्यः; ९ विश्वामित्रः; १० नद्यः; ११–१३विश्वामित्रः	१–३ नद्यः; ४ विश्वामित्रः; ५ नद्यः; ६; ७ इन्द्रः; ८ विश्वामित्रः; ९ नद्यः; १० विश्वामित्रः; ११–१३ नद्यः	१–१२ त्रिष्टुप्; १३ अनुष्टुप्	३४६
३४(२६८)	३.३.५	३.२.१५	इन्द्रः पूर्भिद्	११	विश्वामित्रः	इन्द्रः	त्रिष्टुप्	३५५
३५(२६९)	३.३.६	३.२.१७	तिष्ठा हरी	११	„	„	„	३६१

३६(२७०)	३.३.७	३.२.१९	इमामू षु	११	१–९ विश्वामित्रः; १० घोर आङ्गिरसः; ११ विश्वामित्रः	,,	,,	३६७
३७(२७१)	३.३.८	३.२.२०	वार्त्रहत्याय	११	विश्वामित्रः	,,	१–१० गायत्री; ११ अनुष्टुप्	३७३
३८(२७२)	३.३.९	३.२.२२	अभि तष्टेव	१०	प्रजापतिर्वैश्वामित्रो वाच्यो वा द्वौ वा तौ विश्वामित्रो वा	,,	त्रिष्टुप्	३७७
३९(२७३)	३.४.१	३.२.२५	इन्द्रं मतिः	९	विश्वामित्रः	,,	,,	३८३
४०(२७४)	३.४.२	३.३.१	इन्द्र त्वा	९	,,	,,	गायत्री	३८८
४१(२७५)	३.४.३	३.३.३	आ तू न इन्द्र	९	,,	,,	,,	३९१
४२(२७६)	३.४.४	३.३.५	उप नः सुतं	९	,,	,,	,,	३९५
४३(२७७)	३.४.५	३.३.७	आ याह्यर्वाङ्	८	,,	,,	त्रिष्टुप्	३९८
४४(२७८)	३.४.६	३.३.८	अयं ते अस्तु	५	,,	,,	बृहती	४०१
४५(२७९)	३.४.७	३.३.९	आ मन्द्रैः	५	,,	,,	,,	४०४
४६(२८०)	३.४.८	३.३.१०	युध्मस्य ते	५	,,	,,	त्रिष्टुप्	४०६
४७(२८१)	३.४.९	३.३.११	मरुत्वान्	५	,,	,,	,,	४०९
४८(२८२)	३.४.१०	३.३.१२	सद्यो ह	५	,,	,,	,,	४१२
४९(२८३)	३.४.११	३.३.१३	शंसा महाम्	५	,,	,,	,,	४१४
५०(२८४)	३.४.१२	३.३.१४	इन्द्रः स्वाहा	५	,,	,,	,,	४१७
५१(२८५)	३.४.१३	३.३.१५	चर्षणीधृतं	१२	,,	,,	१–३ जगती; ४–९ त्रिष्टुप्; १०–१२ गायत्री	४१९
५२(२८६)	३.४.१४	३.३.१७	धानावन्तं	८	,,	,,	१–४ गायत्री; ५; ७; ८ त्रिष्टुप्; ६ जगती	४२५
५३(२८७)	३.४.१५	३.३.१९	इन्द्रापर्वता	२४	,,	१ इन्द्रापर्वतौ; २–१४ इन्द्रः; १५; १६ वाक्; १७–२० रथाङ्गानि;	१–९; ११; १४; १५; १७; १९; २१; २३; २४ त्रिष्टुप्; १०; १६ जगती;	४२८

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि०-भागे पृष्ठ-संख्या
५४(२८८)	३.५.१	३.३.२४	इमं महे	२२	प्रजापतिर्वैश्वामित्रः प्रजापतिर्वाच्यो वा	२१–२४ इन्द्रः (अभिशापार्था वसिष्ठद्वेषिण्यः) विश्वे देवाः	१२; २०; २२ अनुष्टुप्; १३ गायत्री; १८ बृहती त्रिष्टुप्	४४०
५५(२८९)	३.५.२	३.३.२८	उषसः पूर्वाः	२२	”	विश्वे देवाः—१ उषाः; २–१० अग्निः; ११ अहोरात्रे; १२–१४ रोदसी; १५ रोदसी द्युनिशौ वा; १६ दिशः; १७–२२ इन्द्रः पर्जन्यात्मा, त्वष्टाग्निश्च वा	”	४५१
५६(२९०)	३.५.३	३.४.१	न ता मिनन्ति	८	”	विश्वे देवाः	”	४६२
५७(२९१)	३.५.४	३.४.२	प्र मे विविक्वान्	६	विश्वामित्रः	” ”	”	४६६
५८(२९२)	३.५.५	३.४.३	धेनुः प्रत्नस्य	९	”	अश्विनौ	”	४६९
५९(२९३)	३.५.६	३.४.५	मित्रो जनान्	९	”	मित्रः	१–५ त्रिष्टुप्; ६–९ गायत्री	४७३
६०(२९४)	३.५.७	३.४.७	इहेह वः	७	”	१–४ ऋभवः; ५–७ ऋभव इन्द्रश्च	जगती	४७७
६१(२९५)	३.५.८	३.४.८	उषो वाजेन	७	”	उषाः	त्रिष्टुप्	४८१
६२(२९६)	३.५.९	३.४.९	इमा उ वां	१८	१–१५ विश्वामित्रः; १६–१८ विश्वामित्रो जमदग्निर्वा	१–३ इन्द्रावरुणौ; ४–६ बृहस्पतिः; ७–९ पूषा; १०–१२ सविता; १३–१५ सोमः; १६–१८ मित्रावरुणौ	१–३ त्रिष्टुप्; ४–१८ गायत्री	४८४

१(२९७)	४.१.१	३.४.१२	त्वां ह्यग्ने सदमित्	२०	वामदेवो गौतमः	१; ६–२० अग्निः; २–५ अग्निः अग्निर्वरुणश्च वा	१ अष्टिः; २ अतिजगती; ३ धृतिः; ४–२० त्रिष्टुप्	४९३
२(२९८)	४.१.२	३.४.१६	यो मर्त्येषु	२०	,, ,,	अग्निः	त्रिष्टुप्	५०२
३(२९९)	४.१.३	३.४.२०	आ वो राजानं	१६	,, ,,	,,	,,	५१२
४(३००)	४.१.४	३.४.२३	कृणुष्व पाजः	१५	,, ,,	अग्नी रक्षोहा	,,	५१९
५(३०१)	४.१.५	३.५.१	वैश्वानराय	१५	,, ,,	अग्निर्वैश्वानरः	,,	५२८
३०२(६)	४.१.६	३.५.४	ऊर्ध्व ऊ षु	११	,, ,,	अग्निः	,,	५३४
७(३०३)	४.१.७	३.५.६	अयमिह	११	,, ,,	,,	१ जगती; २–६ अनुष्टुप्; ७–११ त्रिष्टुप्	५३८
८(३०४)	४.१.८	३.५.८	दूतं वः	८	,, ,,	,,	गायत्री	५४३
९(३०५)	४.१.९	३.५.९	अग्ने मृळ	८	,, ,,	,,	,,	५४५
१०(३०६)	४.१.१०	३.५.१०	अग्ने तमद्य	८	,, ,,	,,	१–३ पदपङ्क्तिः; ४; ६; ७ उष्णिक् पदपङ्क्तिर्वा; ५ महापदपङ्क्तिः; ८ उष्णिक्	५४७
११(३०७)	४.२.१	३.५.११	भद्रं ते	~~११~~ ६	,, ,,	,,	त्रिष्टुप्	५५०
१२(३०८)	४.२.२	३.५.१२	यस्त्वामग्ने	६	,, ,,	,,	,,	५५३
१३(३०९)	४.२.३	३.५.१३	प्रत्यग्निः	५	,, ,,	अग्निर्लिङ्गोक्तदेवता वा	,,	५५५
१४(३१०)	४.२.४	३.५.१४	प्रत्यग्निरुषसः	५	,, ,,	,,	,,	५५७
१५(३११)	४.२.५	३.५.१५	अग्निर्होता	१०	,, ,,	१–६ अग्निः; ७; ८ सोमकः साहदेव्यः; ९; १० अश्विनौ	गायत्री	५५९
१६(३१२)	४.२.६	३.५.१७	आ सत्यो यातु	२१	,, ,,	इन्द्रः	त्रिष्टुप्	५६१
१७(३१३)	४.२.७	३.५.२१	त्वं महान्	२१	,, ,,	,,	१–१४; १६–२१ त्रिष्टुप्; १५ एकपदा विराट्	५७०
१८(३१४)	४.२.८	३.५.२५	अयं पन्थाः	१३	संवाद इन्द्रादितिवामदेवानाम्		त्रिष्टुप्	५७९
१९(३१५)	४.२.९	३.६.१	एवा त्वाम्	११	वामदेवः	इन्द्रः	,,	५८५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि°-भागे पृष्ठ-संख्या
२०(३१६)	४.२.१०	३.६.३	आ न इन्द्रः	११	वामदेवः	इन्द्रः	त्रिष्टुप्	५८९
२१(३१७)	४.२.११	३.६.५	आ यात्विन्द्रः	११	,,	,,	,,	५९३
२२(३१८)	४.३.१	३.६.७	यन्न इन्द्रः	११	,,	,,	,,	५९७
२३(३१९)	४.३.२	३.६.९	कथा महाम्	११	,,	१–७; ११ इन्द्रः; ८–१० इन्द्र ऋतदेवो वा	,,	६०१
२४(३२०)	४.३.३	३.६.११	का सुष्टुतिः	११	,,	इन्द्रः	१–९; ११ त्रिष्टुप्; १० अनुष्टुप्	६०५
२५(३२१)	४.३.४	३.६.१३	को अद्य	८	,,	,,	त्रिष्टुप्	६०९
२६(३२२)	४.३.५	३.६.१५	अहं मनुः	७	१–३ वामदेव इन्द्रो वा; ४–७ वामदेवः	१–३ इन्द्रो वामदेवो वा; ४–७ श्येनः	,,	६१२
२७(३२३)	४.३.६	३.६.१६	गर्भे नु सन्	५	वामदेवः	१–४ श्येनः; ५ श्येन इन्द्रो वा	१–४ त्रिष्टुप्; ५ शक्करी	६१६
२८(३२४)	४.३.७	३.६.१७	त्वा युजा	५	,,	इन्द्रः इन्द्रासोमौ वा	त्रिष्टुप्	६१८
२९(३२५)	४.३.८	३.६.१८	आ नः स्तुतः	५	,,	इन्द्रः	,,	६२०
३०(३२६)	४.३.९	३.६.१९	नकिरिन्द्र	२४	,,	१–८; १२–२४ इन्द्रः; ९–११ इन्द्र उषाश्च	१–७; ९–२३ गायत्री; ८; २४ अनुष्टुप्	६२१
३१(३२७)	४.३.१०	३.६.२४	कया नः	१५	,,	इन्द्रः	१; २; ४–१५ गायत्री; ३ पादनिचृत्	६२७
३२(३२८)	४.३.११	३.६.२७	आ तू नः	२४	,,	१–२२ इन्द्रः; २३; २४ इन्द्राश्वौ	गायत्री	६३१
३३(३२९)	४.४.१	३.७.१	प्र ऋभुभ्यः	११	,,	ऋभवः	त्रिष्टुप्	६३७
३४(३३०)	४.४.२	३.७.३	ऋभुर्विभ्वा	११	,,	,,	,,	६४१
३५(३३१)	४.४.३	३.७.५	इहोप यात	९	,,	,,	,,	६४६

३६(३३२)	४.४.४	३.७.७	अनश्वो जातः	९	,,	,,	१–८ जगती; ९ त्रिष्टुप्	६४९
३७(३३३)	४.४.५	३.७.९	उप नः	८	,,	,,	१–४ त्रिष्टुप्; ५–८ अनुष्टुप्	६५३
३८(३३४)	४.४.६	३.७.११	उतो हि वां	८ 10	,,	१ द्यावापृथिवी; २–१० दधिक्राः	त्रिष्टुप्	६५५
३९(३३५)	४.४.७	३.७.१३	आशुं	६	,,	दधिक्राः	१–५ त्रिष्टुप्; ६ अनुष्टुप्	६५९
४०(३३६)	४.४.८	३.७.१४	दधिक्राव्णः	५	,,	१–४ दधिक्राः; ५ सूर्यः	१ त्रिष्टुप्; २–५ जगती	६६२
४१(३३७)	४.४.९	३.७.१५	इन्द्रा को वां	११	,,	इन्द्रावरुणौ	त्रिष्टुप्	६६५
४२(३३८)	४.४.१०	३.७.१७	मम द्विता	१०	त्रसदस्युः पौरुकुत्स्यः	१–६ आत्मस्तुतिः; ७–१० इन्द्रावरुणौ	,,	६६९
४३(३३९)	४.४.११	३.७.१९	क उ श्रवत्	७	पुरुमीळ्हाजमीळ्हौ सौहोत्रौ	अश्विनौ	,,	६७३
४४(३४०)	४.४.१२	३.७.२०	तं वां	७	,, ,,	,,	,,	६७६
४५(३४१)	४.४.१३	३.७.२१	एष स्य	७	वामदेवः	,,	१–६ जगती; ७ त्रिष्टुप्	६७८
४६(३४२)	४.५.१	३.७.२२	अग्रं पिब	७	,,	१ वायुः; २–७ इन्द्रवायू	गायत्री	६८१
४७(३४३)	४.५.२	३.७.२३	वायो शुक्रः	४	,,	१ वायुः; २–४ इन्द्रवायू	अनुष्टुप्	६८३
४८(३४४)	४.५.३	३.७.२४	विहि होत्रा	५	,,	वायुः	,,	६८४
४९(३४५)	४.५.४	३.७.२५	इदं वां	६	,,	इन्द्राबृहस्पती	गायत्री	६८६
५०(३४६)	४.५.५	३.७.२६	यस्तस्तम्भ	११	,,	१–९ बृहस्पतिः; १०; ११ इन्द्राबृहस्पती	१–९; ११ त्रिष्टुप्; १० जगती	६८७
५१(३४७)	४.५.६	३.८.१	इदमु त्यत्	११	,,	उषाः	त्रिष्टुप्	६९२
५२(३४८)	४.५.७	३.८.३	प्रति ष्या	७	,,	,,	गायत्री	६९६
५३(३४९)	४.५.८	३.८.४	तद्देवस्य	७	,,	सविता	जगती	६९८
५४(३५०)	४.५.९	३.८.५	अभूद्देवः	६	,,	,,	१–५ जगती; ६ त्रिष्टुप्	७०१
५५(३५१)	४.५.१०	३.८.६	को वस्त्राता	१०	,,	विश्वे देवाः	१–७ त्रिष्टुप्; ८–१० गायत्री	७०३
५६(३५२)	४.५.११	३.८.८	मही	७	,,	द्यावापृथिवी	१–४ त्रिष्टुप्; ५–७ गायत्री	७०७

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	द्वि॰ भागे पृष्ठसंख्या
५७(३५३)	४.५.१२	३.८.९	क्षेत्रस्य	८	वामदेवः	१–३ क्षेत्रपतिः; ४ शुनः; ५; ८ शुनासीरौ; ६; ७ सीता	१; ४; ६; ७ अनुष्टुप् ; २; ३; ८ त्रिष्टुप् ; ५ पुर-उष्णिक्	७०९
५८(३५४)	४.५.१३	३.८.१०	समुद्रात्	११	”	अग्निः सूर्यो वापो वा गावो वा घृतं वा	१–१० त्रिष्टुप् ; ११ जगती	७१३
१(३५५)	५.१.१	३.८.१२	अबोध्यग्निः	१२	बुधगविष्ठिरौ आत्रेयौ	अग्निः	त्रिष्टुप्	७१९
२(३५६)	५.१.२	३.८.१४	कुमारं	१२	१; ३–८; १०–१२ कुमार आत्रेयः वृशो वा जानः (जारः) उभौ वा; २; ९ वृशो जानः (जारः)	”	१–११ त्रिष्टुप् ; १२ शाक्वरी	७२३
३(३५७)	५.१.३	३.८.१६	त्वमग्ने	१२	वसुश्रुत आत्रेयः	१–२; ४–१२ अग्निः; ३ मरुतो रुद्रो विष्णुश्च	त्रिष्टुप्	७२९
४(३५८)	५.१.४	३.८.१८	त्वामग्ने	११	” ”	अग्निः	”	७३४
५(३५९)	५.१.५	३.८.२०	सुसमिद्धाय	११	” ”	आप्रियः	गायत्री	७३८
६(३६०)	५.१.६	३.८.२२	अग्निं तं	१०	” ”	अग्निः	पङ्क्तिः	७४०
७(३६१)	५.१.७	३.८.२४	सखायः	१०	इष आत्रेयः	”	१–९ अनुष्टुप् ; १० पङ्क्तिः	७४४
८(३६२)	५.१.८	३.८.२६	त्वामग्ने	७	” ”	”	जगती	७४८
९(३६३)	५.१.९	४.१.१	”	७	गय आत्रेयः	”	१–४; ६ अनुष्टुप् ; ५; ७ पङ्क्तिः	७५३
१०(३६४)	५.१.१०	४.१.२	अग्न ओजिष्ठम्	७	” ”	”	१–३; ५; ६ अनुष्टुप् ; ४; ७ पङ्क्तिः	७५७
११(३६५)	५.१.११	४.१.३	जनस्य	६	सुतंभर आत्रेयः	”	जगती	७६१

१२(३६६)	५.१.१२	४.१.४	प्राग्नये	६	,, ,,	,,	त्रिष्टुप्	७६४
१३(३६७)	५.१.१३	४.१.५	अर्चन्तः	६	,, ,,	,,	गायत्री	७६७
१४(३६८)	५.१.१४	४.१.६	अग्निं स्तोमेन	६	,, ,,	,,	,,	७६८
१५(३६९)	५.२.१	४.१.७	प्र वेधसे	५	धरुण आङ्गिरसः	,,	त्रिष्टुप्	७७०
१६(३७०)	५.२.२	४.१.८	बृहद्वयः	५	पूरुरात्रेयः	,,	१–४ अनुष्टुप् ;५ पङ्क्तिः	७७१
१७(३७१)	५.२.३	४.१.९	आ यज्ञैः	५	,,	,,	१–४ अनुष्टुप् ; ५ पङ्क्तिः	७७३
१८(३७२)	५.२.४	४.१.१०	प्रातरग्निः	५	सृक्तवाहा द्वित आत्रेयः	,,	१–४ अनुष्टुप् ; ५ पङ्क्तिः	७७५
१९(३७३)	५.२.५	४.१.११	अस्थ्यवस्थाः	५	वव्रिरात्रेयः	,,	१; २ गायत्री; ३; ४ अनुष्टुप् ; ५ विराड्रूपा	७७७
२०(३७४)	५.२.६	४.१.१२	यमग्ने	४	प्रयस्वन्तः अत्रयः	,,	१–३ अनुष्टुप् ; ४ पङ्क्तिः	७७८
२१(३७५)	५.२.७	४.१.१३	मनुष्वत्वा	४	सस आत्रेयः	,,	१–३ अनुष्टुप् ; ४ पङ्क्तिः	७८०
२२(३७६)	५.२.८	४.१.१४	प्र विश्वसामन्	४	विश्वसामा आत्रेयः	,,	१–३ अनुष्टुप् ; ४ पङ्क्तिः	७८१
२३(३७७)	५.२.९	४.१.१५	अग्ने सहन्तम्	४	द्युम्नो विश्वचर्षणिरात्रेयः	,,	१–३ अनुष्टुप् ; ४ पङ्क्तिः	७८३
२४(३७८)	५.२.१०	४.१.१६	अग्ने त्वं	४	बन्धुः सुबन्धुः श्रुतबन्धु-र्विप्रबन्धुश्च गौपायना लौपायना वा	,,	द्विपदा (विराट्)	७८४
२५(३७९)	५.२.११	४.१.१७	अच्छा वः	९	वसूयव आत्रेयाः	,,	अनुष्टुप्	७८५
२६(३८०)	५.२.१२	४.१.१९	अग्ने पावक	९	,, ,,	१–८ अग्निः; ९ विश्वे देवाः	गायत्री	७८८
२७(३८१)	५.२.१३	४.१.२१	अनस्वन्ता	६	त्र्यरुणस्त्रैवृष्णः त्रसदस्युः पौरुकुत्स्यः भारतोऽश्वमेधश्च (अत्रिर्भौम इति केचित्)	१–५ अग्निः; ६ इन्द्राग्नी	१–३ त्रिष्टुप् ; ४–६ अनुष्टुप्	७९०
२८(३८२)	५.२.१४	४.१.२२	समिद्धः	६	विश्ववारात्रेयी	अग्निः	१; ३ त्रिष्टुप् ; २ जगती; ४अनुष्टुप् ; ५; ६गायत्री	७९२
२९(३८३)	५.२.१५	४.१.२३	त्र्ययंमा	१५	गौरिवीतिः शाक्त्यः	१–८; ९[२]–१५ इन्द्रः; ९[१] इन्द्र उशना वा	त्रिष्टुप्	७९४
३०(३८४)	५.२.१६	४.१.२६	क्व१स्य	१५	बभ्रुरात्रेयः	इन्द्र ऋणंचयश्च (राजा)	,,	८०१

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि०-भागे पृष्ठ-संख्या
३१(३८५)	५.२.१७	४.१.२९	इन्द्रो रथाय	१३	अवस्युरात्रेयः	१–८$^{१-२}$; १०–१३ इन्द्रः; ८^{३} इन्द्रः कुत्सो वा; ८^{४} इन्द्र उशना वा; ९ इन्द्रः कुत्सश्च	त्रिष्टुप्	८०६
३२(३८६)	५.२.१८	४.१.३२	अदर्दः	१२	गातुरात्रेयः	इन्द्रः	,,	८११
३३(३८७)	५.३.१	४.२.१	महि महे	१०	संवरणः प्राजापत्यः	,,	,,	८१७
३४(३८८)	५.३.२	४.२.३	अजातशत्रुम्	९	,, ,,	,,	१–८ जगती; ९ त्रिष्टुप्	८२१
३५(३८९)	५.३.३	४.२.५	यस्ते	८	प्रभूवसुराङ्गिरसः	,,	१–७ अनुष्टुप्; ८ पङ्क्तिः	८२४
३६(३९०)	५.३.४	४.२.७	स आ गमत्	६	,,	,,	१; २; ४–६ त्रिष्टुप्; ३ जगती	८२७
३७(३९१)	५.३.५	४.२.८	सं भानुना	५	अत्रिः	,,	त्रिष्टुप्	८२९
३८(३९२)	५.३.६	४.२.९	उरोष्टे	५	,,	,,	अनुष्टुप्	८३१
३९(३९३)	५.३.७	४.२.१०	यदिन्द्र	५	,,	,,	१–४ अनुष्टुप्; ५पङ्क्तिः	८३३
४०(३९४)	५.३.८	४.२.११	आ याह्यद्रिभिः	९	,,	१–४ इन्द्रः; ५ सूर्यः; ६–९ अत्रिः	१–३ उष्णिक्; ४; ६–८ त्रिष्टुप्; ५; ९ अनुष्टुप्	८३४
४१(३९५)	५.३.९	४.२.१३	को नु वां	२०	,,	विश्वे देवाः	१–१५; १८; १९त्रिष्टुप्; १६; १७ अतिजगती; २० एकपदा (विराट्)	८३८
४२(३९६)	५.३.१०	४.२.१७	प्र शंतमा	१८	,,	१–१०; १२–१८ विश्वे देवाः; ११ रुद्रः	१–१६; १८ त्रिष्टुप्; १७ एकपदा (विराट्)	८४६
४३(३९७)	५.३.११	४.२.२०	आ धेनवः	१७	,,	विश्वे देवाः	१–१५; १७ त्रिष्टुप्; १६ एकपदा (विराट्)	८५२
४४(३९८)	५.३.१२	४.२.२३	तं प्रत्नथा	१५	अवत्सारः काश्यपः अन्ये च ऋषयो दृष्टलिङ्गाः	,, ,,	१–१३ जगती; १४; १५ त्रिष्टुप्	८५९

४५(३९९)	५.४.१	४.२.२६	विदा दिवः	११	सदापृण आत्रेयः	,, ,,	त्रिष्टुप्	८६५
४६(४००)	५.४.२	४.२.२८	हयो न	८	प्रतिक्षत्र आत्रेयः	१–६ विश्वे देवाः; ७; ८ देवपत्न्यः	१; ३–६ जगती; २; ८ त्रिष्टुप्	८७०
४७(४०१)	५.४.३	४.३.१	प्रयुञ्जती	७	प्रतिरथ आत्रेयः	विश्वे देवाः	त्रिष्टुप्	८७४
४८(४०२)	५.४.४	४.३.२	कदु प्रियाय	५	प्रतिभानुरात्रेयः	,, ,,	जगती	८७७
४९(४०३)	५.४.५	४.३.३	देवं वः	५	प्रतिप्रभ आत्रेयः	,, ,,	त्रिष्टुप्	८७९
५०(४०४)	५.४.६	४.३.४	विश्वो देवस्य	५	स्वस्त्यात्रेयः	,, ,,	१–४अनुष्टुप्; ५पङ्क्तिः	८८१
५१(४०५)	५.४.७	४.३.५	अग्ने सुतस्य	१५	,,	,, ,,	१–४ गायत्री; ५–१० उष्णिक्; ११–१३ त्रिष्टुब्जगती वा; १४; १५ अनुष्टुप्	८८३
५२(४०६)	५.४.८	४.३.८	प्र श्यावाश्व	१७	श्यावाश्व आत्रेयः	मरुतः	१–५; ७–१६ अनुष्टुप्; ६; १७ पङ्क्तिः	८८८
५३(४०७)	५.४.९	४.३.११	को वेद	१६	,, ,,	,,	१; ५; १०; ११; १५ ककुप्; २ बृहती; ३ अनुष्टुप्; ४ पुरउष्णिक्; ६; ७; ९; १३; १४; १६ सतोबृहती; ८; १२ गायत्री	८९४
५४(४०८)	५.४.१०	४.३.१४	प्र शर्धाय	१५	,, ,,	,,	१–१३; १५ जगती; १४ त्रिष्टुप्	९००
५५(४०९)	५.४.११	४.३.१७	प्रयज्यवः	१०	,, ,,	,,	१–९ जगती; १० त्रिष्टुप्	९०६
५६(४१०)	५.४.१२	४.३.१९	अग्ने शर्धन्तम्	९	,, ,,	,,	१; २; ४–६; ८; ९ बृहती; ३; ७ सतोबृहती	९१०
५७(४११)	५.५.१	४.३.२१	आ रुद्रासः	८	,, ,,	,,	१–६ जगती; ७; ८ त्रिष्टुप्	९१३
५८(४१२)	५.५.२	४.३.२३	तमु नूनं	८	,, ,,	,,	त्रिष्टुप्	९१६

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	द्वि॰-भागे पृष्ठ-संख्या
५९(४१३)	५.५.३	४.३.२४	प्र वः	८	श्यावाश्व आत्रेयः	मरुतः	१–७ जगती; ८ त्रिष्टुप्	९१९
६०(४१४)	५.५.४	४.३.२५	ईळे अग्निं	८	,, ,,	मरुतोऽग्निश्च मरुतोऽग्निर्वा	१–६ त्रिष्टुप्; ७; ८ जगती	९२३
६१(४१५)	५.५.५	४.३.२६	के ष्ठा नरः	१९	,, ,,	१–४ मरुतः; ५–८ शशीयसी तरन्तमहिषी; ९ पुरुमीळ्हो वैददश्विः; १० तरन्तो वैददश्विः; ११–१६ मरुतः; १७–१९ रथवीतिर्दाल्भ्यः	१–४; ६–८; १०–१९ गायत्री; ५ अनुष्टुप्; ९ सतोबृहती	९२६
६२(४१६)	५.५.६	४.३.३०	ऋतेन	९	श्रुतविदात्रेयः	मित्रावरुणौ	त्रिष्टुप्	९३२
६३(४१७)	५.५.७	४.४.१	ऋतस्य गोपौ	७	अर्चनाना आत्रेयः	,,	जगती	९३७
६४(४१८)	५.५.८	४.४.२	वरुणं वः	७	,, ,,	,,	१–६अनुष्टुप्; ७पङ्क्तिः	९३९
६५(४१९)	५.५.९	४.४.३	यश्चिकेत	६	रातहव्य आत्रेयः	,,	१–५अनुष्टुप्; ६पङ्क्तिः	९४२
६६(४२०)	५.५.१०	४.४.४	आ चिकितान	६	,, ,,	,,	अनुष्टुप्	९४४
६७(४२१)	५.५.११	४.४.५	बळित्था	५	यजत आत्रेयः	,,	,,	९४६
६८(४२२)	५.५.१२	४.४.६	प्र वो मित्राय	५	,, ,,	,,	गायत्री	९४८
६९(४२३)	५.५.१३	४.४.७	त्री रोचना	४	उरुचक्रिरात्रेयः	,,	त्रिष्टुप्	९५०
७०(४२४)	५.५.१४	४.४.८	पुरूरुणा	४	,, ,,	,,	गायत्री	९५१
७१(४२५)	५.५.१५	४.४.९	आ नो गन्तं	३	बाहुवृक्त आत्रेयः	,,	,,	९५२
७२(४२६)	५.५.१६	४.४.१०	आ मित्रे	३	,, ,,	,,	उष्णिक्	९५३
७३(४२७)	५.६.१	४.४.११	यदद्य	१०	पौर आत्रेयः	अश्विनौ	अनुष्टुप्	९५४
७४(४२८)	५.६.२	४.४.१३	कूष्ठो देवौ	१०	,, ,,	,,	,,	९५८
७५(४२९)	५.६.३	४.४.१५	प्रति प्रियतमं	९	अवस्युरात्रेयः	,,	पङ्क्तिः	९५९

७६(४३०)	५.६.४	४.४.१७	आ भाति	५	अत्रिः	,,	त्रिष्टुप्	९६५
७७(४३१)	५.६.५	४.४.१८	प्रातर्यावाणा	५	,,	,,	,,	९६७
७८(४३२)	५.६.६	४.४.१९	अश्विनौ	९	सप्तवध्रिरात्रेयः	,,	१–३ उष्णिक्; ४ त्रिष्टुप् ; ५–९ अनुष्टुप्	९६९
७९(४३३)	५.६.७	४.४.२१	महे नो अद्य	१०	सत्यश्रवा आत्रेयः	उषाः	पङ्क्तिः	९७३
८०(४३४)	५.६.८	४.४.२३	द्युतद्यामानं	६	,, ,,	,,	त्रिष्टुप्	९७६
८१(४३५)	५.६.९	४.४.२४	युञ्जते	५	श्यावाश्व आत्रेयः	सविता	जगती	९७८
८२(४३६)	५.६.१०	४.४.२५	तत्सवितुः	९	,, ,,	,,	१ अनुष्टुप् ; २–९ गायत्री	९८०
८३(४३७)	५.६.११	४.४.२७	अच्छा वद	१०	अत्रिः	पर्जन्यः	१; ५–८; १० त्रिष्टुप् ; २–४ जगती; ९ अनुष्टुप्	९८३
८४(४३८)	५.६.१२	४.४.२९	बळित्था	३	,,	पृथिवी	अनुष्टुप्	९८७
८५(४३९)	५.६.१३	४.४.३०	प्र सम्राजे	८	,,	वरुणः	त्रिष्टुप्	९८९
८६(४४०)	५.६.१४	४.४.३२	इन्द्राग्नी	६	,,	इन्द्राग्नी	१–५ अनुष्टुप् ; ६ विराट्पूर्वा	९९२
८७(४४१)	५.६.१५	४.४.३३	प्र वो महे	९	एवयामरुदात्रेयः	मरुतः	अतिजगती	९९४
								तृ°-भागे
१(४४२)	६.१.१	४.४.३५	त्वं ह्यग्ने	१३	भरद्वाजो बार्हस्पत्यः	अग्निः	त्रिष्टुप्	१
२(४४३)	६.१.२	४.५.१	त्वं हि क्षैतवत्	११	,, ,,	,,	१–१० अनुष्टुप् ; ११ शाकरी	६
३(४४४)	६.१.३	४.५.३	अग्ने स क्षेषत्	८	,, ,,	,,	त्रिष्टुप्	१०
४(४४५)	६.१.४	४.५.५	यथा होतः	८	,, ,,	,,	,,	१३
५(४४६)	६.१.५	४.५.७	हुवे वः	७	,, ,,	,,	,,	१६
६(४४७)	६.१.६	४.५.८	प्र नव्यसा	७	,, ,,	,,	,,	१९
७(४४८)	६.१.७	४.५.९	मूर्धानं	७	,, ,,	वैश्वानरः	१–५ त्रिष्टुप् ; ६; ७ जगती	२२
८(४४९)	६.१.८	४.५.१०	पृक्षस्य	७	,, ,,	,,	१–६ जगती; ७ त्रिष्टुप्	२५

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	तृ॰-भागे पृष्ठ-संख्या
९(४५०)	६.१.९	४.५.११	अहश्च	७	भरद्वाजो बार्हस्पत्यः	वैश्वानरः	त्रिष्टुप्	२७
१०(४५१)	६.१.१०	४.५.१२	पुरो वः	७	,, ,,	अग्निः	१–६ त्रिष्टुप्; ७ द्विपदा	३१
११(४५२)	६.१.११	४.५.१३	यजस्व	६	,, ,,	,,	त्रिष्टुप्	३३
१२(४५३)	६.१.१२	४.५.१४	मध्ये होता	६	,, ,,	,,	,,	३६
१३(४५४)	६.१.१३	४.५.१५	त्वद्विश्वा	६	,, ,,	,,	,,	३८
१४(४५५)	६.१.१४	४.५.१६	अग्ना यः	६	,, ,,	,,	१–५ अनुष्टुप्; ६ शक्करी	४०
१५(४५६)	६.१.१५	४.५.१७	इममू षु	१९	भरद्वाजो बार्हस्पत्यो वीतहव्यो वा	,,	१; २; ४; ५; ७–९ जगती; ३; १५ शक्करी; ६ अतिशक्करी; १०–१४; १६; १९ त्रिष्टुप्; १७ अनुष्टुप्; १८ बृहती	४३
१६(४५७)	६.२.१	४.५.२१	त्वमग्ने	४८	भरद्वाजो बार्हस्पत्यः	,,	१; ६ वर्धमाना; २–५; ७–२६; २८–४५ गायत्री; ४६ त्रिष्टुप्; २७; ४७; ४८ अनुष्टुप्	५०
१७(४५८)	६.२.१	४.६.१	पिबा सोमं	१५	,, ,,	इन्द्रः	१–१४ त्रिष्टुप्; १५ द्विपदा	६३
१८(४५९)	६.२.२	४.६.४	तमु ष्टुहि	१५	,, ,,	,,	त्रिष्टुप्	६९
१९(४६०)	६.२.३	४.६.७	महाँ इन्द्रो	१३	,, ,,	,,	,,	७४
२०(४६१)	६.२.४	४.६.९	द्यौर्न	१३	,, ,,	,,	१–६; ८–१३ त्रिष्टुप्; ७ विराट्	७८
२१(४६२)	६.२.५	४.६.११	इमा उ	१२	,, ,,	१–८; १०; १२ इन्द्रः; ९; ११ विश्वे देवाः	त्रिष्टुप्	८३

२२(४६३)	६.२.६	४.६.१३	य एकः	११	भरद्वाजो बार्हस्पत्यः	इन्द्रः	त्रिष्टुप्	८७
२३(४६४)	६.२.७	४.६.१५	सुत इत्	१०	,, ,,	,,	,,	९१
२४(४६५)	६.३.१	४.६.१७	वृषा मदः	१०	,, ,,	,,	,,	९५
२५(४६६)	६.३.२	४.६.१९	या त ऊतिः	९	,, ,,	,,	,,	९८
२६(४६७)	६.३.३	४.६.२१	श्रुधी नः	८	,, ,,	,,	,,	१०२
२७(४६८)	६.३.४	४.६.२३	किमस्य	८	,, ,,	१–७ इन्द्रः; ८ अभ्यावर्तिनश्चायमानस्य दानस्तुतिः	,,	१०४
२८(४६९)	६.३.५	४.६.२५	आ गावः	८	,, ,,	१; ३–८^{3} गावः २; ८^{4} गाव इन्द्रो वा	१; ५–७ त्रिष्टुप् ; २–४ जगती; ८ अनुष्टुप्	१०७
२९(४७०)	६.३.६	४.७.१	इन्द्रं वः	६	,, ,,	इन्द्रः	त्रिष्टुप्	११०
३०(४७१)	६.३.७	४.७.२	भूय इत्	५	,, ,,	,,	,,	११३
३१(४७२)	६.३.८	४.७.३	अभूरेकः	५	सुहोत्रो भारद्वाजः	,,	१–३; ५ त्रिष्टुप् ; ४ शक्वरी	११५
३२(४७३)	६.३.९	४.७.४	अपूर्व्या	५	,, ,,	,,	त्रिष्टुप्	११७
३३(४७४)	६.३.१०	४.७.५	य ओजिष्ठः	५	शुनहोत्रो भारद्वाजः	,,	,,	११९
३४(४७५)	६.३.११	४.७.६	सं च त्वे	५	,, ,,	,,	,,	१२०
३५(४७६)	६.३.१२	४.७.७	कदा भुवन्	५	नरो भारद्वाजः	,,	,,	१२२
३६(४७७)	६.३.१३	४.७.८	सत्रा मदासः	५	,, ,,	,,	,,	१२४
३७(४७८)	६.३.१४	४.७.९	अर्वाग्रथं	५	भरद्वाजो बार्हस्पत्यः	,,	,,	१२६
३८(४७९)	६.३.१५	४.७.१०	अपादितः	५	,, ,,	,,	,,	१२८
३९(४८०)	६.३.१६	४.७.११	मन्द्रस्य	५	,, ,,	,,	,,	१२९
४०(४८१)	६.३.१७	४.७.१२	इन्द्र पिब	५	,, ,,	,,	,,	१३१
४१(४८२)	६.३.१८	४.७.१३	अहेळमानः	५	,, ,,	,,	,,	१३३
४२(४८३)	६.३.१९	४.७.१४	प्रत्यस्मै	४	,, ,,	,,	१–३ अनुष्टुप् ; ४ बृहती	१३५
४३(४८४)	६.३.२०	४.७.१५	यस्य त्यत्	४	,, ,,	,,	उष्णिक्	१३६
४४(४८५)	६.४.१	४.७.१६	यो रयिवः	२४	शंयुर्बार्हस्पत्यः	,,	१–६ अनुष्टुप् ; ७; ९	१३७

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ॰ भागे पृष्ठ-संख्या
							विराट्; ८विराट् त्रिष्टुब्वा; १०–२४ त्रिष्टुप्	
४५(४८६)	६.४.२	४.७.२१	य आनयत्	३३	शंयुर्बार्हस्पत्यः	१–३० इन्द्रः; ३१–३३ बृबुस्तक्षा	१–२८; ३०–३२गायत्री; २९ अतिनिचृत्; ३३ अनुष्टुप्	१४६
४६(४८७)	६.४.३	४.७.२७	त्वामिद्धि	१४	,,	इन्द्रः	प्रागाथम्	१५३
४७(४८८)	६.४.४	४.७.३०	स्वादुः	३१	गर्गो भारद्वाजः	१–५ सोमः; ६–१९; २०²; २१; ३१² इन्द्रः; २०¹ लिङ्गोक्तदेवताः; २२–२५ प्रस्तोकस्य साञ्जयस्य दानस्तुतिः; २६–२८ रथः; २९–३१¹ दुन्दुभिः	१–१८; २०–२२; २६; २८–३१ त्रिष्टुप्; १९ बृहती; २३ अनुष्टुप्; २४ गायत्री; २५ द्विपदा; २७ जगती	१५८
४८(४८९)	६.४.५	४.८.१	यज्ञायज्ञा	२२	शंयुर्बार्हस्पत्यः	तृणपाणिकं पृश्निसूक्तम् १–१० अग्निः; ११; १२ मरुतः; १३–१५ मरुतो लिङ्गोक्तदेवता वा; १६–१९ पूषा; २०; २१ मरुतः; २२ मरुतः पृश्नि-र्द्यावाभूमी वा	१; ३; ५; ९; १४; १९; २० बृहती; २; ४; १०; १२; १७ सतोबृहती; ६; ८ महासतोबृहती; ७ महाबृहती; ११; १६ ककुप्; १३; १८ पुरउष्णिक्; १५ अतिजगती; २१ यवमध्या महाबृहती; २२ अनुष्टुप्	१७०
४९(४९०)	६.४.६	४.८.५	स्तुषे जनं	१५	ऋजिश्वा भारद्वाजः	विश्वे देवाः	१–१४ त्रिष्टुप्; १५ शक्वरी	१७८

५०(४९१)	६.५.१	४.८.८	हुवे वः	१५	,, ,,	,, ,,	त्रिष्टुप्	१८४
५१(४९२)	६.५.२	४.८.११	उदु त्यत्	१६	,, ,,	,, ,,	१–१२ त्रिष्टुप्; १३–१५ उष्णिक्; १६ अनुष्टुप्	१८९
५२(४९३)	६.५.३	४.८.१४	न तद्दिवा	१७	,, ,,	,, ,,	१–६; १३; १५–१७ त्रिष्टुप्; ७–१२ गायत्री; १४ जगती	१९५
५३(४९४)	६.५.४	४.८.१७	वयमु त्वा	१०	भरद्वाजो बार्हस्पत्यः	पूषा	१–७; ९; १० गायत्री; ८ अनुष्टुप्	२००
५४(४९५)	६.५.५	४.८.१९	सं पूषन्	१०	,, ,,	,,	गायत्री	२०२
५५(४९६)	६.५.६	४.८.२१	एहि वां	६	,, ,,	,,	,,	२०४
५६(४९७)	६.५.७	४.८.२२	य एनम्	६	,, ,,	,,	१–५ गायत्री; ६ अनुष्टुप्	२०५
५७(४९८)	६.५.८	४.८.२३	इन्द्रा नु	६	,, ,,	इन्द्रापूषणौ	गायत्री	२०७
५८(४९९)	६.५.९	४.८.२४	शुक्रं ते	४	,, ,,	पूषा	१; ३; ४ त्रिष्टुप्; २ जगती	२०८
५९(५००)	६.५.१०	४.८.२५	प्र नु वोचा	१०	,, ,,	इन्द्राग्नी	१–६ बृहती; ७–१० अनुष्टुप्	२१०
६०(५०१)	६.५.११	४.८.२७	श्नथद्वृत्रम्	१५	,, ,,	,,	[गायत्री] १–३; १३ त्रिष्टुप्; १४ बृहती; १५ अनुष्टुप्	२१३
६१(५०२)	६.५.१२	४.८.३०	इयमददात्	१४	,, ,,	सरस्वती	१–३; १३ जगती; ४–१२ गायत्री; १४ त्रिष्टुप्	२१७
६२(५०३)	६.६.१	५.१.१	स्तुषे नरा	११	,, ,,	अश्विनौ	त्रिष्टुप्	२२१
६३(५०४)	६.६.२	५.१.३	क्व त्या	११	,, ,,	,,	१–१० त्रिष्टुप्; ११ एकपदा	२२५
६४(५०५)	६.६.३	५.१.५	उदु श्रिये	६	,, ,,	उषाः	त्रिष्टुप्	२२८
६५(५०६)	६.६.४	५.१.६	एषा स्या	६	,, ,,	,,	,,	२३०

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	तृ॰ भागे पृष्ठसंख्या
६६(५०७)	६.६.५	५.१.७	वपुर्नु	११	भरद्वाजो बार्हस्पत्यः	मरुतः	त्रिष्टुप्	२३२
६७(५०८)	६.६.६	५.१.९	विश्वेषां	११	,, ,,	मित्रावरुणौ	,,	२३६
६८(५०९)	६.६.७	५.१.११	श्रुष्टी वां	११	,, ,,	इन्द्रावरुणौ	१–८; ११ त्रिष्टुप्; ९; १० जगती	२४०
६९(५१०)	६.६.८	५.१.१३	सं वां	८	,, ,,	इन्द्राविष्णू	त्रिष्टुप्	२४३
७०(५११)	६.६.९	५.१.१४	घृतवती	६	,, ,,	द्यावापृथिवी	जगती	२४६
७१(५१२)	६.६.१०	५.१.१५	उदु ष्य	६	,, ,,	सविता	१–३ जगती; ४–६ त्रिष्टुप्	२४९
७२(५१३)	६.६.११	५.१.१६	इन्द्रासोमा	५	,, ,,	इन्द्रासोमौ	त्रिष्टुप्	२५१
७३(५१४)	६.६.१२	५.१.१७	यो अद्रिभित्	३	,, ,,	बृहस्पतिः	,,	२५३
७४(५१५)	६.६.१३	५.१.१८	सोमारुद्रा	४	,, ,,	सोमारुद्रौ	,,	२५४
७५(५१६)	६.६.१४	५.१.१९	जीमूतस्येव	१९	पायुर्भारद्वाजः	१ वर्म; २ धनुः; ३ ज्या; ४ आर्त्नी; ५ इषुधिः; ६[१] सारथिः; ६[२] रश्मयः; ७ अश्वाः; ८ रथः; ९ रथगोपाः; १० लिङ्गोक्तदेवताः; ११; १२ इषवः; १३ प्रतोदः; १४ हस्तघ्नः; १५; १६ इषवः; १७–१९ लिङ्गोक्तदेवताः संग्रामाशिषः (१७ युद्धभूमिर्ब्रह्मणस्पतिरदितिश्च; १८ कवचसोमवरुणाः; १९ देवा ब्रह्म च)	१–५; ७–९; ११; १४; १८ त्रिष्टुप्; ६; १० जगती; १२; १३; १५; १६; १९ अनुष्टुप्; १७ पङ्क्तिः	२५५

१(५१७)	७.१.१	५.१.२३	अग्निं नरो	२५	वसिष्ठः	अग्निः	१–१८ विराट्; १९–२५ त्रिष्टुप्	२६३
२(५१८)	७.१.२	५.२.१	जुषस्व	११	,,	आप्रियः	त्रिष्टुप्	२७०
३(५१९)	७.१.३	५.२.३	अग्निं वः	१०	,,	अग्निः	,,	२७४
४(५२०)	७.१.४	५.२.५	प्र वः	१०	,,	,,	,,	२७७
५(५२१)	७.१.५	५.२.७	प्राग्नये	९	,,	वैश्वानरः	,,	२८०
६(५२२)	७.१.६	५.२.९	प्र सम्राजः	७	,,	,,	,,	२८३
७(५२३)	७.१.७	५.२.१०	प्र वो देवं	७	,,	अग्निः	,,	२८५
८(५२४)	७.१.८	५.२.११	इन्धे राजा	७	,,	,,	,,	२८७
९(५२५)	७.१.९	५.२.१२	अबोधि जारः	७	,,	,,	,,	२८९
१०(५२६)	७.१.१०	५.२.१३	उषो न	५	,,	,,	,,	२९१
११(५२७)	७.१.११	५.२.१४	महाँ असि	५	,,	,,	,,	२९२
१२(५२८)	७.१.१२	५.२.१५	अगन्म	३	,,	,,	,,	२९४
१३(५२९)	७.१.१३	५.२.१६	प्राग्नये	३	,,	वैश्वानरः	,,	२९५
१४(५३०)	७.१.१४	५.२.१७	समिधा	३	,,	अग्निः	१ बृहती; २; ३ त्रिष्टुप्	२९६
१५(५३१)	७.१.१५	५.२.१८	उपसद्याय	१५	,,	,,	गायत्री	२९७
१६(५३२)	७.१.१६	५.२.२१	एना वः	१२	,,	,,	प्रगाथम्	२९९
१७(५३३)	७.१.१७	५.२.२३	अग्ने भव	७	,,	,,	द्विपदा त्रिष्टुप्	३०३
१८(५३४)	७.२.१	५.२.२४	त्वे ह यत्	२५	,,	१–२१ इन्द्रः; २२–२५ सुदासः पैजवनस्य दानस्तुतिः	त्रिष्टुप्	३०४
१९(५३५)	७.२.२	५.२.२९	यस्तिग्मश्रृङ्गो	११	,,	इन्द्रः	,,	३१२
२०(५३६)	७.२.३	५.३.१	उग्रो जज्ञे	१०	,,	,,	,,	३१६
२१(५३७)	७.२.४	५.३.३	असावि देवं	१०	,,	,,	,,	३१९
२२(५३८)	७.२.५	५.३.५	पिबा सोमम्	९	,,	,,	१–८ विराट्; ९ त्रिष्टुप्	३२२
२३(५३९)	७.२.६	५.३.७	उदु ब्रह्माणि	६	,,	,,	त्रिष्टुप्	३२४
२४(५४०)	७.२.७	५.३.८	योनिष्टे	६	,,	,,	,,	३२६

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	तृ॰ भागे पृष्ठसंख्या
२५(५४१)	७.२.८	५.३.९	आ ते महः	६	वसिष्ठः	इन्द्रः	त्रिष्टुप्	३२८
२६(५४२)	७.२.९	५.३.१०	न सोमः	५	,,	,,	,,	३२९
२७(५४३)	७.२.१०	५.३.११	इन्द्रं नरः	५	,,	,,	,,	३३१
२८(५४४)	७.२.११	५.३.१२	ब्रह्मा णः	५	,,	,,	,,	३३३
२९(५४५)	७.२.१२	५.३.१३	अयं सोमः	५	,,	,,	,,	३३४
३०(५४६)	७.२.१३	५.३.१४	आ नो देव	५	,,	,,	,,	३३६
३१(५४७)	७.२.१४	५.३.१५	प्र व इन्द्राय	१२	,,	,,	१–९ गायत्री; १०–१२ विराट्	३३७
३२(५४८)	७.२.१५	५.३.१७	मो षु त्वा	२७	१–२५; २६[२]; २७ वसिष्ठः; २६[१] शक्तिर्वसिष्ठो वा	,,	१; २; ४–२७ प्रागाथम्; ३ द्विपदा	३४०
३३(५४९)	७.२.१६	५.३.२२	श्वित्यञ्चः	१४	१–९ वसिष्ठः; १०–१४ वसिष्ठपुत्राः; अथवा वसिष्ठस्य सपुत्रस्येन्द्रेण संवादः	१–९ वसिष्ठपुत्राः; १०–१४ वसिष्ठः	त्रिष्टुप्	३४८
३४(५५०)	७.३.१	५.३.२५	प्र शुक्रा	२५	वसिष्ठः	१–१५; १८–२५ विश्वे देवाः; १६ अब्जा अहिः; १७ अहिर्बुध्न्यः	१–२१ द्विपदा विराट्; २२–२५ त्रिष्टुप्	३५३
३५(५५१)	७.३.२	५.३.२८	शं नः	१५	,,	विश्वे देवाः (शान्तिः)	त्रिष्टुप्	३५८
३६(५५२)	७.३.३	५.४.१	प्र ब्रह्म	९	,,	विश्वे देवाः	,,	३६३
३७(५५३)	७.३.४	५.४.३	आ वो वाहिष्ठः	८	,,	,, ,,	,,	३६६
३८(५५४)	७.३.५	५.४.५	उदु ष्यः	८	,,	१–६[१] सविता; ६[२] सविता भगो वा; ७; ८ वाजिनः	,,	३६८

३९(५५५)	७.३.६	५.४.६	ऊर्ध्वो अग्निः	७	”	विश्वे देवाः	”	३७१
४०(५५६)	७.३.७	५.४.७	ओ श्रुष्टिः	७	”	” ”	”	३७३
४१(५५७)	७.३.८	५.४.८	प्रातरग्निं	७	”	१ लिङ्गोक्तदेवताः; २–६ भगः; ७ उषाः	१ जगती; २–७ त्रिष्टुप्	३७५
४२(५५८)	७.३.९	५.४.९	प्र ब्रह्माणः	६	”	विश्वे देवाः	त्रिष्टुप्	३७७
४३(५५९)	७.३.१०	५.४.१०	प्र वो यज्ञेषु	५	”	” ”	”	३७९
४४(५६०)	७.३.११	५.४.११	दधिक्रां	५	”	१ लिङ्गोक्तदेवताः; २–५ दधिक्राः	१ जगती; २–५ त्रिष्टुप्	३८१
४५(५६१)	७.३.१२	५.४.१२	आ देवः	४	”	सविता	त्रिष्टुप्	३८२
४६(५६२)	७.३.१३	५.४.१३	इमा रुद्राय	४	”	रुद्रः	१–३ जगती; ४ त्रिष्टुप्	३८४
४७(५६३)	७.३.१४	५.४.१४	आपो यं	४	”	आपः	त्रिष्टुप्	३८५
४८(५६४)	७.३.१५	५.४.१५	ऋभुक्षणः	४	”	१–३ ऋभवः; ४ ऋभवो विश्वे देवा वा	”	३८६
४९(५६५)	७.३.१६	५.४.१६	समुद्रज्येष्ठाः	४	”	आपः	”	३८८
५०(५६६)	७.३.१७	५.४.१७	आ मां मित्रावरुणा	४	”	१ मित्रावरुणौ; २ अग्निः; ३ विश्वे देवाः; ४ नद्यः	१–३ जगती; ४ अतिजगती शाक्वरी वा	३८९
५१(५६७)	७.३.१८	५.४.१८	आदित्यानाम्	३	”	आदित्याः	त्रिष्टुप्	३९०
५२(५६८)	७.३.१९	५.४.१९	आदित्यासः	३	”	”	”	३९१
५३(५६९)	७.३.२०	५.४.२०	प्र द्यावा	३	”	द्यावापृथिवी	”	३९२
५४(५७०)	७.३.२१	५.४.२१	वास्तोष्पते	३	”	वास्तोष्पतिः	”	३९३
५५(५७१)	७.३.२२	५.४.२२	अमीवहा	८	”	१ वास्तोष्पतिः; २–८ इन्द्रः (प्रस्वापिन्य उपनिषत्)	१ गायत्री; २–४ उपरिष्टाद्बृहती; ५–८ अनुष्टुप्	३९५
५६(५७२)	७.४.१	५.४.२३	क ईं व्यक्ताः	२५	”	मरुतः	१–११ द्विपदा विराट्; १२–२५ त्रिष्टुप्	३९७
५७(५७३)	७.४.२	५.४.२७	मध्वो वः	७	”	”	त्रिष्टुप्	४०३
५८(५७४)	७.४.३	५.४.२८	प्र साकमुक्षे	६	”	”	”	४०५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ॰-भागे पृष्ठ-संख्या
५९(५७५)	७.४.४	५.४.२९	यं त्रायध्वे	१२	वसिष्ठः	१–११ मरुतः; १२ रुद्रः (मृत्युविमोचनी)	१; ३; ५ बृहती; २; ४; ६ सतोबृहती; ७; ८ त्रिष्टुप्; ९–११ गायत्री; १२ अनुष्टुप्	४०७
६०(५७६)	७.४.५	५.५.१	यदद्य सूर्यं	१२	,,	१सूर्यः; २–१२ मित्रावरुणौ	त्रिष्टुप्	४११
६१(५७७)	७.४.६	५.५.३	उद्वां चक्षुः	७	,,	मित्रावरुणौ	,,	४१४
६२(५७८)	७.४.७	५.५.४	उत्सूर्यः	६	,,	१–३ सूर्यः; ४–६ मित्रावरुणौ	,,	४१६
६३(५७९)	७.४.८	५.५.५	उद्वेति	६	,,	१–५[१] सूर्यः; ५[२]; ६ मित्रावरुणौ	,,	४१८
६४(५८०)	७.४.९	५.५.६	दिवि क्षयन्ता	६ ५	,,	मित्रावरुणौ	,,	४२०
६५(५८१)	७.४.१०	५.५.७	प्रति वां	६ ५	,,	,,	,,	४२२
६६(५८२)	७.४.११	५.५.८	प्र मित्रयोः	१९	,,	१–३ मित्रावरुणौ; ४–१३ आदित्याः; १४–१६ सूर्यः; १७–१९ मित्रावरुणौ	१–९ गायत्री; १०; १२; १४बृहती; ११; १३; १५; सतोबृहती; १६पुरउष्णिक्; १७–१९ गायत्री	४२३
६७(५८३)	७.४.१२	५.५.१२	प्रति वां रथं	१०	,,	अश्विनौ	त्रिष्टुप्	४२८
६८(५८४)	७.४.१३	५.५.१४	आ शुभ्रा	९	,,	,,	१–७ विराट्; ८; ९ त्रिष्टुप्	४३१
६९(५८५)	७.४.१४	५.५.१६	आ वां रथः	८	,,	,,	त्रिष्टुप्	४३४
७०(५८६)	७.४.१५	५.५.१७	आ विश्ववारा	७	,,	,,	,,	४३६
७१(५८७)	७.५.१	५.५.१८	अप स्वसुः	६	,,	,,	,,	४३९

७२(५८८)	७.५.२	५.५.१९	आ गोमता	५	,,	,,	,,	४४०
७३(५८९)	७.५.३	५.५.२०	अतारिष्म	५	,,	,,	,,	४४२
७४(५९०)	७.५.४	५.५.२१	इमा उ वां	६	,,	,,	प्रागाथम्	४४४
७५(५९१)	७.५.५	५.५.२२	व्यु१षाः	८	,,	उषाः	त्रिष्टुप्	४४५
७६(५९२)	७.५.६	५.५.२३	उदु ज्योतिः	७	,,	,,	,,	४४८
७७(५९३)	७.५.७	५.५.२४	उपो रुरुचे	६	,,	,,	,,	४५०
७८(५९४)	७.५.८	५.५.२५	प्रति केतवः	५	,,	,,	,,	४५२
७९(५९५)	७.५.९	५.५.२६	व्यु१षा आवः	५	,,	,,	,,	४५३
८०(५९६)	७.५.१०	५.५.२७	प्रति स्तोमेभिः	३	,,	,,	,,	४५५
८१(५९७)	७.५.११	५.६.१	प्रत्यु अदर्शि	६	,,	,,	प्रागाथम्	४५६
८२(५९८)	७.५.१२	५.६.२	इन्द्रावरुणा	१०	,,	इन्द्रावरुणौ	जगती	४५७
८३(५९९)	७.५.१३	५.६.४	युवां नरा	१०	,,	,,	,,	४६१
८४(६००)	७.५.१४	५.६.६	आ वां राजानौ	५	,,	,,	त्रिष्टुप्	४६४
८५(६०१)	७.५.१५	५.६.७	पुनीषे वाम्	५	,,	,,	,,	४६५
८६(६०२)	७.५.१६	५.६.८	धीरा त्वस्य	८	,,	वरुणः	,,	४६७
८७(६०३)	७.५.१७	५.६.९	रदापथः	७	,,	,,	,,	४७०
८८(६०४)	७.५.१८	५.६.१०	प्र शुन्ध्युवं	७	,,	,,	,,	४७२
८९(६०५)	७.५.१९	५.६.११	मो षु वरुण	५	,,	,,	१–४ गायत्री; ५ जगती	४७४
९०(६०६)	७.६.१	५.६.१२	प्र वीरया	७	,,	१–४ वायुः; ५–७ इन्द्र-वायू	त्रिष्टुप्	४७६
९१(६०७)	७.६.२	५.६.१३	कुविदङ्ग	७	,,	१; ३ वायुः; २; ४–७ इन्द्रवायू	,,	४७८
९२(६०८)	७.६.३	५.६.१४	आ वायो	५	,,	१; ३–५ वायुः; २ इन्द्र-वायू	,,	४८१
९३(६०९)	७.६.४	५.६.१५	शुचिं नु	८	,,	इन्द्राग्नी	,,	४८२
९४(६१०)	७.६.५	५.६.१६	इयं वामस्य	१२	,,	,,	१–११ गायत्री; १२ अनुष्टुप्	४८५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ°-भागे पृष्ठ-संख्या
९५(६११)	७.६.६	५.६.१९	प्र क्षोदसा	६	वसिष्ठः	१; २; ४–६ सरस्वती; ३ सरस्वान्	त्रिष्टुप्	४८७
९६(६१२)	७.६.७	५.६.२०	बृहदु	६	,,	१–३ सरस्वती; ४–६ सरस्वान्	१ बृहती; २ सतोबृहती; ३ प्रस्तारपङ्क्तिः; ४–६ गायत्री	४९०
९७(६१३)	७.६.८	५.६.२१	यज्ञे दिवः	१०	,,	१ इन्द्रः; २; ४–८ बृहस्पतिः; ३; ९इन्द्राब्रह्मणस्पती; १० इन्द्राबृहस्पती	त्रिष्टुप्	४९१
९८(६१४)	७.६.९	५.६.२३	अध्वर्यवः	७	,,	१–६ इन्द्रः; ७ इन्द्राबृहस्पती	,,	४९५
९९(६१५)	७.६.१०	५.६.२४	परो मात्रया	७	,,	१–३; ७ विष्णुः; ४–६ इन्द्राविष्णू	,,	४९७
१००(६१६)	७.६.११	५.६.२५	नू मर्तः	७	,,	विष्णुः	,,	४९९
१०१(६१७)	७.६.१२	५.७.१	तिस्रो वाचः	६	वसिष्ठः कुमारो वाग्नेयः	पर्जन्यः	,,	५०२
१०२(६१८)	७.६.१३	५.७.२	पर्जन्याय	३	,, ,, ,,	,,	गायत्री	५०५
१०३(६१९)	७.६.१४	५.७.३	संवत्सरं	१०	वसिष्ठः	मण्डूकाः	१ अनुष्टुप्; २–१० त्रिष्टुप्	५०५
१०४(६२०)	७.६.१५	५.७.५	इन्द्रासोमा	२५	,,	१–७; १५; २५ इन्द्रासोमौ रक्षोहणौ; ८; १६; १९–२२; २४ इन्द्रः; ९; १२; १३ सोमः; १०; १४ अग्निः; ११ देवाः; १७ ग्रावाणः; १८ मरुतः;	१–६; १८; २१; २३ जगती; ७ त्रिष्टुब्जगती वा; ८–१७; १९; २०; २२; २४ त्रिष्टुप्; २५ अनुष्टुप्	५०८

						२३¹ आशीः; २३² पृथिव्यन्तरिक्षे		
१(६२१)	८.१.१	५.७.१०	मा चित्	३४	१; २ प्रगाथो घौरः काण्वो वा; ३–२९ मेधातिथिमेध्यातिथी काण्वौ; ३०–३३आसङ्गः प्लायोगिः; ३४ शश्वत्याङ्गिरसस्यासङ्गस्य पत्नी	१–२९ इन्द्रः; ३०–३३ (आसङ्गस्य) दानस्तुतिः; ३४ आसङ्गः	१; ३; ५–३२ बृहती; २; ४ सतोबृहती; ३३; ३४ त्रिष्टुप्	५१७
२(६२२)	८.१.२	५.७.१७	इदं वसो	४२	१–४०मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः; ४१; ४२ मेधातिथिः	१–४० इन्द्रः; ४१; ४२ (विभिन्दोः) दानस्तुतिः	१–२७; २९–४२ गायत्री; २८ अनुष्टुप्	५२८
३(६२३)	८.१.३	५.७.२५	पिबा सुतस्य	२४	मेध्यातिथिः काण्वः	१–२० इन्द्रः; २१–२४ (पाकस्थाम्नः कौरयाणस्य) दानस्तुतिः	१–२० प्रागाथम्; २१ अनुष्टुप्; २२; २३ गायत्री; २४ बृहती	५३८
४(६२४)	८.१.४	५.७.३०	यदिन्द्र	२१	देवातिथिः काण्वः	१–१४ इन्द्रः; १५–१८ इन्द्रः पूषा वा; १९–२१ (कुरुङ्गस्य) दानस्तुतिः	१–२० प्रगाथम्; २१ पुरउष्णिक्	५४६
५(६२५)	८.१.५	५.८.१	दूरादिहेव	३९	ब्रह्मातिथिः काण्वः	१–३७¹अश्विनौ;३७²–३९ (चैद्यस्य कशोः) दानस्तुतिः	१–३६गायत्री; ३७; ३८ बृहती; ३९ अनुष्टुप्	५५४
६(६२६)	८.२.१	५.८.९	महाँ इन्द्रो	४८	वत्सः काण्वः	१–४५ इन्द्रः; ४६–४८ (तिरिन्दिरस्य पार्शव्यस्य) दानस्तुतिः	गायत्री	५६४
७(६२७)	८.२.२	५.८.१८	प्र यद्वः	३६	पुनर्वत्सः काण्वः	मरुतः	,,	५७४
८(६२८)	८.२.३	५.८.२५	आ नो विश्वाभिः	२३	सध्वंसः काण्वः	अश्विनौ	अनुष्टुप्	५८२
९(६२९)	८.२.४	५.८.२९	आ नूनम्	२१	शशकर्णः काण्वः	,,	१; ४; ६; १४; १५बृहती; २; ३; २०; २१ गायत्री;	५८९

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ॰-भागे पृष्ठ-संख्या
							५ ककुप्; ७–९; १३; १६–१९ अनुष्टुप्; १० त्रिष्टुप्; ११विराट्; १२ जगती	
१०(६३०)	८.२.५	५.८.३४	यत् स्थः	६	प्रगाथः काण्वः	अश्विनौ	१ बृहती; २त्रिष्टुप् (मध्येज्योतिः); ३ अनुष्टुप्; ४ आस्तारपङ्क्तिः; ५बृहती; ६ सतोबृहती	५९५
११(६३१)	८.२.६	५.८.३५	त्वमग्ने	१०	वत्सः काण्वः	अग्निः	१(प्रतिष्ठा) गायत्री; २ (वर्धमाना) गायत्री; ३–९ गायत्री; १० त्रिष्टुप्	५९७
१२(६३२)	८.२.७	६.१.१	य इन्द्र	३३	पर्वतः काण्वः	इन्द्रः	उष्णिक्	५९९
१३(६३३)	८.३.१	६.१.७	इन्द्रः सुतेषु	३३	नारदः काण्वः	,,	,,	६०८
१४(६३४)	८.३.२	६.१.१४	यदिन्द्र	१५	गोषूक्त्यश्वसूक्तिनौ काण्वायनौ	,,	गायत्री	६१५
१५(६३५)	८.३.३	६.१.१७	तम्वभि	१३	,, ,,	,,	उष्णिक्	६१८
१६(६३६)	८.३.४	६.१.२०	प्र सम्राजं	१२	इरिम्बिठिः काण्वः	,,	गायत्री	६२१
१७(६३७)	८.३.५	६.१.२२	आ याहि	१५	,, ,,	,,	१–१३ गायत्री; १४; १५ प्रागाथम्	६२४
१८(६३८)	८.३.६	६.१.२५	इदं ह	२२	,, ,,	१–७; १०–२२आदित्याः; ८ अश्विनौ; ९ अग्निसूर्यानिलाः	उष्णिक्	६२७
१९(६३९)	८.३.७	६.१.२९	तं गूर्धय	३७	सोभरिः काण्वः	१–३३ अग्निः; ३४; ३५	१–२६; २८–३३	६३२

						आदित्याः; ३६; ३७ (त्रसदस्योः) दानस्तुतिः	प्रागाथं काकुभम्; २७ द्विपदा विराट्; ३४ उष्णिक्; ३५ सतोबृहती; ३६ ककुप्; ३७ पङ्क्तिः;	
२०(६४०)	८.३.८	६.१.३६	आ गन्ता	२६	,, ,,	मरुतः	प्रागाथं काकुभम्	६४२
२१(६४१)	८.४.१	६.२.१	वयमु	१८	,, ,,	१–१६ इन्द्रः; १७; १८ (चित्रस्य) दानस्तुतिः	,, ,,	६४९
२२(६४२)	८.४.२	६.२.५	ओ त्यम्	१८	,, ,,	अश्विनौ	१–६ प्रागाथम्; ७ बृहती; ८ अनुष्टुप्; ९ १० प्रागाथं काकुभम्; ११ ककुप्; १२ मध्येज्योतिः (त्रिष्टुप्); १३–१८ प्रागाथं काकुभम्	६५५
२३(६४३)	८.४.३	६.२.९	ईळिष्व	३०	विश्वमना वैयश्वः	अग्निः	उष्णिक्	६६०
२४(६४४)	८.४.४	६.२.१५	सखायः	३०	,, ,,	१–२७ इन्द्रः; २८–३० (वरोः सौषाम्णस्य) दानस्तुतिः	१–२९ उष्णिक्; ३० अनुष्टुप्	६६६
२५(६४५)	८.४.५	६.२.२१	ता वां	२४	,, ,,	१–९; १३–२४ मित्रावरुणौ; १०–१२ विश्वे देवाः	१–२२; २४ उष्णिक्; २३ उष्णिग्गर्भा	६७५
२६(६४६)	८.४.६	६.२.२६	युवोरु	२५	विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः	१–१९ अश्विनौ; २०–२५ वायुः	१–१५; २२–२४ उष्णिक्; १६–१९; २१; २५ गायत्री; २० अनुष्टुप्	६८१
२७(६४७)	८.४.७	६.२.३०	अग्निरुक्थे	२२	मनुर्वैवस्वतः	विश्वे देवाः	प्रागाथम्	६८७
२८(६४८)	८.४.८	६.२.३५	ये त्रिंशति	५	,,	,, ,,	१–३; ५ गायत्री; ४ पुरउष्णिक्	६९४
२९(६४९)	८.४.९	६.२.३६	बभ्रुरेकः	१०	मनुर्वैवस्वतः कश्यपो वा मारीचः	,, ,,	द्विपदा	६९६

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	तृ॰ भागे पृष्ठसंख्या
३०(६५०)	८.४.१०	६.२.३७	नहि वः	४	मनुर्वैवस्वतः	विश्वे देवाः	१ गायत्री; २पुरउष्णिक्; ३ बृहती; ४ अनुष्टुप्	६९८
३१(६५१)	८.५.१	६.२.३८	यो यजाति	१८	,,	१–४इज्यास्तवो यजमानप्रशंसा च; ५–९ दंपती १०–१८ दंपत्योराशिषः	१–८; ११–१३ गायत्री; ९; १४ अनुष्टुप्; १० पादनिचृत्; १५–१८ पङ्क्तिः	६९९
३२(६५२)	८.५.२	६.३.४	प्र कृतानि	३०	मेधातिथिः काण्वः	इन्द्रः	गायत्री	७०४
३३(६५३)	८.५.३	६.३.७	वयं घ	१९	मेध्यातिथिः ,,	,,	१–१५ बृहती; १६–१८ गायत्री; १९ अनुष्टुप्	७१०
३४(६५४)	८.५.४	६.३.११	एन्द्र याहि	१८	१–१५नीपातिथिः काण्वः; १६–१८ सहस्रं वसुरोचिषोऽङ्गिरसः	,,	१–१५ अनुष्टुप्; १६–१८ गायत्री	७१५
३५(६५५)	८.५.५	६.४.१४	अग्निना	२४	श्यावाश्व आत्रेयः	अश्विनौ	१–२१ उपरिष्टाज्ज्योतिः; २२; २४ पङ्क्तिः; २३ महाबृहती	७१९
३६(६५६)	८.५.६	६.३.१८	अवितासि	७	,, ,,	इन्द्रः	१–६ शक्करी; ७ महापङ्क्तिः	७२५
३७(६५७)	८.५.७	६.३.१९	प्रेदं	७	,, ,,	,,	१ अतिजगती; २–७ महापङ्क्तिः	७२६
३८(६५८)	८.५.८	६.३.२०	यज्ञस्य	१०	,, ,,	इन्द्राग्नी	गायत्री	७२८
३९(६५९)	८.५.९	६.३.२२	अग्निमस्तोषि	१०	नाभाकः काण्वः	अग्निः	महापङ्क्तिः	७३०
४०(६६०)	८.५.१०	६.३.२४	इन्द्राग्नी	१२	,, ,,	इन्द्राग्नी	१; ३–११ महापङ्क्तिः; २ शक्करी; १२ त्रिष्टुप्	७३३

४१(६६१)	८.५.११	६.३.२६	अस्मा ऊ षु	१०	,, ,,	वरुणः	महापङ्क्तिः	७३७
४२(६६२)	८.५.१२	६.३.२८	अस्तभ्नात्	६	नाभाकः काण्वः अर्चनाना वा	१–३ वरुणः; ४–६ अश्विनौ	१–३ त्रिष्टुप्; ४–६ अनुष्टुप्	७४०
४३(६६३)	८.६.१	६.३.२९	इमे विप्रस्य	३३	विरूप आङ्गिरसः	अग्निः	गायत्री	७४२
४४(६६४)	८.६.२	६.३.३६	समिधाग्निं	३०	,, ,,	,,	,,	७४७
४५(६६५)	८.६.३	६.३.४२	आ घा ये	४२	त्रिशोकः काण्वः	१ इन्द्राग्नी; २–४२ इन्द्रः	,,	७५२
४६(६६६)	८.६.४	६.४.१	त्वावतः	३३	वशोऽश्व्यः	१–२०; २९–३१; ३३ इन्द्रः; २१–२४ (पृथुश्रवसः कानीतस्य) दानस्तुतिः; २५–२८; ३२ वायुः	१ पादनिचृत्; २–४ गायत्री; ५ ककुप्; ६ गायत्री; ७ बृहती; ८ अनुष्टुप्; ९ सतोबृहती; १० गायत्री; ११ बृहती; १२ विपरीता सतोबृहती; १३ द्विपदा; १४ बृहती पिपीलिकमध्या; १५ ककुम्न्यङ्कुशिरा; १६ विराट्; १७ जगती; १८; उपरिष्टाद्बृहती; १९ बृहती; २० विषमपदा बृहती; २१; २२ पङ्क्तिः; २३ गायत्री; २४पङ्क्तिः; २५; २७ बृहती; २६; २८ सतोबृहती; २९ गायत्री; ३० द्विपदा विराट्; ३१ उष्णिक्; ३२ पङ्क्तिः; ३३ गायत्री	७५९
४७(६६७)	८.६.५	६.४.७	महि वः	१८	त्रित आप्त्यः	१–१३ आदित्याः; १४–१८ आदित्या उषाश्च	महापङ्क्तिः	७६८

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ°-भागे पृष्ठ-संख्या
४८(६६८)	८.६.६	६.४.११	स्वादोः	१५	प्रगाथः काण्वः	सोमः	१–४; ६–१५ त्रिष्टुप्; ५ जगती	७७४
अथ वालखिल्यम्								
१(४९)	८.६.७	६.४.१४	अभि प्र	१०	प्रस्कण्वः काण्वः	इन्द्रः	प्रागाथम्	७७९
२(५०)	८.६.८	६.४.१६	प्र सु श्रुतं	१०	पुष्टिगुः काण्वः	,,	,,	७८३
३(५१)	८.६.९	६.४.१८	यथा मनौ सांवरणौ	१०	श्रुष्टिगुः काण्वः	,,	,,	७८६
४(५२)	८.६.१०	६.४.२०	यथा मनौ विवस्वति	१०	आयुः काण्वः	,,	,,	७८९
५(५३)	८.६.११	६.४.२२	उपमं त्वा	८	मेध्यः काण्वः	,,	,,	७९२
६(५४)	८.६.१२	६.४.२४	एतत्ते	८	मातरिश्वा काण्वः	१; २; ५–८ इन्द्रः; ३; ४ विश्वे देवाः	,,	७९५
७(५५)	८.६.१३	६.४.२६	भूरीदिन्द्रस्य	५	कृशः काण्वः	(प्रस्कण्वस्य) दानस्तुतिः	१; २; ४ गायत्री; ३; ५ अनुष्टुप्	७९७
८(५६)	८.६.१४	६.४.२७	प्रति ते	५	पृषध्रः काण्वः	१–४ (प्रस्कण्वस्य) दानस्तुतिः; ५ अग्निसूर्यौ	१–४ गायत्री; ५ पङ्क्तिः	७९९
९(५७)	८.६.१५	६.४.२८	युवं देवा	४	मेध्यः काण्वः	अश्विनौ	त्रिष्टुप्	८००
१०(५८)	८.६.१६	६.४.२९	यमृत्विजः	३	*	*	,,	८०२
११(५९)	८.६.१७	६.४.३०	इमानि वां	७	सुपर्णः काण्वः	इन्द्रावरुणौ	जगती	८०३
इति वालखिल्यम्								

*५८ सूक्तविषये सर्वानुक्रमसूत्रं नास्ति। ५७; ५८ सूक्तयोर्देवते बृहद्देवतायां न निर्दिष्टे।

६०(६६९)	८.७.१	६.४.३२	अग्न आ याहि	२०	भर्गः प्रागाथः	अग्निः	प्रागाथम्	८०६
६१(६७०)	८.७.२	६.४.३६	उभयं	१८	,, ,,	इन्द्रः	,,	८११
६२(६७१)	८.७.३	६.४.४०	प्रो अस्मै	१२	प्रगाथः काण्वः	,,	१–६; १०–१२ पङ्क्तिः; ७–९ बृहती	८१७
६३(६७२)	८.७.४	६.४.४२	स पूर्व्यः	१२	,, ,,	१–११ इन्द्रः; १२ देवाः	१; ४; ५; ७ अनुष्टुप्; २; ३; ६; ८–११गायत्री; १२ त्रिष्टुप्	८२०
६४(६७३)	८.७.५	६.४.४४	उत् त्वा	१२	,, ,,	इन्द्रः	गायत्री	८२३
६५(६७४)	८.७.६	६.४.४६	यदिन्द्र	१२	,, ,,	,,	,,	८२५
६६(६७५)	८.७.७	६.४.४८	तरोभिर्वः	१५	कलिः प्रागाथः	,,	१–१४ प्रागाथम्; १५ अनुष्टुप्	८२७
६७(६७६)	८.७.८	६.४.५१	त्यान्नु	२१	मत्स्यः सांमदो मैत्रावरुणि-र्मान्यो वा बहवो वा मत्स्या जालनद्धाः	आदित्याः	गायत्री	८३२
६८(६७७)	८.७.९	६.५.१	आ त्वा रथं	१९	प्रियमेध आङ्गिरसः	१–१३ इन्द्रः; १४–१९ (ऋक्षाश्वमेधयोः) दान-स्तुतिः	१; ४; ७; १० अनुष्टुप्; २; ३; ५; ६; ८; ९; ११–१९ गायत्री	८३७
६९(६७८)	८.७.१०	६.५.५	प्रप्र वः	१८	,, ,,	१–१०; १३–१८ इन्द्रः; ११[1] विश्वे देवाः; ११[2]; १२ वरुणः	१; ३; ७–१०; १२–१५ अनुष्टुप्; २ उष्णिक्; ४–६ गायत्री; ११; १६ पङ्क्तिः १७; १८ बृहती	८४१
७०(६७९)	८.८.१	६.५.८	यो राजा	१५	पुरुहन्मा आङ्गिरसः	इन्द्रः	१–६ प्रागाथम्; ७–१२ बृहती; १३ उष्णिक्; १४ अनुष्टुप्; १५ पुरउष्णिक्	८४६
७१(६८०)	८.८.२	६.५.११	त्वं नो अग्ने	१५	सुदीतिपुरुमीळ्हौ आङ्गि-रसौ तयोर्वा अन्यतरः	अग्निः	१–९ गायत्री; १०–१५ प्रागाथम्	८५१
७२(६८१)	८.८.३	६.५.१४	हविष्कृणुध्वम्	१८	हर्यतः प्रागाथः	अग्निर्हविषां स्तुतिर्वा	गायत्री	८५५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ०-भागे पृष्ठ-संख्या
७३(६८२)	८.८.४	६.५.१७	उदीराथाम्	१८	गोपवन आत्रेयः सप्तवध्रिर्वा	अश्विनौ	गायत्री	८५९
७४(६८३)	८.८.५	६.५.२१	विशोविशो वः	१५	गोपवन आत्रेयः	१–१२ अग्निः; १३–१५ (श्रुतर्वण आर्क्ष्यस्य) दानस्तुतिः	१; ४; ७; १०; १३–१५ अनुष्टुप्; २; ३; ५; ६; ८; ९; ११; १२ गायत्री	८६२
७५(६८४)	८.८.६	६.५.२४	युक्ष्वा हि	१६	विरूप आङ्गिरसः	अग्निः	गायत्री	८६६
७६(६८५)	८.८.७	६.५.२७	इमं नु	१२	कुरुसुतिः काण्वः	इन्द्रः	,,	८६९
७७(६८६)	८.८.८	६.५.२९	जज्ञानः	११	,, ,,	,,	१–९ गायत्री; १० बृहती; ११ सतोबृहती	८७१
७८(६८७)	८.८.९	६.५.३१	पुरोळाशं	१०	,, ,,	,,	१–९ गायत्री; १० बृहती	८७४
७९(६८८)	८.८.१०	६.५.३३	अयं कृत्नुः	९	कृत्नुर्भार्गवः	सोमः	१–८ गायत्री; ९ अनुष्टुप्	८७७
८०(६८९)	८.८.११	६.५.३५	नह्य१न्यं	१०	एकद्यूर्नौधसः	१–९ इन्द्रः; १० देवाः	१–९ गायत्री; १० त्रिष्टुप्	८७९
८१(६९०)	८.९.१	६.५.३७	आ तू नः	९	कुसीदी काण्वः	इन्द्रः	गायत्री	८८१
८२(६९१)	८.९.२	६.६.१	आ प्र द्रव	९	,, ,,	,,	,,	८८३
८३(६९२)	८.९.३	६.६.३	देवानाम्	९	,, ,,	विश्वे देवाः	,,	८८६
८४(६९३)	८.९.४	६.६.५	प्रेष्ठं	९	उशना काव्यः	अग्निः	,,	८८८
८५(६९४)	८.९.५	६.६.७	आ मे हवम्	९	कृष्ण आङ्गिरसः	अश्विनौ	,,	८९०
८६(६९५)	८.९.६	६.६.९	उभा हि	५	कृष्णो विश्वको वा कार्ष्णिः	,,	जगती	८९२
८७(६९६)	८.९.७	६.६.१०	द्युम्नी वां	६	कृष्णो द्युम्नीको वासिष्ठो वा प्रियमेध आङ्गिरसो वा	,,	प्रागाथम्	८९३
८८(६९७)	८.९.८	६.६.११	तं वो दस्मम्	६	नोधाः	इन्द्रः	,,	८९६
८९(६९८)	८.९.९	६.६.१२	बृहदिन्द्राय	७	नृमेधपुरुमेधौ	,,	१–४ प्रागाथम्; ५; ६ अनुष्टुप्; ७ बृहती	८९८

९०(६९९)	८.९.१०	६.६.१३	आ नो विश्वासु	६	,,	,,	प्रागाथम्	९०१
९१(७००)	८.९.११	६.६.१४	कन्या३वाः	७	अपाला आत्रेयी	,,	१; २ पङ्क्तिः; ३–७ अनुष्टुप्	९०३
९२(७०१)	८.९.१२	६.६.१५	पान्तमा	३३	श्रुतकक्षः सुकक्षो वा	,,	१ अनुष्टुप्; २–३३ गायत्री	९०६
९३(७०२)	८.९.१३	६.६.२१	उद्घेदभि	३४	सुकक्ष आङ्गिरसः	१–३३ इन्द्रः; ३४ इन्द्र ऋभवश्च	गायत्री	९१४
९४(७०३)	८.१०.१	६.६.२८	गौर्धयति	१२	बिन्दुराङ्गिरसः पूतदक्षो वा	मरुतः	,,	९२३
९५(७०४)	८.१०.२	६.६.३०	आ त्वा	९	तिरश्चीराङ्गिरसः	इन्द्रः	अनुष्टुप्	९२५
९६(७०५)	८.१०.३	६.६.३२	अस्मै	२१	तिरश्चीर्द्युतानो वा मारुतः	१–१४³; १६–२१ इन्द्रः; १४⁴ मरुतः; १५ इन्द्राबृहस्पती	१–३; ५–२१ त्रिष्टुप्; ४ विराट्	९२८
९७(७०६)	८.१०.४	६.६.३६	या इन्द्र	१५	रेभः काश्यपः	इन्द्रः	१–९ बृहती; १०; १३ अतिजगती; ११; १२ उपरिष्टाद्बृहती; १४ त्रिष्टुप्; १५ जगती	९३७
९८(७०७)	८.१०.५	६.७.१	इन्द्राय	१२	नृमेधः	,,	१–६; ८ उष्णिक्; ७; १०; ११ककुप्; ९; १२ पुरउष्णिक्	९४३
९९(७०८)	८.१०.६	६.७.३	त्वामिदा	८	,,	,,	प्रागाथम्	९४६
१००(७०९)	८.१०.७	६.७.४	अयं ते	१२	१–३; ६–१२ नेमो भार्गवः; ४; ५ इन्द्रः	१–९; १२ इन्द्रः; १०; ११ वाक्	१–५; १०–१२ त्रिष्टुप्; ६ जगती; ७–९ अनुष्टुप्	९४९
१०१(७१०)	८.१०.८	६.७.६	ऋधक्	१६	१–१६ जमदग्निर्भार्गवः	१–५³ मित्रावरुणौ; ५⁴; ६ आदित्याः; ७; ८ अश्विनौ; ९; १० वायुः ११; १२ सूर्यः; १३ उषाः सूर्यप्रभा वा; १४ पवमानः; १५; १६ गौः	१; २ प्रागाथम्; ३ गायत्री; ४ सतोबृहती; ५–१२ प्रागाथम्; १३ बृहती; १४–१६ त्रिष्टुप्	९५३

सूक्तम्	मण्डलानु-वाक-सूक्तानि	अष्टका-ध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	तृ०-भागे पृष्ठ-संख्या
१०२(७११)	८.१०.९	६.७.९	त्वमग्ने	२२	प्रयोगो भार्गवः अग्निर्वा पावको बार्हस्पत्यः अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः	अग्निः	गायत्री	९५८
१०३(७१२)	८.१०.१०	६.७.१३	अदर्शि	१४	सोभरिः काण्वः	१–१३ अग्निः; १४ अग्निर्मरुतश्च	१–४; ६ बृहती; ५ विराड्रूपा; ७; ९; ११; १३; सतोबृहती; ८; १२ ककुप्; १० ह्रसीयसी (गायत्री); १४ अनुष्टुप्	९६२
								चतुर्थ-भागे
१(७१३)	९.१.१	६.७.१६	स्वादिष्ठया	१०	मधुच्छन्दाः (वैश्वामित्रः)	पवमानः सोमः	गायत्री	१
२(७१४)	९.१.२	६.७.१८	पवस्व	१०	मेधातिथिः काण्वः	,,	,,	३
३(७१५)	९.१.३	६.७.२०	एष देवो	१०	शुनःशेप आजीगर्तिः	,,	,,	४
४(७१६)	९.१.४	६.७.२२	सना च	१०	हिरण्यस्तूप आङ्गिरसः	,,	,,	६
५(७१७)	९.१.५	६.७.२४	समिद्धो	११	असितः काश्यपो देवलो वा	आप्रियः	१–७ गायत्री; ८–११ अनुष्टुप्	८
६(७१८)	९.१.६	६.७.२६	मन्द्रया	९	,, ,,	पवमानः सोमः	गायत्री	१०
७(७१९)	९.१.७	६.७.२८	असृग्रम्	९	,, ,,	,,	,,	१२
८(७२०)	९.१.८	६.७.३०	एते सोमाः	९	,, ,,	,,	,,	१३
९(७२१)	९.१.९	६.७.३२	परि प्रिया	९	,, ,,	,,	,,	१५
१०(७२२)	९.१.१०	६.७.३४	प्र स्वानासः	९	,, ,,	,,	,,	१६
११(७२३)	९.१.११	६.७.३६	उपास्मै	९	,, ,,	,,	,,	१८
१२(७२४)	९.१.१२	६.७.३८	सोमा असृग्रम्	९	,, ,,	,,	,,	१९
१३(७२५)	९.१.१३	६.८.१	सोमः पुनानः	९	,, ,,	,,	,,	२१

१४(७२६)	९.१.१४	६.८.३	परि प्र	८	„ „	„	„	२३
१५(७२७)	९.१.१५	६.८.५	एष धिया	८	„ „	„	„	२५
१६(७२८)	९.१.१६	६.८.६	प्र ते सोतारः	८	„ „	„	„	२६
१७(७२९)	९.१.१७	६.८.७	प्र निम्नेनेव	८	„ „	„	„	२८
१८(७३०)	९.१.१८	६.८.८	परि सुवानः	७	„ „	„	„	२९
१९(७३१)	९.१.१९	६.८.९	यत् सोम चित्रम्	७	„ „	„	„	३१
२०(७३२)	९.१.२०	६.८.१०	प्र कविः	७	„ „	„	„	३२
२१(७३३)	९.१.२१	६.८.११	एते धावन्ति	७	„ „	„	„	३३
२२(७३४)	९.१.२२	६.८.१२	एते सोमासः	७	„ „	„	„	३४
२३(७३५)	९.१.२३	६.८.१३	सोमा असृग्रम्	७	„ „	„	„	३६
२४(७३६)	९.१.२४	६.८.१४	प्र सोमासः	७	„ „	„	„	३७
२५(७३७)	९.२.१	६.८.१५	पवस्व	६	दृळ्हच्युत आगस्त्यः	„	„	३८
२६(७३८)	९.२.२	६.८.१६	तमसृक्षन्त	६	इध्मवाहो दार्ढच्युतः	„	„	३९
२७(७३९)	९.२.३	६.८.१७	एष कविः	६	नृमेधः	„	„	४०
२८(७४०)	९.२.४	६.८.१८	एष वाजी	६	प्रियमेधः	„	„	४१
२९(७४१)	९.२.५	६.८.१९	प्रास्य धाराः	६	नृमेधः	„	„	४२
३०(७४२)	९.२.६	६.८.२०	प्र धाराः	६	बिन्दुः	„	„	४३
३१(७४३)	९.२.७	६.८.२१	प्र सोमासः	६	गोतमः	„	„	४५
३२(७४४)	९.२.८	६.८.२२	„	६	श्यावाश्वः	„	„	४६
३३(७४५)	९.२.९	६.८.२३	प्र सोमासः	६	त्रितः	„	„	४७
३४(७४६)	९.२.१०	६.८.२४	प्र सुवानः	६	„	„	„	४८
३५(७४७)	९.२.११	६.८.२५	आ नः पवस्व	६	प्रभूवसुः	„	„	४९
३६(७४८)	९.२.१२	६.८.२६	असर्जि	६	„	„	„	५०
३७(७४९)	९.२.१३	६.८.२७	स सुतः	६	रहूगणः	„	„	५१
३८(७५०)	९.२.१४	६.८.२८	एष उ स्यः	६	„	„	„	५२
३९(७५१)	९.२.१५	६.८.२९	आशुरर्षं	६	बृहन्मतिः	„	„	५४
४०(७५२)	९.२.१६	६.८.३०	पुनानः	६	„	„	„	५५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठ-संख्या
४१(७५३)	९.२.१७	६.८.३१	प्र ये गावः	६	मेध्यातिथिः	पवमानः सोमः	गायत्री	५६
४२(७५४)	९.२.१८	६.८.३२	जनयन्	६	,,	,,	,,	५७
४३(७५५)	९.२.१९	६.८.३३	यो अत्यइव	६	,,	,,	,,	५८
४४(७५६)	९.२.२०	७.१.१	प्र णः	६	अयास्यः	,,	,,	६१
४५(७५७)	९.२.२१	७.१.२	स पवस्व	६	,,	,,	,,	६२
४६(७५८)	९.२.२२	७.१.३	असृग्रन्	६	,,	,,	,,	६३
४७(७५९)	९.२.२३	७.१.४	अया सोमः	५	कविर्भार्गवः	,,	,,	६४
४८(७६०)	९.२.२४	७.१.५	तं त्वा	५	,,	,,	,,	६५
४९(७६१)	९.२.२५	७.१.६	पवस्व	५	,,	,,	,,	६६
५०(७६२)	९.२.२६	७.१.७	उत्ते शुष्मासः	५	उचथ्यः	,,	,,	६७
५१(७६३)	९.२.२७	७.१.८	अध्वर्यो	५	,,	,,	,,	६८
५२(७६४)	९.२.२८	७.१.९	परि द्युक्षः	५	,,	,,	,,	६८
५३(७६५)	९.२.२९	७.१.१०	उत्ते शुष्मासो	४	अवत्सारः	,,	,,	६९
५४(७६६)	९.२.३०	७.१.११	अस्य प्रत्नाम्	४	,,	,,	,,	७०
५५(७६७)	९.२.३१	७.१.१२	यवंयवं	४	,,	,,	,,	७१
५६(७६८)	९.२.३२	७.१.१३	परि सोमः	४	,,	,,	,,	७१
५७(७६९)	९.२.३३	७.१.१४	प्र ते धाराः	४	,,	,,	,,	७२
५८(७७०)	९.२.३४	७.१.१५	तरत्स मन्दी	४	,,	,,	,,	७३
५९(७७१)	९.२.३५	७.१.१६	पवस्व	४	,,	,,	,,	७४
६०(७७२)	९.२.३६	७.१.१७	प्र गायत्रेण	४	,,	,,	१; २; ४ गायत्री; ३ पुरउष्णिक्	७४
६१(७७३)	९.३.१	७.१.१८	अया वीती	३०	अमहीयुः	,,	,,	७५
६२(७७४)	९.३.२	७.१.२४	एते असृग्रम्	३०	जमदग्निः	,,	,,	८०

६३(७७५)	९.३.३	७.१.३०	आ पवस्व	३०	निध्रुविः काश्यपः	,,	,,	८४
६४(७७६)	९.३.४	७.१.३६	वृषा सोम	३०	कश्यपः	,,	,,	८९
६५(७७७)	९.३.५	७.२.१	हिन्वन्ति	३०	भृगुर्वारुणिर्जमदग्निर्वा	,,	,,	९४
६६(७७८)	९.३.६	७.२.७	पवस्व	३०	शतं वैखानसाः	१–१८ पवमानः सोमः; १९–२१अग्निः; २२–३० पवमानः सोमः	१–१७; १९–३०गायत्री; १८ अनुष्टुप्	१००
६७(७७९)	९.३.७	७.२.१३	त्वं सोमासि	३२	१–३ भरद्वाजः; ४–६ कश्यपः; ७–९ गोतमः; १०–१२अत्रिः; १३–१५ विश्वामित्रः; १६–१८ जमदग्निः; १९–२१ वसिष्ठः; २२–३२ पवित्रो वसिष्ठो वोभौ वा	१–९; १३–२२; २८–३० पवमानः सोमः; १०–१२ पूषा वा; २३; २४ अग्निः; २५ अग्निः सविता वा; २६ अग्निः अथवा अग्निः सविता च; २७ अग्निर्विश्वे देवा वा; ३१; ३२ पावमान्यध्येतृस्तुतिः	१–१५; १९–२६; २८; २९ गायत्री; १६–१८ द्विपदा गायत्री; २७; ३१; ३२ अनुष्टुप्; ३० पुरउष्णिक्	१०७
६८(७८०)	९.४.१	७.२.१९	प्र देवम्	१०	वत्सप्रिर्भालन्दनः	पवमानः सोमः	१–९ जगती; १० त्रिष्टुप्	११४
६९(७८१)	९.४.२	७.२.२१	इषुर्न	१०	हिरण्यस्तूपः	,,	१–८ जगती; ९; १० त्रिष्टुप्	११८
७०(७८२)	९.४.३	७.२.२३	त्रिरस्मै	१०	रेणुर्वैश्वामित्रः	,,	१–९ जगती; १० त्रिष्टुप्	१२२
७१(७८३)	९.४.४	७.२.२५	आ दक्षिणा	९	ऋषभो वैश्वामित्रः	,,	१–८ जगती; ९ त्रिष्टुप्	१२६
७२(७८४)	९.४.५	७.२.२७	हरिं मृजन्ति	९	हरिमन्त आङ्गिरसः	,,	जगती	१३०
७३(७८५)	९.४.६	७.२.२९	स्रक्के	९	पवित्रः	,,	,,	१३३
७४(७८६)	९.४.७	७.२.३१	शिशुर्न	९	कक्षीवान्	,,	१–७; ९ जगती; ८ त्रिष्टुप्	१३७
७५(७८७)	९.४.८	७.२.३३	अभि प्रियाणि	५	कविः	,,	जगती	१४०
७६(७८८)	९.४.९	७.३.१	धर्ता दिवः	५	,,	,,	,,	१४२
७७(७८९)	९.४.१०	७.३.२	एष प्र कोशे	५	,,	,,	,,	१४४
७८(७९०)	९.४.११	७.३.३	प्र राजा	५	,,	,,	,,	१४६

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठसंख्या
७९(७९१)	९.४.१२	७.३.४	अचोदसः	५	कविः	पवमानः सोमः	जगती	१४७
८०(७९२)	९.४.१३	७.३.५	सोमस्य धारा	५	वसुर्भारद्वाजः	,,	,,	१४९
८१(७९३)	९.४.१४	७.३.६	प्र सोमस्य	५	,,	,,	,,	१५१
८२(७९४)	९.४.१५	७.३.७	असावि सोमः	५	,,	,,	१–४ जगती; ५ त्रिष्टुप्	१५२
८३(७९५)	९.४.१६	७.३.८	पवित्रं ते	५	पवित्रः	,,	जगती	१५४
८४(७९६)	९.४.१७	७.३.९	पवस्व	५	प्रजापतिर्वाच्यः	,,	,,	१५६
८५(७९७)	९.४.१८	७.३.१०	इन्द्राय सोम	१२	वेनो भार्गवः	,,	१–१० जगती; ११; १२ त्रिष्टुप्	१५७
८६(७९८)	९.५.१	७.३.१२	प्र त आशवः	४८	१–१० अकृष्टा माषाः; ११–२० सिकता निवावरी; २१–३० पृश्नयोऽजाः; ३१–४० अकृष्टमाषादयस्त्रयः; ४१–४५ अत्रिः; ४६–४८गृत्समदः	,,	जगती	१६१
८७(७९९)	९.५.२	७.३.२२	प्र तु द्रव	९	उशना	,,	त्रिष्टुप्	१७६
८८(८००)	९.५.३	७.३.२४	अयं सोमः	८	,,	,,	,,	१७९
८९(८०१)	९.५.४	७.३.२५	प्रो स्य वह्निः	७	,,	,,	,,	१८१
९०(८०२)	९.५.५	७.३.२६	प्र हिन्वानः	६	वसिष्ठः	,,	,,	१८३
९१(८०३)	९.५.६	७.४.१	असर्जि	६	कश्यपः	,,	,,	१८५
९२(८०४)	९.५.७	७.४.२	परि सुवानः	६	,,	,,	,,	१८७
९३(८०५)	९.५.८	७.४.३	साकमुक्षः	५	नोधाः	,,	,,	१८९
९४(८०६)	९.५.९	७.४.४	अधि यत्	५	कण्वः	,,	,,	१९१
९५(८०७)	९.५.१०	७.४.५	कनिक्रन्ति	५	प्रस्कण्वः	,,	,,	१९३

९६(८०८)	९.५.११	७.४.६	प्र सेनानीः	२४	प्रतर्दनः दैवोदासिः	,,	,,	१९५
९७(८०९)	९.६.१	७.४.११	अस्य प्रेषा	५८	१–३ वसिष्ठः; ४–६ इन्द्रप्रमतिर्वासिष्ठः; ७–९ वृषगणो वासिष्ठः;१०–१२ मन्युर्वासिष्ठः; १३–१५ उपमन्युर्वासिष्ठः;१६–१८ व्याघ्रपाद्वासिष्ठः;१९–२१ शक्तिर्वासिष्ठः; २२–२४ कर्णश्रुद्वासिष्ठः; २५–२७ मृळीको वासिष्ठः;२८–३० वसुक्रो वासिष्ठः;३१–४४ पराशरः; ४५–५८ कुत्सः	,,	,,	२०३
९८(८१०)	९.६.२	७.४.२३	अभि नः	१२	अम्बरीष ऋजिश्वा च	,,	१–१०; १२ अनुष्टुप् ;११ बृहती	२२२
९९(८११)	९.६.३	७.४.२५	आ हर्यताय	८	रेभसूनू काश्यपौ	,,	१ बृहती; २–८ अनुष्टुप्	२२६
१००(८१२)	९.६.४	७.४.२७	अभी नवन्ते	९	,, ,,	,,	अनुष्टुप्	२२८
१०१(८१३)	९.६.५	७.५.१	पुरोजिती	१६	१–३अन्धीगुः श्यावाश्विः; ४–६ ययातिर्नाहुषः; ७–९ नहुषो मानवः; १०–१२ मनुः सांवरणः; १३–१६ प्रजापतिः	,,	१; ४–१६ अनुष्टुप् ; २; ३ गायत्री	२३१
१०२(८१४)	९.६.६	७.५.४	क्राणा	८	त्रितः	,,	उष्णिक्	२३५
१०३(८१५)	९.६.७	७.५.६	प्र पुनानाय	६	द्वित आप्त्यः	,,	,,	२३७
१०४(८१६)	९.७.१	७.५.७	सखायः	६	पर्वतनारदौ शिखण्डिन्यौ वा काश्यप्यावप्सरसौ	,,	,,	२३८
१०५(८१७)	९.७.२	७.५.८	तं वः	६	पर्वतनारदौ	,,	,,	२४०

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठ-संख्या
१०६(८१८)	९.७.३	७.५.९	इन्द्रमच्छ	१४	१–३ अग्निश्चाक्षुषः; ४–६ चक्षुर्मानवः; ७–९ मनुराप्सवः; १०–१४ अग्निः	पवमानः सोमः	उष्णिक्	२४१
१०७(८१९)	९.७.४	७.५.१२	परीतः	२६	सप्तर्षयः	,,	प्रागाथम् ; ३; १६ द्विपदा; ८–१० बृहती	२४४
१०८(८२०)	९.७.५	७.५.१७	पवस्व	१६	१; २ गौरिवीतिः; ३ शक्तिः; ४; ५ ऊरुः; ६; ७ ऋजिश्वा; ८; ९ ऊर्ध्वसद्मा; १०; ११ कृतयशाः; १२; १३ ऋणंचयः; १४–१६ शक्तिः	,,	काकुभः प्रगाथाः; १३ गायत्री यवमध्या	२५१
१०९(८२१)	९.७.६	७.५.२०	परि प्र	२२	अग्नयो धिष्ण्या ऐश्वराः	,,	द्विपदा	२५६
११०(८२२)	९.७.७	७.५.२२	पर्यू षु	१२	त्र्यरुणत्रसदस्यू	,,	१–३ अनुष्टुप् पिपीलिकमध्यमा; ४–९ ऊर्ध्वबृहती; १०–१२ विराट्	२५९
१११(८२३)	९.७.८	७.५.२४	अया रुचा	३	अनानतः पारुच्छेपिः	,,	अत्यष्टिः	२६३
११२(८२४)	९.७.९	७.५.२५	नानानं	४	शिशुराङ्गिरसः	,,	पङ्क्तिः	२६४
११३(८२५)	९.७.१०	७.५.२६	शर्यणावति	११	कश्यपः	,,	,,	२६६
११४(८२६)	९.७.११	७.५.२८	य इन्दोः	४	,,	,,	,,	२६९
१(८२७)	१०.१.१	७.५.२९	अग्रे बृहन्	७	त्रितः	अग्निः	त्रिष्टुप्	२७१
२(८२८)	१०.१.२	७.५.३०	पिप्रीहि	७	,,	,,	,,	२७४
३(८२९)	१०.१.३	७.५.३१	इनो राजन्	७	,,	,,	,,	२७६

४(८३०)	१०.१.४	७.५.३२	प्र ते यक्षि	७	,,	,,	,,	२७९
५(८३१)	१०.१.५	७.५.३३	एकः समुद्रः	७	,,	,,	,,	२८१
६(८३२)	१०.१.६	७.६.१	अयं स यस्य	७	,,	,,	,,	२८५
७(८३३)	१०.१.७	७.६.२	स्वस्ति नो	७	,,	,,	,,	२८७
८(८३४)	१०.१.८	७.६.३	प्र केतुना	९	त्रिशिरास्त्वाष्ट्रः	१–६ अग्निः; ७–९ इन्द्रः	,,	२८९
९(८३५)	१०.१.९	७.६.५	आपो हि	९	त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीप आम्बरीषो वा	आपः	१–४; ६ गायत्री; ५ वर्धमाना; ७ प्रतिष्ठा; ८; ९ अनुष्टुप्	२९३
१०(८३६)	१०.१.१०	७.६.६	ओ चित्	१४	१; ३; ५–७; ११; १३ यमी वैवस्वती; २; ४; ८–१०; १२; १४ यमो वैवस्वतः	१; ३; ५–७; ११; १३ यमो वैवस्वतः; २; ४; ८–१०; १२; १४ यमी वैवस्वती	त्रिष्टुप्	२९४
११(८३७)	१०.१.११	७.६.९	वृषा	९	हविर्धान आङ्गिः	अग्निः	१–६ जगती; ७–९ त्रिष्टुप्	२९९
१२(८३८)	१०.१.१२	७.६.११	द्यावा	९	,, ,,	,,	त्रिष्टुप्	३०३
१३(८३९)	१०.१.१३	७.६.१३	युजे वां	५	विवस्वान् आदित्यः	हविर्धानम्	१–४ त्रिष्टुप्; ५ जगती	३०६
१४(८४०)	१०.१.१४	७.६.१४	परेयिवांसं	१६	यमः	१–५; १३–१६ यमः; ६ लिङ्गोक्तदेवताः; ७–९ लिङ्गोक्तदेवताः पितरो वा; १०–१२ श्वानौ	१–१२ त्रिष्टुप्; १३; १४; १६ अनुष्टुप्; १५ बृहती	३०८
१५(८४१)	१०.१.१५	७.६.१७	उदीरताम्	१४	शङ्खो यामायनः	पितरः	१–१०; १२–१४ त्रिष्टुप्; ११ जगती	३१३
१६(८४२)	१०.१.१६	७.६.२०	मैनम्	१४	दमनो यामायनः	अग्निः	१–१० त्रिष्टुप्; ११–१४ अनुष्टुप्	३१८
१७(८४३)	१०.२.१	७.६.२३	त्वष्टा दुहित्रे	१४	देवश्रवा यामायनः	१; २ सरण्यूः; ३–६ पूषा; ७–९ सरस्वती; १०; १४ आपः; ११–१३ आपः सोमो वा	१–१२ त्रिष्टुप्; १३ अनुष्टुप् पुरस्ताद्बृहती वा; १४ अनुष्टुप्	३२३

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठसंख्या
१८(८४४)	१०.२.२	७.६.२६	परं मृत्यो	१४	संकुसुको यामायनः	१–४ मृत्युः; ५ धाता; ६ त्वष्टा; ७–१३ पितृमेधः; १४ पितृमेधः प्रजापतिर्वा	१–१०; १२ त्रिष्टुप्; ११ प्रस्तारपङ्क्तिः; १३ जगती; १४ अनुष्टुप्	३२८
१९(८४५)	१०.२.३	७.७.१	नि वर्तध्वं	८	मथितो यामायनः भृगुर्वा वारुणिः च्यवनो वा भार्गवः	१[१]; २–८ आपो गावो वा; १[२] अग्नीषोमौ	१–५; ७; ८ अनुष्टुप्; ६ गायत्री	३३४
२०(८४६)	१०.२.४	७.७.२	भद्रं	१०	विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः	अग्निः (१ शान्त्यर्थः)	१ एकपदा; २ अनुष्टुप्; ३–८ गायत्री; ९ विराट्; १० त्रिष्टुप्	३३६
२१(८४७)	१०.२.५	७.७.४	आग्निं न	८	,, ,,	अग्निः	आस्तारपङ्क्तिः	३३९
२२(८४८)	१०.२.६	७.७.६	कुह	१५	,, ,,	इन्द्रः	१–४; ६; ८; १०–१४ पुरस्ताद्बृहती; ५; ७; ९ अनुष्टुप्; १५ त्रिष्टुप्	३४२
२३(८४९)	१०.२.७	७.७.९	यजामहे	७	,, ,,	,,	१; ७ त्रिष्टुप्; ५ अभिसारिणी; २–४; ६ जगती	३४७
२४(८५०)	१०.२.८	७.७.१०	इन्द्र सोमम्	६	,, ,,	१–३ इन्द्रः; ४–६ अश्विनौ	१–३ आस्तारपङ्क्तिः; ४–६ अनुष्टुप्	३४९
२५(८५१)	१०.२.९	७.७.११	भद्रं	११	,, ,,	सोमः	आस्तारपङ्क्तिः	३५१
२६(८५२)	१०.२.१०	७.७.१३	प्र हि	९	,, ,,	पूषा	१; ४ उष्णिक्; २; ३; ५–९ अनुष्टुप्	३५५
२७(८५३)	१०.२.११	७.७.१५	असत्सु	२४	वसुक्र ऐन्द्रः	इन्द्रः	त्रिष्टुप्	३५८
२८(८५४)	१०.२.१२	७.७.२०	विश्वो हि	१२	१ इन्द्रस्नुषा वसुक्रपत्नी;	२; ६; ८; १०; १२ ऐन्द्रो	,,	३६७

					२; ६; ८; १०; १२ इन्द्रः; ३; ४; ५; ७; ९; ११ ऐन्द्रो वसुक्रः	वसुक्रः; १; ३; ४; ५; ७; ९; ११ इन्द्रः		
२९(८५५)	१०.२.१३	७.७.२२	वने न	८	वसुक्रः	इन्द्रः	त्रिष्टुप्	३७१
३०(८५६)	१०.३.१	७.७.२४	प्र देवत्रा	१५	कवष ऐलूषः	आपोऽपां नपाद्वा	,,	३७५
३१(८५७)	१०.३.२	७.७.२७	आ नः	११	,,	विश्वे देवाः	,,	३८०
३२(८५८)	१०.३.३	७.७.२९	प्र सु ग्मन्ता	९	,,	,,	१–५ जगती; ६–९ त्रिष्टुप्	३८४
३३(८५९)	१०.३.४	७.८.१	प्र मा	९	,,	१ विश्वे देवाः; २; ३ इन्द्रः; ४; ५ कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः; ६–९ उपमश्रवा मित्रातिथिपुत्रः	१ त्रिष्टुप्; २; ३ प्रागाथः; ४–९ गायत्री	३८८
३४(८६०)	१०.३.५	७.८.३	प्रावेपाः	१४	कवष ऐलूषः अक्षो वा मौजवान्	१; ७; ९; १२; १३ अक्षकृषिप्रशंसा; २–६; ८; १०; ११; १४ अक्षकितवनिन्दा	१–६; ८–१४ त्रिष्टुप्; ७ जगती	३९१
३५(८६१)	१०.३.६	७.८.४	अबुध्रम्	१४	लुशो धानाकः	विश्वे देवाः	१–१२ जगती; १३; १४ त्रिष्टुप्	३९५
३६(८६२)	१०.३.७	७.८.९	उषासानक्ता	१४	,,	,,	१–१२ जगती; १३; १४ त्रिष्टुप्	३९९
३७(८६३)	१०.३.८	७.८.१२	नमो मित्रस्य	१२	अभितपाः सौर्यः	सूर्यः	१–९; ११; १२ जगती; १० त्रिष्टुप्	४०३
३८(८६४)	१०.३.९	७.८.१४	अस्मिन्नः	५	इन्द्रो मुष्कवान्	इन्द्रः	जगती	४०७
३९(८६५)	१०.३.१०	७.८.१५	यो वां	१४	घोषा काक्षीवती	अश्विनौ	१–१३ जगती; १४ त्रिष्टुप्	४०९
४०(८६६)	१०.३.११	७.८.१८	रथं यान्तं	१४	,,	,,	जगती	४१३
४१(८६७)	१०.३.१२	७.८.२१	समानमु	३	सुहस्त्यो घौषेयः	,,	,,	४१८
४२(८६८)	१०.३.१३	७.८.२२	अस्तेव	११	कृष्णः	इन्द्रः	त्रिष्टुप्	४१९

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठसंख्या
४३(८६९)	१०.४.१	७.८.२४	अच्छा मे	११	कृष्णः	इन्द्रः	१–९ जगती; १०; ११ त्रिष्टुप्	४२२
४४(८७०)	१०.४.२	७.८.२६	आ यातु	११	,,	,,	१–३; १०; ११ त्रिष्टुप्; ४–९ जगती	४२५
४५(८७१)	१०.४.३	७.८.२८	दिवस्परि	१२	वत्सप्रिः	अग्निः	त्रिष्टुप्	४२९
४६(८७२)	१०.४.४	८.१.१	प्र होता	१०	,,	,,	,,	४३५
४७(८७३)	१०.४.५	८.१.३	जगृभ्मा	८	सप्तगुः	इन्द्रो वैकुण्ठः	,,	४३८
४८(८७४)	१०.४.६	८.१.५	अहं भुवं	११	इन्द्रो वैकुण्ठः	,,	१–६; ८; ९ जगती; ७; १०; ११ त्रिष्टुप्	४४१
४९(८७५)	१०.४.७	८.१.७	अहं दां	११	,,	,,	१; ३–१० जगती; २; ११ त्रिष्टुप्	४४५
५०(८७६)	१०.४.८	८.१.९	प्र वो महे	७	,,	,,	१; २; ६; ७ जगती; ३; ४ अभिसारिणी; ५त्रिष्टुप्	४४९
५१(८७७)	१०.४.९	८.१.१०	महत्तत्	९	१; ३; ५; ७; ९ देवाः; २; ४; ६; ८; अग्निः सौचीकः	१; ३; ५; ७; ९ अग्निः सौचीकः; २; ४; ६; ८ देवाः	त्रिष्टुप्	४५२
५२(८७८)	१०.४.१०	८.१.१२	विश्वे देवाः	६	अग्निः सौचीकः	देवाः	,,	४५५
५३(८७९)	१०.४.११	८.१.१३	यमैच्छाम	११	१–३; ६–११ देवाः; ४; ५ अग्निः सौचीकः	१–३; ६–११ अग्निः सौचीकः; ४; ५ देवाः	१–५; ८ त्रिष्टुप्; ६; ७; ९–११ जगती	४५७
५४(८८०)	१०.४.१२	८.१.१५	तां सु	६	बृहदुक्थो वामदेव्यः	इन्द्रः	त्रिष्टुप्	४६२
५५(८८१)	१०.४.१३	८.१.१६	दूरे तन्नाम	८	,,	,,	,,	४६४
५६(८८२)	१०.४.१४	८.१.१८	इदं ते	७	,,	विश्वे देवाः	१–३; ७ त्रिष्टुप्; ४–६ जगती	४६७

५७(८८३)	१०.४.१५	८.१.१९	मा प्र गाम	६	बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपायनाः	,,	गायत्री	४७०
५८(८८४)	१०.४.१६	८.१.२०	यत्ते यमं	१२	,,	मनआवर्तनम्	अनुष्टुप्	४७१
५९(८८५)	१०.४.१७	८.१.२२	प्र तार्यायुः	१०	,,	१–३ निर्ऋतिः; ४ निर्ऋतिः सोमश्च; ५; ६ असुनीतिः; ७ लिङ्गोक्तदेवताः; ८; ९; १०[२] द्यावापृथिवी; १०[१] द्यावापृथिवी इन्द्रो वा	१–७ त्रिष्टुप्; ८ पङ्क्तिः; ९ महापङ्क्तिः; १० पङ्क्त्युत्तरा	४७४
६०(८८६)	१०.४.१८	८.१.२४	आ जनं	१२	१–५; ७–१२ बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपायनाः; ६ अगस्त्यस्य स्वसैषां माता	१–४; ६ असमातिः; ५ इन्द्रः; ७–११ सुबन्धुजीवाह्वानम्; १२ सुबन्धोर्लब्धसंज्ञस्य स्पर्शनम्	१–५ गायत्री; ६; ७; १०–१२ अनुष्टुप्; ८; ९ पङ्क्ति	४७७
६१(८८७)	१०.५.१	८.१.२६	इदमित्था	२७	नाभानेदिष्ठो मानवः	विश्वे देवाः	त्रिष्टुप्	४८०
६२(८८८)	१०.५.२	८.२.१	ये यज्ञेन	११	,,	१–६ विश्वे देवाः अङ्गिरसो वा; ७ विश्वे देवाः; ८–११ सावर्णेर्दानस्तुतिः	१–४ जगती; ५; ८; ९ अनुष्टुप्; ६ बृहती; ७ सतोबृहती; १० गायत्री; ११ त्रिष्टुप्	४९१
६३(८८९)	१०.५.३	८.२.३	परावतो ये	१७	गयः प्लातः	१–१४; १७ विश्वे देवाः; १५; १६ पथ्या स्वस्तिः	१–१४ जगती; १५ जगती त्रिष्टुब्वा; १६; १७ त्रिष्टुप्	४९४
६४(८९०)	१०.५.४	८.२.६	कथा देवानां	१७	,,	विश्वे देवाः	१–११; १३–१५ जगती; १२; १६; १७ त्रिष्टुप्	५०१
६५(८९१)	१०.५.५	८.२.९	अग्निरिन्द्रो	१५	वसुकर्णो वासुक्रः	,,	१–१४ जगती; १५ त्रिष्टुप्	५०६
६६(८९२)	१०.५.६	८.२.१२	देवान् हुवे	१५	,,	,,	१–१४ जगती; १५ त्रिष्टुप्	५१२
६७(८९३)	१०.५.७	८.२.१५	इमां धियं	१२	अयास्यः	बृहस्पतिः	त्रिष्टुप्	५१७
६८(८९४)	१०.५.८	८.२.१७	उदप्रुतो न	१२	,,	,,	,,	५२१
६९(८९५)	१०.६.१	८.२.१९	भद्रा अग्नेः	१२	सुमित्रो वाध्र्यश्वः	अग्निः	१; २ जगती; ३–१२ त्रिष्टुप्	५२५

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठ-संख्या
७०(८९६)	१०.६.२	८.२.२१	इमां मे	११	सुमित्रो वाध्र्यश्वः	आप्रियः	त्रिष्टुप्	५२९
७१(८९७)	१०.६.३	८.२.२३	बृहस्पते	११	बृहस्पतिः	ज्ञानम्	१–८; १०; ११ त्रिष्टुप्; ९ जगती	५३२
७२(८९८)	१०.६.४	८.३.१	देवानां	९	बृहस्पतिर्बृहस्पतिर्वा लौक्यः अदितिर्वा दाक्षायणी	देवाः	अनुष्टुप्	५३७
७३(८९९)	१०.६.५	८.३.३	जनिष्ठा उग्रः	११	गौरिवीतिः	इन्द्रः	त्रिष्टुप्	५४०
७४(९००)	१०.६.६	८.३.५	वसूनां वा	६	”	”	”	५४४
७५(९०१)	१०.६.७	८.३.६	प्र सु	९	सिन्धुक्षित् प्रैयमेधः	नद्यः	जगती	५४६
७६(९०२)	१०.६.८	८.३.८	आ व ऋञ्जसे	८	जरत्कर्ण ऐरावतः सर्पः	ग्रावाणः	जगती	५४९
७७(९०३)	१०.६.९	८.३.१०	अभ्रप्रुषो न	८	स्यूमरश्मिर्भार्गवः	मरुतः	१; ४; ६–८ त्रिष्टुप्; ५ जगती	५५२
७८(९०४)	१०.६.१०	८.३.१२	विप्रासो न	८	”	”	१; ३; ४; ८ त्रिष्टुप्; २; ५–७ जगती	५५४
७९(९०५)	१०.६.११	८.३.१४	अपश्यम्	७	अग्निः सौचीको वैश्वानरो वा सप्तिर्वा वाजंभरः	अग्निः	त्रिष्टुप्	५५७
८०(९०६)	१०.६.१२	८.३.१५	अग्निः सप्तिं	७	”	”	”	५६०
८१(९०७)	१०.६.१३	८.३.१६	य इमा	७	विश्वकर्मा भौवनः	विश्वकर्मा	”	५६२
८२(९०८)	१०.६.१४	८.३.१७	चक्षुषः	७	” ”	”	”	५६५
८३(९०९)	१०.६.१५	८.३.१८	यस्ते मन्यो	७	मन्युस्तापसः	मन्युः	१ जगती; २–७ त्रिष्टुप्	५६८
८४(९१०)	१०.६.१६	८.३.१९	त्वया मन्यो	७	”	”	१–३ त्रिष्टुप्; ४–७ जगती	५७०
८५(९११)	१०.७.१	८.३.२०	सत्येनोत्तभिता	४७	सूर्या सावित्री	१–५ सोमः; ६–१६ सूर्याविवाहः; १७ देवाः;	१–१३; १५–१७; २२; २५; २८–३३; ३५;	५७२

						१८ सोमार्कौ; १९ चन्द्रमाः; २०–२८ नृणां विवाहमन्त्रा आशिषश्च; २९; ३० वधूवासःसंस्पर्शनिन्दा; ३१ दंपत्योः यक्ष्मनाशिनी; ३२–४७ सूर्या	३८–४२; ४५–४७ अनुष्टुप्; १४; १९–२१; २३; २४; २६; ३६; ३७; ४४; त्रिष्टुप्; १८; २७; ४३ जगती; ३४ उरोबृहती	
८६(९१२)	१०.७.२	८.४.१	वि हि सोतो°	२३	वृषाकपिरिन्द्राणीन्द्रश्च समूदिरे	इन्द्रः	पङ्क्तिः	५८८
८७(९१३)	१०.७.३	८.४.५	रक्षोहणं	२५	पायुः	अग्नी रक्षोहा	१–२१ त्रिष्टुप्; २२–२५ अनुष्टुप्	५९५
८८(९१४)	१०.७.४	८.४.१०	हविष्पान्तम्	१९	मूर्धन्वान् आङ्गिरसो वामदेव्यो वा	सूर्यवैश्वानरौ	त्रिष्टुप्	६०३
८९(९१५)	१०.७.५	८.४.१४	इन्द्रं स्तवा	१८	रेणुः	१–४; ६–१८ इन्द्रः; ५ इन्द्रासोमौ	"	६०९
९०(९१६)	१०.७.६	८.४.१७	सहस्रशीर्षा	१६	नारायणः	पुरुषः	१–१५ अनुष्टुप्; १६ त्रिष्टुप्	६१४
९१(९१७)	१०.८.१	८.४.२०	सं जागृवद्भिः	१५	अरुणो वैतहव्यः	अग्निः	१–१४ जगती; १५ त्रिष्टुप्	६२०
९२(९१८)	१०.८.२	८.४.२३	यज्ञस्य	१५	शार्यातो मानवः	विश्वे देवाः	जगती	६२५
९३(९१९)	१०.८.३	८.४.२६	महि द्यावा°	१५	तान्वः पार्थ्यः	"	१; ४–८; १०; १२; १४ प्रस्तारपङ्क्तिः; २; ३; १३ अनुष्टुप्; ९ अक्षरैः पङ्क्तिः; ११ न्यङ्कुसारिणी; १५ पुरस्ताद्बृहती	६३०
९४(९२०)	१०.८.४	८.४.२९	प्रैते वदन्तु	१४	अर्बुदः काद्रवेयः सर्पः	ग्रावाणः	१–४; ६; ८–१३ जगती ५; ७; १४ त्रिष्टुप्	६३४

सूक्तम्	मण्डलानु-वाक-सूक्तानि	अष्टका-ध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थ-भागे पृष्ठ-संख्या
९५(९२१)	१०.८.५	८.५.१	हये जाये	१८	१; ३; ६; ८–१०; १२; १४; १७ पुरूरवा ऐळः; २; ४; ५; ७; ११; १३; १५; १६; १८ उर्वशी	१; ३; ६; ८–१०; १२; १४; १७ उर्वशी; २; ४; ५; ७; ११; १३; १५; १६; १८ पुरूरवा ऐळः	त्रिष्टुप्	६३९
९६(९२२)	१०.८.६	८.५.५	प्र ते महे	१३	बरुः सर्वहरिर्वैन्द्रः	हरिस्तुतिः	१–११ जगती; १२; १३ त्रिष्टुप्	६४७
९७(९२३)	१०.८.७	८.५.८	या ओषधीः	२३	भिषगाथर्वणः	ओषधयः	अनुष्टुप्	६५२
९८(९२४)	१०.८.८	८.५.१२	बृहस्पते	१२	देवापिरार्ष्टिषेणः	देवाः	त्रिष्टुप्	६५८
९९(९२५)	१०.८.९	८.५.१४	कं नश्चित्रम्	१२	वम्रो वैखानसः	इन्द्रः	,,	६६२
१००(९२६)	१०.९.१	८.५.१६	इन्द्र दृह्य	१२	दुवस्युर्वान्दनः	विश्वे देवाः	१–११ जगती; १२त्रिष्टुप्	६६६
१०१(९२७)	१०.९.२	८.५.१८	उद्बुध्यध्वं	१२	बुधः सौम्यः	विश्वे देवा ऋत्विजो वा	१–३; ७; ८; १०; ११ त्रिष्टुप्; ४; ६ गायत्री; ५ बृहती; ९; १२ जगती	६७०
१०२(९२८)	१०.९.३	८.५.२०	प्र ते रथं	१२	मुद्गलो भार्म्यश्वः	द्रुघण इन्द्रो वा	१; ३; १२ बृहती; २; ४–११ त्रिष्टुप्	६७५
१०३(९२९)	१०.९.४	८.५.२२	आशुः शिशानो	१३	अप्रतिरथ ऐन्द्रः	१–३; ५–११ इन्द्रः; ४ बृहस्पतिः; १२ अप्वा; १३ इन्द्रो मरुतो वा	१–१२ त्रिष्टुप्; १३ अनुष्टुप्	६७९
१०४(९३०)	१०.९.५	८.५.२४	असावि सोमः	११	अष्टको वैश्वामित्रः	इन्द्रः	त्रिष्टुप्	६८३
१०५(९३१)	१०.९.६	८.५.२६	कदा वसो	११	कौत्सो दुर्मित्रः सुमित्रो वा	,,	१ उष्णिग्गायत्री वा; २; ७ पिपीलिकमध्या; ३–६; ८–१० उष्णिक्; ११ त्रिष्टुप्	६८७

१०६(९३२)	१०.९.७	८.६.१	उभा उ नूनं	११	भूतांशः काश्यपः	अश्विनौ	त्रिष्टुप्	६९२
१०७(९३३)	१०.९.८	८.६.३	आविरभूत्	११	दिव्यो दक्षिणा वा प्राजापत्या	दक्षिणा तद्दातारो वा	१–३; ५–११ त्रिष्टुप्; ४ जगती	६९८
१०८(९३४)	१०.९.९	८.६.५	किमिच्छन्ती	११	१; ३; ५; ७; ९ पणयोऽसुराः; २; ४; ६; ८; १०; ११ सरमा देवशुनी	१; ३; ५; ७; ९ सरमा; २; ४; ६; ८; १०; ११ पणयः	त्रिष्टुप्	७०२
१०९(९३५)	१०.९.१०	८.६.७	तेऽवदन्	७	जुहूर्ब्रह्मजाया ऊर्ध्वनाभा वा ब्राह्मः	विश्वे देवाः	१–५ त्रिष्टुप्; ६; ७ अनुष्टुप्	७०७
११०(९३६)	१०.९.११	८.६.८	समिद्धो अद्य	११	जमदग्निः तत्सुतो वा रामः	आप्रियः	त्रिष्टुप्	७१०
१११(९३७)	१०.९.१२	८.६.१०	मनीषिणः	१०	अष्टादंष्ट्रो वैरूपः	इन्द्रः	”	७१४
११२(९३८)	१०.९.१३	८.६.१२	इन्द्र पिब	१०	नभःप्रभेदनो वैरूपः	”	”	७१८
११३(९३९)	१०.१०.१	८.६.१४	तमस्य द्यावापृथिवी	१०	शतप्रभेदनो वैरूपः	”	१–९ जगती; १० त्रिष्टुप्	७२१
११४(९४०)	१०.१०.२	८.६.१६	घर्मा समन्ता	१०	सध्रिर्वैरूपः घर्मो वा तापसः	विश्वे देवाः	१–३; ५–१० त्रिष्टुप्; ४ जगती	७२५
११५(९४१)	१०.१०.३	८.६.१८	चित्र इत्	९	उपस्तुतो वार्ष्टिहव्यः	अग्निः	१–७ जगती; ८ त्रिष्टुप्; ९ शक्वरी	७२९
११६(९४२)	१०.१०.४	८.६.२०	पिबा सोमं	९	स्थौरः अग्नियुतः अग्नियूपो वा	इन्द्रः	त्रिष्टुप्	७३३
११७(९४३)	१०.१०.५	८.६.२२	न वा उ	९	भिक्षुः	धनान्नदानप्रशंसा	१; २जगती; ३–९त्रिष्टुप्	७३७
११८(९४४)	१०.१०.६	८.६.२४	अग्ने हसि	९	उरुक्षय आमहीयवः	अग्नी रक्षोहा	गायत्री	७४१
११९(९४५)	१०.१०.७	८.६.२६	इति वा इति	१३	लब ऐन्द्रः	लब ऐन्द्रः	”	७४३
१२०(९४६)	१०.१०.८	८.७.१	तदिदास	९	बृहद्दिव आथर्वणः	इन्द्रः	त्रिष्टुप्	७४६
१२१(९४७)	१०.१०.९	८.७.३	हिरण्यगर्भः	१०	हिरण्यगर्भः प्राजापत्यः	कः	”	७५०
१२२(९४८)	१०.१०.१०	८.७.५	वसुं न	८	चित्रमहा वासिष्ठः	अग्निः	१; ५ त्रिष्टुप्; २–४; ६–८ जगती	७५५
१२३(९४९)	१०.१०.११	८.७.७	अयं वेनः	८	वेनः	वेनः	त्रिष्टुप्	७५९

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठ-संख्या
१२४(९५०)	१०.१०.१२	८.७.९	इमं नो	९	१; ५–९ अग्निवरुण-सोमाः; २–४ अग्निः	१–४ अग्निः; ५–८ यथानिपातम्; ९ इन्द्रः	१–६; ८; ९ त्रिष्टुप्; ७ जगती	७६२
१२५(९५१)	१०.१०.१३	८.७.११	अहं रुद्रेभिः	८	वागाम्भृणी	वागाम्भृणी	१; ३–८ त्रिष्टुप्; २ जगती	७६५
१२६(९५२)	१०.१०.१४	८.७.१३	न तमंहो	८	कुल्मलबर्हिषः शैलूषिरंहोमुग्वा वामदेव्यः	विश्वे देवाः	१–७ उपरिष्टाद्बृहती; ८ त्रिष्टुप्	७६९
१२७(९५३)	१०.१०.१५	८.७.१४	रात्री व्यख्यदायती	८	कुशिकः सौभरो रात्रिर्वा भारद्वाजी	रात्रिः	गायत्री	७७१
१२८(९५४)	१०.१०.१६	८.७.१५	ममाग्ने	९	विहव्यः	विश्वे देवाः	१–८ त्रिष्टुप्; ९ जगती	७७३
१२९(९५५)	१०.११.१	८.७.१७	नासदासीत्	७	प्रजापतिः परमेष्ठी	भाववृत्तम्	त्रिष्टुप्	७७७
१३०(९५६)	१०.११.२	८.७.१८	यो यज्ञो	७	यज्ञः प्राजापत्यः	,,	१ जगती; २–७ त्रिष्टुप्	७८३
१३१(९५७)	१०.११.३	८.७.१९	अप प्राचः	७	सुकीर्तिः काक्षीवतः	१–३; ६; ७ इन्द्रः; ४; ५ अश्विनौ	१–३; ५–७ त्रिष्टुप्; ४ अनुष्टुप्	७८७
१३२(९५८)	१०.११.४	८.७.२०	ईजानम्	७	शकपूतो नार्मेधः	१ लिङ्गोक्तदेवताः; २–७ मित्रावरुणौ	१ न्यङ्कुसारिणी; २; ६ प्रस्तारपङ्क्तिः; ३–५ विराड्रूपा; ८ महासतोबृहती	७९०
१३३(९५९)	१०.११.५	८.७.२१	प्रो ष्वस्मै	७	सुदाः पैजवनः	इन्द्रः	१–३ शक्वरी; ४–६ महापङ्क्तिः; ७ त्रिष्टुप्	७९३
१३४(९६०)	१०.११.६	८.७.२२	उभे यत्	७	१–६[१] मान्धाता यौवनाश्वः; ६[२]; ७ गोधा	,,	१–६ महापङ्क्तिः; ७ पङ्क्तिः	७९६
१३५(९६१)	१०.११.७	८.७.२३	यस्मिन् वृक्षे	७	कुमारो यामायनः	यमः	अनुष्टुप्	७९९

१३६(९६२)	१०.११.८	८.७.२४	केश्य१ग्निं	७	मुनयो वातरशनाः—१ जूतिः; २ वातजूतिः; ३ विप्रजूतिः; ४ वृषाणकः; ५ करिक्रतः; ६ एतशः; ७ ऋष्यशृङ्गः	केशिनः (अग्निसूर्यवायवः)	”	८०२
१३७(९६३)	१०.११.९	८.७.२५	उत देवाः	७	सप्त ऋषयः	विश्वे देवाः	”	८०४
१३८(९६४)	१०.११.१०	८.७.२६	तव त्ये	६	अङ्ग औरवः	इन्द्रः	जगती	८०७
१३९(९६५)	१०.११.११	८.७.२७	सूर्यरश्मिः	६	विश्वावसुर्देवगन्धर्वः	१–३ सविता; ४–६ विश्वावसुर्देवगन्धर्वः	त्रिष्टुप्	८०९
१४०(९६६)	१०.११.१२	८.७.२८	अग्ने तव	६	अग्निः पावकः	अग्निः	१ विष्टारपङ्क्तिः; २–४ सतोबृहती; ५ उपरिष्टाज्ज्योतिः; ६ त्रिष्टुप्	८१२
१४१(९६७)	१०.११.१३	८.७.२९	अग्ने अच्छा	६	अग्निस्तापसः	विश्वे देवाः	अनुष्टुप्	८१४
१४२(९६८)	१०.११.१४	८.७.३०	अयमग्ने	८	शार्ङ्गाः— १; २ जरिता; ३; ४ द्रोणः; ५; ६ सारिसृक्वः; ७; ८ स्तम्बमित्रः	अग्निः	१; २ जगती; ३–६ त्रिष्टुप्; ७; ८ अनुष्टुप्	८१६
१४३(९६९)	१०.११.१५	८.८.१	त्यं चित्	६	अत्रिः सांख्यः	अश्विनौ	अनुष्टुप्	८१९
१४४(९७०)	१०.११.१६	८.८.२	अयं हि	६	सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः	इन्द्रः	१; ३; ४ गायत्री; २ बृहती; ५ सतोबृहती; ६ विष्टारपङ्क्तिः	८२२
१४५(९७१)	१०.११.१७	८.८.३	इमां खनाम्योषधिं	६	इन्द्राणी	सपत्नीबाधनम् (उपनिषत्)	१–५ अनुष्टुप्; ६ पङ्क्तिः	८२४
१४६(९७२)	१०.११.१८	८.८.४	अरण्यानि	६	देवमुनिः ऐरंमदः	अरण्यानी	अनुष्टुप्	८२५
१४७(९७३)	१०.११.१९	८.८.५	श्रत्ते दधामि	५	सुवेदाः शैरीषिः	इन्द्रः	१–४ जगती; ५ त्रिष्टुप्	८२७
१४८(९७४)	१०.११.२०	८.८.६	सुष्वाणासः	५	पृथुर्वैन्यः	”	त्रिष्टुप्	८२९
१४९(९७५)	१०.११.२१	८.८.७	सविता	५	अर्चन् हैरण्यस्तूपः	सविता	”	८३१

सूक्तम्	मण्डलानुवाकसूक्तानि	अष्टकाध्यायवर्गाः	सूक्तस्य प्रतीकम्	मन्त्रसंख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठसंख्या
१५०(९७६)	१०.११.२२	८.८.८	समिद्धश्चित्	५	मृळीको वसिष्ठः	अग्निः	१–३ बृहती; ४ उपरिष्टाज्ज्योतिर्जगती वा; ५ उपरिष्टाज्ज्योतिः	८३३
१५१(९७७)	१०.११.२३	८.८.९	श्रद्धयाग्निः	५	श्रद्धा कामायनी	श्रद्धा	अनुष्टुप्	८३५
१५२(९७८)	१०.१२.१	८.८.१०	शास इत्था	५	शासो भारद्वाजः	इन्द्रः	,,	८३६
१५३(९७९)	१०.१२.२	८.८.११	ईङ्खयन्तीः	५	इन्द्रमातरो देवजामयः	,,	गायत्री	८३८
१५४(९८०)	१०.१२.३	८.८.१२	सोम एकेभ्यः	५	यमी	भाववृत्तम्	अनुष्टुप्	९३९
१५५(९८१)	१०.१२.४	८.८.१३	अरायि काणे	५	शिरिम्बिठो भारद्वाजः	१; ४ अलक्ष्मीघ्नम्; २ ३ ब्रह्मणस्पतिः; ५ विश्वे देवाः	,,	८४०
१५६(९८२)	१०.१२.५	८.८.१४	अग्निं हिन्वन्तु	५	केतुराग्नेयः	अग्निः	गायत्री	८४२
१५७(९८३)	१०.१२.६	८.८.१५	इमा नु कं	५	भुवन आप्त्यः साधनो वा भौवनः	विश्वे देवाः	द्विपदा त्रिष्टुप्	८४३
१५८(९८४)	१०.१२.७	८.८.१६	सूर्यो नो	५	चक्षुः सौर्यः	सूर्यः	गायत्री	८४४
१५९(९८५)	१०.१२.८	८.८.१७	उदसौ सूर्यो	६	शची पौलोमी	शची पौलोमी (आत्मानं तुष्टाव)	अनुष्टुप्	८४५
१६०(९८६)	१०.१२.९	८.८.१८	तीव्रस्य	५	पूरणो वैश्वामित्रः	इन्द्रः	त्रिष्टुप्	८४७
१६१(९८७)	१०.१२.१०	८.८.१९	मुञ्चामि त्वा	५	यक्ष्मनाशनः प्राजापत्यः	इन्द्रः (राजयक्ष्मघ्नम्)	१–४ त्रिष्टुप्; ५ अनुष्टुप्	८४९
१६२(९८८)	१०.१२.११	८.८.२०	ब्रह्मणाग्निः	६	रक्षोहा ब्राह्मः	गर्भसंस्रावे प्रायश्चित्तम्	अनुष्टुप्	८५१
१६३(९८९)	१०.१२.१२	८.८.२१	अक्षीभ्यां ते	६	विवृहा काश्यपः	यक्ष्मघ्नम्	,,	८५३
१६४(९९०)	१०.१२.१३	८.८.२२	अपेहि	५	प्रचेताः	दुःस्वप्नघ्नम्	१; २; ४ अनुष्टुप्; ३ त्रिष्टुप्; ५ पङ्क्तिः	८५५
१६५(९९१)	१०.१२.१४	८.८.२३	देवाः कपोतः	५	कपोतो नैर्ऋतः	विश्वे देवाः (कपोतोपहतौ प्रायश्चित्तम्)	त्रिष्टुप्	८५६

१६६(९९२)	१०.१२.१५	८.८.२४	ऋषभं मा	५	ऋषभो वैराजः शाक्वरो वा	सपत्नघ्नम्	१–४ अनुष्टुप्; ५ महापङ्क्तिः	८५८
१६७(९९३)	१०.१२.१६	८.८.२५	तुभ्येदम्	४	विश्वामित्रजमदग्नी	१; २; ४ इन्द्रः; ३ लिङ्गोक्तदेवताः	जगती	८६०
१६८(९९४)	१०.१२.१७	८.८.२६	वातस्य नु	४	अनिलो वातायनः	वायुः	त्रिष्टुप्	८६१
१६९(९९५)	१०.१२.१८	८.८.२७	मयोभूर्वातो	४	शबरः काक्षीवतः	गावः	,,	८६२
१७०(९९६)	१०.१२.१९	८.८.२८	विभ्राड्बृहत्	४	विभ्राट् सौर्यः	सूर्यः	१–३ जगती; ४आस्तारपङ्क्तिः	८६४
१७१(९९७)	१०.१२.२०	८.८.२९	त्वं त्यम्	४	इटो भार्गवः	इन्द्रः	गायत्री	८६५
१७२(९९८)	१०.१२.२१	८.८.३०	आ याहि	४	संवर्तः	उषाः	द्विपदा	८६६
१७३(९९९)	१०.१२.२२	८.८.३१	आ त्वाहार्षम्	६	ध्रुवः	राज्ञः स्तुतिः	अनुष्टुप्	८६७
१७४(१०००)	१०.१२.२३	८.८.३२	अभीवर्तेन	५	अभीवर्तः	,,	,,	८६९
१७५(१००१)	१०.१२.२४	८.८.३३	प्र वो ग्रावाणः	४	ऊर्ध्वग्रावार्बुदिः	ग्रावाणः	गायत्री	८७०
१७६(१००२)	१०.१२.२५	८.८.३४	प्र सूनवः	४	सूनुरार्भवः	१ ऋभवः; २–४ अग्निः	१; ३; ४ अनुष्टुप्; २ गायत्री	८७१
१७७(१००३)	१०.१२.२६	८.८.३५	पतङ्गमक्त॰	३	पतङ्गः प्राजापत्यः	मायाभेदः	१ जगती; २; ३; त्रिष्टुप्	८७२
१७८(१००४)	१०.१२.२७	८.८.३६	त्यमू षु	३	अरिष्टनेमिस्तार्क्ष्यः	तार्क्ष्यः	त्रिष्टुप्	८७४
१७९(१००५)	१०.१२.२८	८.८.३७	उत्तिष्ठताव	३	१ शिबिरौशीनरः; २ प्रतर्दनः काशिराजः; ३ वसुमना रौहिदश्वः	इन्द्रः	१ अनुष्टुप्; २; ३ त्रिष्टुप्	८७६
१८०(१००६)	१०.१२.२९	८.८.३८	प्र ससाहिषे	३	जय ऐन्द्रः	,,	त्रिष्टुप्	८७७
१८१(१००७)	१०.१२.३०	८.८.३९	प्रथश्च	३	१ प्रथो वासिष्ठः; २सप्रथो भारद्वाजः; ३ घर्मः सौर्यः	विश्वे देवाः	,,	८७८
१८२(१००८)	१०.१२.३१	८.८.४०	बृहस्पतिर्नयतु	३	तपुर्मूर्धा बार्हस्पत्यः	बृहस्पतिः	,,	८७९
१८३(१००९)	१०.१२.३२	८.८.४१	अपश्यं त्वा	३	प्रजावान् प्राजापत्यः	यजमानपत्नीहोत्राशिषः	,,	८८०
१८४(१०१०)	१०.१२.३३	८.८.४२	विष्णुर्योनिं	३	त्वष्टा गर्भकर्ता विष्णुर्वा प्राजापत्यः	लिङ्गोक्तदेवताः (गर्भार्थाशीः)	अनुष्टुप्	८८१

सूक्तम्	मण्डलानुवाक-सूक्तानि	अष्टकाध्याय-वर्गाः	सूक्तस्य प्रतीकम्	मन्त्र-संख्या	ऋषिः	देवता	छन्दः	चतुर्थभागे पृष्ठ-संख्या
१८५(१०११)	१०.१२.३४	८.८.४३	महि त्रीणाम्	३	सत्यधृतिर्वारुणिः	अदितिः (स्वस्त्ययनम्)	गायत्री	८८२
१८६(१०१२)	१०.१२.३५	८.८.४४	वात आ वातु	३	उलो वातायनः	वायुः	,,	८८२
१८७(१०१३)	१०.१२.३६	८.८.४५	प्राग्नये	५	वत्स आग्नेयः	अग्निः	,,	८८३
१८८(१०१४)	१०.१२.३७	८.८.४६	प्र नूनं	३	श्येन आग्नेयः	अग्निर्जातवेदाः	,,	८८४
१८९(१०१५)	१०.१२.३८	८.८.४७	आयं गौः	३	सार्पराज्ञी	सार्पराज्ञी सूर्यो वा	,,	८८४
१९०(१०१६)	१०.१२.३९	८.८.४८	ऋतं च सत्यं	३	अघमर्षणो माधुच्छन्दसः	भाववृत्तम्	अनुष्टुप्	८८६
१९१(१०१७)	१०.१२.४०	८.८.४९	संसमिद्युवसे	४	संवननः	१ अग्निः; २–४ संज्ञानम्	१; २; ४ अनुष्टुप्; ३ त्रिष्टुप्	८८७